[illegible]

([illegible])

पाणिनीयधातुपाठसमीक्षा

[illegible] विरचिता

3-2

सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः

सरस्वतीभवन-अध्ययनमाला

(१४)

पाणिनीयधातुपाठसमीक्षा

लेखकः सम्पादकश्च

डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'

व्याकरणाचार्यः, विद्यावारिधिः (पी-एच्० डी०)

सीनियर-रिसर्च-फेलो

वाराणस्याम्

१८८७ तमे शकाब्दे

प्राप्तिस्थानम्—
प्रकाशनविभागः
वाराणसेयसंस्कृतविश्वविद्यालयः
वाराणसी—२
मूल्यम्—१८.५०

SARASVATĪ BHAVANA STUDIES

Vol. XIV

GENERAL EDITOR
Surati Narayana Mani Tripathi
Vice-Chancellor
Varanaseya Sanskrit Vishvavidyalaya,
Varanasi.

PĀṆINĪYA-DHĀTUPĀṬHA-SAMĪKṢĀ

by

Dr. Bhāgīratha Prasāda Tripāṭhī
Vidyāvāridhi (Ph. D.)

VARANASI
1965

Published by :—
Director, Research Institute
Varanaseya Sanskrit Vishvavidyalaya
Varanasi

Printed by :—
Manager,
Sansar Press (Private) Ltd.,
Kashipura, Varanasi,

उपोद्घातः

इह ग्रन्थे क्षीरतरङ्गिणी-धातुप्रदीप-धातुवृत्ति-गतान् सर्वान् सपाठभेदधातूनधिकृत्य गवेषण-प्रवर्तना-वर्तते मदीया । शर्ववर्म-(त्रिविष्टपद्योतस्समुप[illegible]धातुपाठ-(अर्थविहीन-) चन्द्र-जैनेन्द्र-काशकृत्स्न-कातन्त्र-शाकटायन-हेमचन्द्र-वोपदेवानां धातुपाठधातवः समे प्रायशोऽस्मिन् ग्रन्थे सन्ति समाविष्टाः । प्रतिपृष्ठे कृतं विभागद्वयम् । प्रथमे विभागे तावत् खण्डद्वयम् । यत्र प्रथमे खण्डे व्याख्येया धातवो द्वितीये च सन्ति समायोजिता अर्थाः । द्वितीये विभागे व्याख्येयधातुभिः सह ध्वनितुलनायै पूर्वोक्तानां निखिलानां धातुपाठानां धातवो वेदनिघण्टुनिरुक्तपुराणपालिप्राकृता-दीनां च प्रासङ्गिकी सामग्री समुपन्यस्ता वर्तते । अस्मिन् भागे समुपन्यस्तानां धातूनां स्थापनया संस्कृतधातुविकासपरिचयः शक्येत विज्ञातुम् ।

यद्यपि पूर्वोक्तैकादशधातुपाठानां धातुसूची दशधातुपाठानां च्वार्थसूची श्रीबालकृष्ण-गजाननपल्सुलेमहोदयेन प्रस्तुताऽस्ति; तथापि तत्रार्था धातूनामनुसारेण नोपलभ्यन्ते । धातूनामस्ति पृथक् सूची, अर्थानाञ्च पृथक् । धातुं ज्ञात्वा कश्चन तदीयानखिलानर्थान् बोद्धुं न प्रभवति; कस्यापि धातोः समस्तानर्थानेकत्र प्राप्तुमपि नहि शक्नोति सारल्येन । सूच्येषा तु तेषामुपकारिका येषामेतन्निखिलधातुपाठगतधातूनामर्थाः कण्ठस्थाःस्युः, साधारणानां कृते नितरां नोपकारिका । उदाहरणतः प्रस्तूयते धातुद्वयम्—√वी धातुरस्त्येतेष्वर्थेषु—१–गतौ, २–व्याप्तौ, ३–प्रजने, ४–कान्तौ, ५–असने, ६–खादने च । √अव् धातुश्च—१–रक्षणे, २–गतौ, ३–कान्तौ, ४–प्रीतौ, ५–तृप्तौ, ६–अवगमे, ७–प्रवेशे, ८–श्रवणे, ९–स्वाम्यर्थे, १०–याचने, ११–क्रिया-याम्, १२–इच्छायाम्, १३–दीप्तौ, १४–अवाप्तौ, १५–आलिङ्गने, १६–हिंसायाम्, १७–आदाने, १८–भागे, १९–वृद्धौ च । सूच्यामेकैकोऽर्थोऽकारादिक्रमेण विन्यस्तोऽस्ति तत्र तत्र च तद्धातुरपीति जिज्ञासू रक्षणेऽर्थे धातुं दृष्ट्वा ज्ञास्यति–√अव् धातू रक्षणार्थक एवेति । कथं स धातोरनूनकानर्थाञ्छक्नुयाद् युगपज्ज्ञातुम् ? पाठकैर्धातुदेश एव अर्था लभ्येरन् न त्वर्थदेशे धातवः । एवंदशा सा सूची जिज्ञासूनामेव नैव पण्डितानामपि प्रहेलिका जाता । प्रस्तुते ग्रन्थे भवन्तः कस्मिन्नपि धातौ सर्वधातुपाठानामर्थानेकत्र समुपलप्स्यन्तेऽकारादिक्रमके ।

प्रथमविभागस्य प्रथमे खण्डे गणस्य धातुसंख्यायाश्चोल्लेखो विद्यते । मयेह ग्रन्थे क्षीरतरङ्गिणीपाठः प्रामुख्येन गृहीत इति यत्र यत्र धातौ कस्यापि नामोल्लेखो न स्यात् तत्र तत्र क्षीरतरङ्गिण्याः संख्यादि विज्ञानीयम् । यो धातुः क्षीरतरङ्गिण्यां नोपलब्धस्तत्र मया धातुप्रदीपस्य संख्या निर्दिष्टा । यत्र च धातुप्रदीपेऽपि यो धातुर्नावाप्तस्तत्र धातुवृत्तेः संख्यासमुल्लेखो व्यधायि । क्षीरतरङ्गिण्याः संस्करणद्वयमधिगतम्—डॉ० ब्रूनोलीबिशसम्पादितं मीमांसकयुधिष्ठिरसम्पादितं च । द्वितीयस्य संख्यायां भूयस्यव्यवस्थेति मया प्रथमसंस्करणगतसंख्या समुल्लिखिता । द्वितीये संस्करणे यत्र मनागपि भेदः परिलक्षितस्तत्र मया तत्संख्या सङ्केतिता । धातुवृत्तेर्महीसुर-वाराणसीप्रकाशितं संस्करणद्वयं समुपायोजि ।

प्रथमविभागस्य द्वितीये खण्डे परस्मैपदस्थाने (प) इति, आत्मनेपदस्थाने च (आ) इति प्रयुक्तं विराजते। अर्थनिर्देशनस्थले क्षीरस्वाम्यादिनाम्नामाद्याक्षराणि गृहीतानि। यथा—"क्षी मै-सा-श-च-जै-काकृ-कात-शा-हे-वो" इति। क्षीरतरङ्गिणी-धातुप्रदीप-धातुवृत्ति-चान्द्रव्याकरण-काशकृत्स्नशब्दकलापधातुपाठ-कातन्त्रधातुपाठ (हस्तलेख)-कविकल्पद्रुमा उपलब्धा इति तत्साहाय्येन विरचितेऽस्मिन् ग्रन्थे मया बालकृष्णगजाननपलसुलेमहाशयस्य सूच्यपि कार्त्स्न्येन समुपायोजि।

यद्यप्येकादशधातुपाठैः पाठशुद्धेः प्रकामं निर्णयसम्भवः, तथापि मया सरस्वतीभवन-पुस्तकालयस्थधातुपाठानां सप्तहस्तलेखैः समपादि पाठभेदसङ्गतिः। तेषां संख्यादिनिर्देशः सहायकग्रन्थानां सूच्यां वीक्षणीयः।

धातुपाठमवलम्ब्य लिखिताष्टीकाश्चिप्पण्यश्चैतावच्चिरं यावत् प्रायेण सन्ति कल्पनासम्भूताः। व्याकरणं वस्तुतः प्रयोगमाश्रित्य प्रवर्तते। प्रयोगशरणा वैयाकरणा इति व्याकरणग्रन्थेषु यत्र यत्र समाधिर्न सङ्गच्छते तत्र तत्र 'लक्ष्यानुसन्धानात्' 'अनभिधानात्' वेति प्रस्तूयते। यथा—'वचन्ति' इति रूपं व्याकरणशुद्धमपि नोल्लिख्यते, अनभिधानात्। इत एव कारणाल्लक्ष्यैकचक्षुष्को लक्षणैकचक्षुष्काज्ज्यायान् आश्रूयते। वैयाकरणैः केवलकल्पनाभिरिदं तथ्यं प्रायेण विस्मृतम्। तैर्लक्ष्याण्यननुसन्धाय सलक्षणानुसन्धानं कल्पनाः प्राबल्येन समाश्रीयन्त इति ते तथ्येभ्यः सुदूरं गताः सन्ति। वैयाकरणा ऐतिह्यतस्तु दवीयस्त्वं गच्छन्तो दृश्यन्ते। खातमिदं समीकर्तुं मया भूयः प्रयोगानाश्रित्य धातुसम्बन्धे विचारः प्रवर्तितोऽस्ति। एनमेव प्रयोगं शरणीकृत्य ह्विट्नीनवशतसंख्याकानेव धातूनङ्गीचकार। शेषांश्च धातूनप्रामाणिकान् उज्जुघोष, ते वैयाकरणैः परतो यथाबुद्धि सन्निवेशिताः स्युरिति। तेन संकुचितदृशा विचार्येयं धारणा समास्थितासीत्। वस्तुगत्या संस्कृतभाषाप्रयोगविषयो विष्टपेऽस्मिन् तत्सम-तद्भव-देशजेति येन केनापि रूपेण वर्तत एव। संस्कृतवाङ्मयानुपलम्भादेव कमपि धातुमप्रामाणिकमङ्गीकर्तुं न युज्यते। महाभाष्यकृता तथ्यमिदं सुसाधु प्रस्फोरितम्—*सर्वे देशान्तरे*अन्वेति।

भगवता पतञ्जलिना भाषाणां सुविचारितः स्वरूपपरिचयः प्रास्तावि। तेन समा भाषाः प्रयोग-विषयीकृता इति "सप्तद्वीपा वसुमती, त्रयो लोकाः"—कथनेन सुस्पष्टं भवति। साधुत्वासाधुत्व-(व्याकरण)-विचारस्तु तदा परतः समुद्भवेद् यदा हि सुज्ञानां दिङ्नैयत्यस्य प्रयोगनैयत्यस्य वा चिन्ता जायेत। साधुत्वासाधुत्वविचारे च व्याकरणं मूलम्। व्याकरणं तु परवर्ति। तद्यथा—"वाग्वै पराच्यव्याकृता अवदत्। ते देवा इन्द्रमब्रुवन्—इमां नो वाचं व्याकुरु इति" (तैत्तिरीये षष्ठकाण्डे)। अत्र वाण्या अव्याकृतत्वं सुज्ञेयम्। अत्र मान्यता तैः शिष्टप्रयोगमाधृत्य प्रत्यज्ञायि। शिष्टैर्ये प्रयोगाः स्वीकृतास्ते ते साधुत्वसंवलिता प्रख्यापिताः।

भगवता पतञ्जलिना देशान्तराणां केषाञ्चिन्नामानि प्रयोगभेदाश्च समुदाहृताः—"एतस्मिंश्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविषया दृश्यन्ते। तद्यथा—शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति, विकार एवैनमार्या भाषन्ते शव इति। हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमध्यमेषु, गमिमेव त्वार्याः प्रयुञ्जते। दातिर्लवनार्थे प्राच्येषु दात्रमुदीच्येषु (गिरिधरशर्म-संपा.सं. ५२ पृ.) द्रष्ट. निरु. २,२,८। अद्यत्वे √शव् धातोर्गत्यर्थकत्वं संस्कृतप्रयोगेषु नोपलभ्यते

सत्यपि धातौ √शव् (शव) १/ गतौ (प) इति पाणिन्युल्लिखिते, तर्हि धातोरस्य गत्यर्थकत्वमपलापयितुं शक्यते ? न शक्यते, कम्बोजेषु प्रयोगोपलम्भात् । उक्तभाष्यनिरुक्ताभ्यां सिद्ध्यति यदेकस्यैव धातोर्देशान्तरेषु भवन्ति भिन्नभिन्ना अर्था इत्यशेषास्ते न शक्यन्ते संग्रहीतुम् । महामुनिना पाणिनिना √शव्धातोरार्यानुमोदितं विकारार्थमनुपदिश्य कम्बोजप्रचलितं गत्यर्थकत्वमेव समुद्दिष्टम्, इत्येतेन व्यज्यते यत् तेन कुत्रापि प्रयुक्ता आख्यातरूपार्था प्राधान्यतो निरूपिताः । फलतो विद्वद्भिः समुपलब्धार्थपर्यन्ते नेयत्ता निश्चेया, देशभेदादर्थानामानन्त्यात् । इह ग्रन्थे धातौ धातौ देशान्तरप्रयुक्तधातूनामर्थानां च सङ्गत्यै यथागति प्रयतितम् ।

तथ्यानि सर्वाण्येतानि समनुध्याय मया ग्रन्थस्यास्य सज्जायै वक्ष्यमाणा सामग्री समुपयोजिता—(क) भारोपीयान्याख्यातानि नामानि वा । (ख) भारेनीयान्याख्यातानि नामानि वा । (ग) वेदेभ्यः प्रभृति नाटकादिग्रन्थान् यावत् प्रामाणिकाः प्रयोगाः । (घ) पालिसाहित्ये समुपलब्धाः प्रयोगाः । (ङ) प्राकृतसाहित्ये समासादिताः प्रयोगाः । (च) अपभ्रंशसाहित्ये समधिगताः प्रयोगाः । (छ) हिन्दीसाहित्ये भाषाशाखायां वोपलब्धाः प्रयोगाः । पुलिन्दखण्ड-(>बुन्देलखण्ड)-भाषाऽस्ति मदीया मातृभाषेति कोशेष्वनुपलभ्यमानस्तच्छब्दो मया तत्र तत्र लिखितः । तद्भाषामयः कोऽपि कोशो नाशक्यत प्राप्तुं मया । इयं भाषाशाखा खुरई (सागर-म० प्र०) स्थलस्य भाष्यमाणा प्रभाषेति । (ज) मुण्डारीभाषायां प्राप्ताः प्रयोगाः । (झ)—गणभाषा-(पिशाचभाषा)-[देशबाड़ी-प्राकृत]-साहित्ये लब्धा सामग्री । (ञ) कश्मीरभाषेति । लक्षणाधारेण प्रणीतस्य भट्टिकाव्यस्य प्रयोगाः पूर्वं मया संगृहीता अपि ते पश्चाद् बहिष्कृताः । महाभाष्यप्रयोगास्तु यथेप्सितमङ्गीकृताः ।

निर्वचनप्रामाण्याय—निरुक्तम्, नामलिङ्गानुशासनम् अमरकोशोद्घाटिनी-रामाश्रमी-सहितं च समाश्रिते । क्वचित् स्थलेभूणादिव्युत्पत्तिरपि प्रादर्शि । एकस्यैव शब्दस्यानेकेभ्यो धातुभ्यो व्युत्पादितत्वाद् व्युत्पत्तिः प्रायेण काल्पनिक्येव । उदाहरणत्वेन—अन्त्रशब्दः √अन्त् १/ धातौ, अभ्रशब्दः √अभ्र् १/ धातौ, अर्बुदशब्दः √अर्ब् १/ धातौ, अर्वन्शब्दः √अर्व् १/ धातौ, ऊर्दरशब्दः √उर्द् १/ धातौ प्रेक्षणीयः । एवमेवात्र ग्रन्थे सर्वत्र विचारितमस्ति ।

प्रयोगोपस्थापनतत्परतायां मया वैदिकपदानुक्रमकोश–(सम्पूर्णः, खण्डमेकमप्रकाशितं विहाय) सेण्टपीटर्सबर्ग(ब्योथलिङ्क–रॉथ)कोश–शब्दकल्पद्रुमप्रभृतयः समाश्रिताः (द्र० सहायकग्रन्थानां सूची) । वाल्मीकीयरामायण-महाभारत-महाभाष्य-निघण्टु-निरुक्त-मनुस्मृति-रघुवंश-नैषध-यशस्तिलकचम्पूप्रभृतीनामक्षरशः सटीकमनुष्ठितं मया पारायणमिति यत्र यत्र विहितष्टीकोल्लेखस्ते ते ग्रन्था मदधीता अवधेया, न तु कोशसंगृहीताः । सेण्टपीटर्सबर्गकोशे महाभारतस्य पर्वाणि श्लोकसंख्यया सह निर्दिष्टानि । अध्यायास्तत्र नोल्लिखिताः । संपत्स्यमाने संस्करणे मयाऽध्यायोल्लेखाय प्रयतिष्यते । तत्र वाल्मीकीयरामायणादिश्लोकसंख्याप्यद्यतनतत्संस्करणश्लोकादिसंख्यया न संवदति प्रायशः । तन्मार्ष्टुमपीहा ।

भारोपीयाः कोशाः सन्ति शामण्य-(जर्मन)-भाषामयाः । जूलियस्पॉकर्नीमहोदयस्य (यावत्प्रकाशित–), वाल्देपॉकर्नीमहोदयस्य च भारोपीयव्युत्पत्तिकोशावक्षरशो मया पर्यालो-

डितौ जर्मनभाषामयौ। संस्कृतवित्समाजस्य भवेद् बोधगम्या भारोपीयश्रृङ्खला, स्याच तद्विचाराणामिह दिशि प्रवर्तनेत्युद्दिश्य मया सत्यपि भूरिपरिश्रमसाध्ये कर्मणि तत् सर्वमपेक्षितं कर्तुं प्रायत्यत संस्कृतभाषामयम्।

एतैर्निःशेषैः प्रयासैर्मया धातवः प्रयोगशाणेन परीक्षिताः। ह्विट्नीर्यं धातुं नाङ्गीचकार तत्र धात्वादौ '+' एवञ्जातीयकं चिह्नमस्ति संयोजितम्। प्रकृतधातुर्ह्विट्नीव्याख्यातधातुभ्यो व्यतिरिक्त इति तत्सङ्केताकूतम्। ह्विट्न्यननुमोदिता धातव ईदृशा मया प्रायशः प्रयोगैः प्रमाणिताः। एतादृशानां सूची द्रष्टव्या।

धातूनामुदाहरणानि नहि मंस्यन्ते तिङ्प्रयोगा एव, अपि तु नामान्यपि तथा—"अथापि प्रकृतय एवैकेषु भाष्यन्ते विकृतय एकेषु"—निरु. २,२,८=धातोराख्यातपदभावेन यः प्रयोगः सा प्रकृतिः। नामीभूतस्य तस्यैव यः प्रयोगः सा विकृतिरिति दुर्गाचार्यः। ह्विट्नीमहाशयेनापि क्वचिन्नाम्नामेवोदाहरणं प्रास्तावि। दृश्यताम्—√कद् धातुः। अन्येषां परिवर्तमानानामंशानामपेक्षया मूले यस्य शब्दस्य स्थितिः प्रायशोऽपरिवर्तमाना परिलक्ष्येत स धातुत्वेन परिकल्प्यते। उदाहरणतः स्वर्णादिधातवो ग्राह्याः। कटककुण्डलादि यत् किमप्याभरणं निर्मीयेत हेम्ना, तदाकारे भिन्नतापि नाम सम्पद्येत, जातु तन्नामान्यपि भिन्नतामापद्येरन्, मूलतो द्रक्ष्यते काञ्चनमेव न त्वन्यत्। एवमेव शब्दशास्त्रेऽपि—भवति,-बभूव,-भविता,-भूयात्,-अभूत्-प्रभृतिषु 'भू' इति भव् इति च स्थैर्येण दृश्येते, यदा हि—अति,-अतः,-अन्ति,-व,-म,-इता, यात्,-त्—प्रभृतयः प्रत्ययाः परिवर्तमाना भवन्तीति विचार्य वैयाकरणैर्निरधारि—एतेषां समेषां मूले विद्यते 'भू' इति। एतदेवाधृत्य धातूनां तिङ्रूपानधिगतत्वेऽपि, सत्स्वेव नामसु, तत्र तत्र सन्ति कल्पिता धातव आचार्यैः। यथा—√शूल् १/५२६ रुजायाम्, √शच् १/१६३ व्यक्तायां वाचि, √शट् १/२९६ रुजाविशरणगत्यवसादनेषु, √शठ् १/३३७ कैतवे, √शण् १/७९१ प्रभृतयः।

पाणिनिप्रोक्तास्तदुपदिष्टा वा सन्ति कियन्तो धातवः, परतश्च सन्निवेशिताः कियन्त इति दुःशको निर्णयः। न चानधिगततिङ्रूपनिभानां धातूनां न पाणिनिप्रोक्तत्वमुपदिष्टत्वं वेति वाच्यम्, "शव् गतौ" धातोरपि तथात्वासम्भवात्, तदुल्लेखस्य निरुक्तमहाभाष्ययोः सत्त्वादित्यस्माभिः समेऽपि धातवः प्राप्तपाणिनिपरम्परा उररीकार्याः। एतावति द्राघीयसि काले पाणिनीयैः विद्वद्भिर्देशभेदानुसारेण धातुपाठे बहूनां पाठभेदानां सन्निवेशितत्वात् प्राप्तपाणिनिपरम्परत्वमस्य साधीयः। केचन पाठभेदा लिपिकानां भ्रान्त्या सञ्जाताः केचिच्चानवबोधेन (द्रष्ट. √कांसृ (कासि) १/६३७)। प्रयोगदृशा पाणिनीयधातुपाठो गणपाठतोऽपि गरीयान् वरीवर्तीत्यतो यावन्तः पाठभेदा इह सम्प्राप्यन्ते न तावन्तो व्याकरणस्य कस्मिंश्चिदपि ग्रन्थे। एतेनैवास्य प्रचुरप्रचारता शक्यते बोद्धुम्।

यत्र यादृशः पाठभेदः समासादितः, सङ्गतिं चेष्टमानेन मया तत्र '>' इति शरसङ्काशसङ्केतः समन्वस्थायि। शराणिदिशि पाठभेदोऽवगमनीयः। धातुपाठभेदमतिरिच्य विकासश्रृङ्खलायोजनेऽपीदमेव चिह्नं सुध्यानीयम्। उक्तपाठभेदे हेतुचतुष्टयमत्र सुस्पष्टं निर्वर्ण्यते—

१–लक्ष्यभेदः, २–देशभेदेनोच्चारणभेदाद् विकासः, ३–हस्तलेखानामस्पष्टतयाऽनवबोधेन च भ्रान्तिः, ४–संहितापाठः।

१–लक्ष्यग्रन्थेषु प्राप्तरूपाणामनुसारेण केचन वैयाकरणा निर्दिशन्ति धातून्। हेमचन्द्रः √पल्यूल धातुमुल्लिलेख; तन्मतेन √पल्यूल धातुर्नास्ति। पल्पूलयतेः प्रयोगः काठ. तै. शौ. पै. (संहितासु) लभ्यते। ग्रन्थानामेतेषामध्ययनात् तेन धातुरयं निर्दिश्येत। पूर्वं सर्वा वेदशाखाः सर्वैर्नाधीयन्ते स्म। तत्तच्छाखीयास्तत्तच्छाखा अभ्यस्यन्ति स्मेति तत्तत्क्षेत्रेषु तत्तद्ग्रन्थानामेव प्रचारः स्वाभाविकः। √पल्यूल धातुः तै.आ. १,३,५,२ इत्यत्र प्रयुक्तो लभ्यते। क्षीरगोपौ धातुमिममुल्लिलिखतुर्न तु √पल्पूलधातुमिति तज्ज्ञाताः काठ. १६,६; तै. २,५,५,६; शौ. १२,४,९; पै. १७,१६,९ इति ग्रन्था न स्युः। अन्यथा तौ पल्पूलधातुमवश्यमुल्लिखेताम्। इममेव लक्ष्यभेदं विचिन्त्य ओलडि १०/९ धातौ क्षीरस्वाम्याह—"इत्थं लक्षणमलक्षयताम् अन्धकुक्कुटीन्यायेन लक्ष्यमनुसरतां कियदिव रुष्यामः, कियदिव तुष्यामः" इति। √चर्च्, √छर्च्छ्, √जर्ज्, √झर्झ् १/ परिभाषणे (प) इत्यत्र चाह—"किमत्र सत्यं देवा ज्ञास्यन्ति" इति। √पुण् (पुण) १०/ संघाते (प) इत्यत्र च सायणः प्राह—"पुरुषकारे तु 'पूर्ण' इति स्वामी 'पुण' इति शाकटायन इत्युक्त्वा कोशसिद्धिस्त्वीदृशेऽर्थे कीदृशीति न विद्म इत्युपहसितम्"। अस्तु, √पल्पूल √पल्यूल इत्युभयोर्धात्वोः स्यात् संक्रान्तिः, लिपिदोषात् पकारस्य यकारत्वेन यकारस्य च पकारत्वेनापि बोधसम्भवात्।

(२) देशभेदेनोच्चारणभेदाद् वर्णेषु जातं परिवर्तनम्। एतादृशेषु स्थलेषु विद्यते तत्तद्वर्गवर्णसंक्रमणप्राभृती। √कख् (कखे) १/ हसने धातुः √कक्ख् इति जायमानः सन् √खक्ख् इति विकासमापन्नः। इदं सर्वं तत्र तत्रैव निभालनीयम्। प्रतिधात्वेतादृशा विचाराः सन्ति प्रवर्तिताः। द्रष्ट. युगि १/ >जुगि, वुगि १/ >भुगि, इति। वर्णविपर्ययेण √सिंह् १/३१६ h काकुधातुः √हिंस् ७/१९ इति जातः, विलोमक्रमेण वा। एवमेवार्थेऽपि √मस् (मसी) ४/ 'परिमाणे' इत्यस्य 'परिणामे' इति, √च्यु, √च्युस् १०/ इत्यत्र 'सहने' इत्यस्य च 'हसने' इति जातम्।

(३) इदानीन्तनीव सौविध्यी लिपिसम्बन्धिनी नासीत् प्राक्तने काले। अद्यतनमिव लिपिसङ्घटनात्मकमैक्यमपि सार्वदेशिकं नासीत् तदानीम्। एकस्य हस्तलेखस्यानेका भवन्ति स्म प्रतिलिपयः। लिपिकराश्च प्रायशो न भवन्ति स्म विद्वांस इति मक्षिकास्थाने मक्षिका अतिरिच्यान्यस्याक्षरस्यान्यत्वेन बोधो नैसर्गिकः। पूर्वतनस्य लिपिकरस्य त्रुटिभिः सह तस्य त्रुट्योऽपि सन्दब्धा भवन्ति स्म। अनेकेषां लिपिकानामनेका भ्रान्तय पाठभेदे कारणं जाताः। यथा–√मेव् (मेवृ) १/ सेचने (प)–मै-सा-काकृ-कात; सेवने—क्षी-च-जै-शा-हे। 'सेचने' इत्यत्र चकाराद्धस्तनपङ्क्तेर्घृष्टत्वान्मृष्टत्वाद् वा वकारभ्रान्तिः प्रकामं सिद्धा। वकारादधस्तनभागे मनाक्मस्या लग्नत्वाच्चकारभ्रान्तिरपि निश्चप्रचम्; एवमेव चकारपकारयोः—√व्यय् १०/९४ क्षये (प) इत्यस्य स्थाने √व्यप् इति पपाठ कौशिक इति क्षीरः।

(४) धातुपाठस्य संहितात्वेनोपदेशे "दश रामशराः" इत्यस्य "दशरा मशराः" इति वदनेकाः जायन्ते विप्रतिपत्तयः। संहितापाठे पूर्वधातोर्वर्णस्य परधातौ सन्निवेशभ्रान्तयः,

पूर्वधात्वर्थाक्षरस्य परधातौ योजनाभ्रमाश्च सन्त्यनेकत्र । यथा–"वृतु ४/ वरणे" इत्यत्र "तप ४/ ऐश्वर्ये वा" इत्यस्य 'वा' 'योजनेन' वावृतु-धातुः सम्पादितः । भट्टिकारेण क्वचिल्लक्ष्यमविचार्य लक्षणस्यानुसारेण "ततो वावृत्यमाना सा" ४,२८ इति रचयित्वा ततोऽप्यग्रे संशीतिरुपस्थापिता । √यु १०/ जुगुप्सायाम् इत्यत्र जुगुप्सायामित्यस्याद्याक्षरं "जु" इति प्रकृते धातौ योजयित्वा गुप्सायाम् इत्यस्य ध्वनिसादृश्येन कुत्सायाम् इति सम्पादितम् इति "युजु कुत्सायाम्" जातः स्वतन्त्रो धातुः । अत्र सन्ति सर्वत्र पाठभेदाः । सर्वे च वैयाकरणा नैकमत्यं भजन्ते । विस्तरशस्त्विह पुस्तके विलोकनीयम् । सपाठभेदं सौत्रं पाणिनीयधातूनां विद्यते संख्या—२३५६ इति । भ्वादेः प्रभृति क्र्यादिपर्यन्तं १७७४ धातवः, चुरादौ च ५८२ इति ।

अनुपतञ्जलि वैयाकरणैः कल्पनाः सुतमां समाश्रिताः, लक्ष्यं प्रति तद्दृक्पातो नास्तिनीकाशः । √तर्ज् (तर्ज) १०/१५१ संतर्जने (आ) इति धातुव्याख्याने क्षीरस्वामी लिलेख— "लक्ष्ये तर्जयतीति दृश्यते" इति । भट्टिकारोऽपि 'तर्जयन्तः' ७,३६ इति प्रयुञ्ज्येदमीयामेव प्रवृत्तिं पर्यचाययत् । यदा हि महाभारते 'तर्जयसे' इत्यस्य द्विःकृत्वो लभ्यते प्रयोगः—५,२४८५; १४,९१३ इत्यत्र । प्रयोगशोधन्या शक्यन्ते मार्ष्टुमिमाः सर्वा भ्रान्तयः । मयाऽत्रार्थे यथाप्राप्तप्रयोगेण प्रयतितम् । अनेकेषां संस्कृतग्रन्थानां विलोपान्न मदिष्टं सर्वतः पूर्तिमगात् । धातुपाठस्य प्रतताध्ययनार्थं प्रादेशिकभाषाकोशानां प्रस्तुतिर्निकाममपेक्षणीयेति विरमति

वा० सं० विश्वविद्यालये;
संवत् २०२२
रथयात्रायाम्

विदुषामनुचरः—
भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
ज्येष्ठानुसन्धानपण्डितगणाभ्यन्तरः
(सीनियर-रिसर्च-फेलो)

सङ्केतबोधकसूची संस्कृतादिग्रन्थानाम्

अ. = अथर्वशिखोपनिषद् ।
अ. को. = अमरकोशः ।
अ. कौ. सू. = अथर्ववेदीयकौशिकसूत्राणि ।
अक्षि. = अक्ष्युपनिषद् ।
अचि. = अभिधानचिन्तामणिः ।
अद्भुब्रा. = अद्भुतब्राह्मणम्
अनर्घरा. = अनर्घराघवम्
अना. = अमृतनादोपनिषद्
अन्न. = अन्नपूर्णोपनिषद्
अभि. = अभिज्ञानशाकुन्तलम्
अमरु. = अमरुशतकम्
अ. वे. = अथर्ववेदः (शौनकसंहिता)
अ. वे. प्रा. = अथर्ववेदप्रातिशाख्यम्
अव्य., अव्यक्तो. = अव्यक्तोपनिषद्
अशि. = अथर्वशिर उपनिषद्
१ आ., आत्मो. = आत्मोपनिषद्
आ. च., आ. चन्द्रिका = आख्यातचन्द्रिका
आनन्दलह. = आनन्दलहरीस्तोत्रम् ।
आबो. = आत्मबोधोपनिषद्
आर्यासप्तश. = आर्यासप्तशती
आर्षे., आर्षेयो. = आर्षेयोपनिषद्
आश्व. गृ., आश्व. गृह्य. = आश्वलायनगृह्यसूत्रम्
आश्रौ., आश्व. श्रौ. = आश्वलायनश्रौतसूत्रम्

इ., इतिहासो. = इतिहासोपनिषद्
उणा. = उणादिः
उत्तररा., उत्तररामच. = उत्तररामचरितम्
ऋ. = ऋग्वेदसंहिता ।
ऋ. प्राति. = ऋग्वेदप्रातिशाख्यम्
ऋ. सं. (निरुक्तादिटीकोद्धृत–) = ऋग्वेदसंहिता ।
ऐ., ऐतरेयो. = ऐतरेयोपनिषद्
ऐआ. = ऐतरेयारण्यकम्
ऐब्रा. = ऐतरेयब्राह्मणम्
क. = कपिष्ठल-(कठ)-कृष्ण-यजुर्वेद-संहिता
कठरुद्रो., करु. = कठरुद्रोपनिषद्
कठो. = कठोपनिषद्
कथासरि. = कथासरित्सागरः
का. = काण्वसंहिता (शुक्लयजुर्वेदीया)
काठ. = काठक-(चरक)-कृष्णयजुर्वेदसंहिता
कादम्ब. = = कादम्बरी
का. प्र., कव्यप्र. = काव्यप्रकाशः
काब्रा. = काण्वशाखीयं शतपथब्राह्मणम्
काशीख. = काशीखण्डम् (स्कन्दपुराणस्य)
काश्रौ., कात्याश्रौ. = कात्यायनश्रौतसूत्रम्
काला. = कालाग्निरुद्रोपनिषद्
किराता. = किरातार्जुनीयम्
कुण्डिको. = कुण्डिकोपनिषद्
कुमारसं. = कुमारसंभवम्

कृ.
कृष्णो. } =कृष्णोपनिषद्

केनो. =केनोपनिषद्

कौ. =कौथुमसामवेदसंहिता

कौलो. =कौलोपनिषद्

कौषीतकिब्राह्मणो. =कौषीतकिब्राह्मणोपनिषद्

कौषीतक्या. =कौषीतक्यारण्यकम्

क्रि. र. स. =क्रियारत्नसमुच्चयः

खि. =(ऋग्वेदीय)-खिलसूक्तानि

खिसा. =(ऋग्वेदीय–) खिलसूक्तानि (सातवलेकरसंस्करणम्)

ग.
गणपत्यु. } =गणपत्युपनिषद्

ग. पु. =गरुडपुराणम्

गरु.
गरुडो. } =गरुडोपनिषद्

गर्भ.
गर्भो. } =गर्भोपनिषद्

गी. =(श्रीमद्भगवद्–) गीता।

गी. गो.
गीतगो. } =गीतगोविन्दकाव्यम्।

गु.
गुह्यकाल्यु. } =गुह्यकाल्युपनिषद्

गोउ. =गोपालोत्तरतापिन्युपनिषद्

गोगृ.
गोभि. गृ. } =गोभिलगृह्यसूत्रम्

गोच. =गोपीचन्दनोपनिषद्

गोपू. =गोपालपूर्वतापिन्युपनिषद्

गोब्रा. =गोपथब्राह्मणम्

च. प. स्तो. =चर्पटपञ्जरीस्तोत्रम्

चरक. =चरकसंहिता

चिकि. =चिकित्सास्थानम् (सुश्रुतस्य)

छन्दोम. =छन्दोमञ्जरी

छाग.
छागलेयो. } =छागलेयोपनिषद्

छान्दो.
छान्दोग्यो. } =छान्दोग्योपनिषद्

जाबा. =जाबाल्युपनिषद्

जै. =जैमिनीयसामवेदसंहिता

जैउ. =(जैमिनीय-तलवकार-)उपनिषद्ब्राह्मणम्

जैब्रा. =जैमिनीयब्राह्मणम्

तांब्रा. =ताण्ड्यब्राह्मणम्

ति. =तिलकटीका (वाल्मीकीयरामायणे)

ते.
तेजोबिन्दू. } =तेजोबिन्दूपनिषद्

तै. =तैत्तिरीयकृष्णयजुर्वेदसंहिता

तैआ. =तैत्तिरीयारण्यकम्

तैउ. =तैत्तिरीयोपनिषद्

तैप्रा.
तैसं. प्रा. } =तैत्तिरीयसंहिताप्रातिशाख्यम्

तैब्रा. =तैत्तिरीयब्राह्मणम्

त्रिका. =त्रिकाण्डशेषः

त्रिता. =त्रिपुरातापिन्युपनिषद्

त्रि.
त्रिपुरोप. } =त्रिपुरोपनिषद्

दे. भा. =देवीभागवतम्

देव्यु. =देव्युपनिषद्

दैब्रा. =दैवतब्राह्मणम्

त्रिवि.
त्रिपाद्विभूतिमहानारायणो. } =त्रिपाद्विभूतिमहानारायणोपनिषद्

नाप.
नारदपरिव्राजको. } =नारदपरिव्राजकोपनिषद्

नाद.
नादबिन्दूप. } =नादबिन्दूपनिषद्

निरु. =निरुक्तम्

नि.
निघ. } =निघण्टुः

निर्वा. =निर्वाणोपनिषद्

नील. =नीलकण्ठीया टीका (महाभारते)

नृपू. } नृसिंहपूर्वतापिन्यु. } = नृसिंहपूर्वतापिन्युपनिषद्
नैष. = नैषधमहाकाव्यम्
पञ्चत. = पञ्चतन्त्रम्
पञ्च. ब्रा. } पञ्चविंब्रा. } = पञ्चविंशब्राह्मणम्
पा. अ. = पाणिनीयाऽष्टाध्यायी
पारमात्मिको. = पारमात्मिकोपनिषद्
पी. } पीताम्बरोप. } = पीताम्बरोपनिषद्
पिंब्र. = पिण्डब्रह्माण्डोपनिषद्
पै. = पैप्पलादाऽथर्ववेदसंहिता
प्रका. = प्रकाशटीका
प्रतापरुद्रीय. = प्रतापरुद्रीयम्
प्रश्नो. = प्रश्नोपनिषद्
प्रायश्चि. = प्रायश्चित्तेन्दुः
बटुको. = बटुकोपनिषद्
बा. } बाष्कलो. } = बाष्कलोपनिषद्
बि. } बिल्वो. } = बिल्वोपनिषद्
बृहत्सं. } बृ. सं. } = बृहत्संहिता
बृहदारण्यको. = बृहदारण्यकोपनिषद्
बृजा. } बृहज्जाबालो. } = बृहज्जाबालोपनिषद्
ब्रह्मवै. } ब्र.वै.पु. } = ब्रह्मवैवर्तपुराणम्
ब्रसू. = ब्रह्मसूत्रम्
ब्रह्मो. = ब्रह्मोपनिषद्
भ. } भस्मजाबालो. } = भस्मजाबालोपनिषद्
भव. } भवसंतारणो. } = भवसंतारणोपनिषद्
भा. } भावनो. } = भावनोपनिषद्

भा.पु. } भाग.पु. } = भागवतपुराणम्
मंब्रा. } मन्त्रब्रा. } = मन्त्रब्राह्मणम्
मण्डलब्राह्मणो. = मण्डलब्राह्मणोपनिषद्
मत्स्यपु. = मत्स्यपुराणम्
मनु. = मनुस्मृतिः
मन्त्रिको. = मन्त्रिकोपनिषद्
मन्वर्थ. = मन्वर्थमुक्तावली (मनुस्मृतिटीका)
मभार. = महाभारतम्
मभाष्य. = महाभाष्यम्
महा. } महो. } = महोपनिषद्
महावीरच. = महावीरचरितम्
महीध. = महीधरभाष्यम्
मा. = माध्यन्दिनसंहिता (शुक्लयजुर्वेदीया)
मा. पु. } मार्क.पु. } = मार्कण्डेयपुराणम्
मालतीमा. = मालतीमाधवम्
मित्र. = मित्रलाभः
मुक्तिको. = मुक्तिकोपनिषद्
मुण्डको. = मुण्डकोपनिषद्
मुद्राराक्ष. = मुद्राराक्षसम्
मृच्छ. } मृच्छकटि. } = मृच्छकटिकम्
मेघ.उ. = मेघदूतम् (उत्तर-)
मेदि. = मेदिनीकोशः
मै. = मैत्रायणी संहिता
मैत्रि. } मैत्र्यु. } = मैत्र्युपनिषद्
मैत्रे. } मैत्रेय्यु. } = मैत्रेय्युपनिषद्
(य.)वा.सं. = (यजुर्वेदीया) वाजसनेयसंहिता
यशस्ति.च. = यशस्तिलकचम्पूः

याज्ञ. / याज्ञवल्क्य. } =याज्ञवल्क्यस्मृतिः
योगकु. / योगकुण्डल्यु. } =योगकुण्डल्युपनिषद्
योचू. =योगचूडामण्युपनिषद्
योत. =योगतत्त्वोपनिषद्
योशि. =योगशिखोपनिषद्
रघु. =रघुवंशमहाकाव्यम्
राजत. =राजतरङ्गिणी
रापू. =रामपूर्वतापिन्युपनिषद्
रार. =रामरहस्योपनिषद्
रुजा. =रुद्रजाबालोपनिषद्
रुहृ. =रुद्रहृदयोपनिषद्
ललित. =ललितविस्तर–
लाट्या. / लाट्या.श्रौ. } =लाट्यायनश्रौतसूत्रम्
व. / वनदुर्गो. } =वनदुर्गोपनिषद्
वटु. / वटुको. } =वटुकोपनिषद्
वउ. / वरदोत्तरतापिन्यु. } =वरदोत्तरतापिन्युपनिषद्
वपू. / वरदपूर्वतापिन्यु. } =वरदपूर्वतापिन्युपनिषद्
वरा. / वराहो. } =वराहोपनिषद्
वा.रा. =वाल्मीकीयं रामायणम्
वा. सं. =वाजसनेयमाध्यन्दिनसंहिता ।
विक्रमाङ्कदेव. =विक्रमाङ्कदेवचरितम्
वै. प. को. =वैदिकपदानुक्रमकोषः
श. क. द्रु. =शब्दकल्पद्रुमकोशः
शत्रुञ्जयमा. =शत्रुञ्जयमाहात्म्यम्
शत.सु.सं. =शतकत्रयादिसुभाषितसंग्रहः

शब्रा. =शतपथब्राह्मणम्
शां / शाण्डिल्यो. } =शाण्डिल्योपनिषद्
शांआ. =शाङ्खायनारण्यकम्
शांब्रा. / शाङ्खा.ब्रा. } =शाङ्खायनब्राह्मणम्
शांगृ. =शाङ्खायनगृह्यसूत्रम्
शार्ङ्ग.सं. =शार्ङ्गधरसंहिता
शाकु. =शाकुन्तलम्
शाङ्खा.श्रौ. / शांश्रौ. } =शाङ्खायनश्रौतसूत्रम्
शि. =शिवोपनिषद्
शिशु. =शिशुपालवधम्
शौ. =शौनकीयाथर्ववेदसंहिता
श्वे. / श्वेताश्वतरो. } =श्वेताश्वतरोपनिषद्
श्री.व्या. =श्रीधरीया व्याख्या (गीतायाम्)
षब्रा. =षड्विंशब्राह्मणम्
संब्रा. =संहितोपनिषद्ब्राह्मणम्
संन्या. / संन्यासो. } =संन्यासोपनिषद्
ससा. / सर्वसारो. } =सर्वसारोपनिषद्
साब्रा. =सामविधानब्राह्मणम्
सा.भा. =सायणीयं भाष्यम्
सार. =सामरहस्योपनिषद्
सुबा. =सुबालोपनिषद्
सौ. =सौभाग्यलक्ष्म्युपनिषद्
स्क.पु. =स्कन्दपुराणम्
संजी. =संजीविनी (मल्लिनाथटीका)
हरिवंश. =हरिवंशपुराणम्
हं. / हंसो. } =हंसोपनिषद्

सङ्केतबोधकसूची पालिग्रन्थानाम्

अंगुत्तर. =अंगुत्तरनिकाय–
दीघ. =दीघनिकाय–
मज्झिम. =मज्झिमनिकाय–
विनय. =विनयपिटक–

प्रास्ताविकम्

"एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामधुग् भवति" इति श्रुतिः। अनया च भगवत्या श्रुत्या एकस्यापि शब्दस्य सम्यग् ज्ञानेन शोभनप्रयोगेण चैह-लौकिकी पारलौकिकी चेष्टप्राप्तिरभिधीयते। तत्रापि ज्ञानमन्तरा प्रयोगस्य कथमप्य-सम्भवाद् ज्ञानं पूर्वमेवापेक्ष्यते। तज्ज्ञानञ्च व्याकरणादेव भवति। अत एव "ब्राह्मणेन निष्कारणो षडङ्गो वेदोऽध्येयो ज्ञेयश्च। प्रधानञ्च षट्स्वङ्गेषु व्याकरणम्" इति महाभाष्ये उक्तम्। प्राधान्यञ्च व्याकरणस्य शब्दराशेर्वेदस्य स्वसंस्कारार्थं सर्वतः प्रथममपेक्षणीयत्वात्। "वाग् वै पराच्यव्याकृता आसीत्। ते वै देवा इन्द्रमब्रुवन्, इमां नो वाचं व्याकुरु" इति तैत्तिरीयात् सर्वतः प्रथममिन्द्रेण वाचो व्याकृतिर्विहिता। तदारभ्य बहुधा व्याकरणानि समजायन्त। लाघवम्, वैज्ञानिकत्वम्, सर्वतः परिपूर्णता, लौकिकवैदिकशब्दानामुभयेषां साधकता चेति दृष्टिकोणैर्विपश्चित्सु पाणिनिव्याकरणस्यैवात्यादर इदानीं यावत् परिदृश्यते। तत्र शब्दानां सारल्येनाव-गमाय प्रकृतिप्रत्ययादिकल्पना बहोः कालात् प्रचलितैव समाश्रिताऽस्मिन् व्याकरणे। अत एवाथर्वणे—"को धातुः? किं प्रातिपदिकम्? कश्च प्रत्ययः?" इत्युक्तम्। धातु-प्रातिपदिकभेदेन प्रकृतेर्द्वैविध्येऽपि प्रातिपदिकेष्वप्यनुगतो धातुरेव प्रकृतित्वेन मुख्यता-मर्हति। बहुत्र शब्देष्वनुगतः कश्चिद् वर्णसमुदायस्तत्संबद्धः कश्चिदर्थोऽप्यनुभूयमानः सर्वास्वपि भाषासु धातुपदेन व्यपदिश्यते। दधाति बहुषु स्थलेष्वनुगतानर्थानिति धातुः, धीयते वाऽनेकैः शब्दैरनुगतेऽर्थे इति कर्मणि प्रत्ययेन वा निष्पन्नो धातुशब्दः। एतद्विषये गवेषणायां प्रवृत्तेषु विद्वत्सु पाणिनिना धातुपाठरूपेण खिलपाठः कृतः। अन्यैश्च क्षीरतरङ्गिणी, धातुप्रदीपः, धातुवृत्त्यादयो ग्रन्थाः सङ्कलनात्मका विद्वद्भिः कृता वर्तन्ते। तत्रैषु वर्तमानानां बहूनां धातूनां कुत्रापि प्रयोगादर्शनाद् ह्विट्नीमहोदयेन नवशतसंख्याका एव धातवः स्वीकृताः।

तत्र महाभाष्ये बहूनां शब्दानां व्याकरणेन निष्पन्नानामद्य प्रयुक्तत्वमाशङ्क्य सन्ति शब्दाः प्रयुक्ता एवेति समाधायानुपलब्धिशङ्कायामुक्तम्—"उपलब्धौ यत्नः क्रियताम्। महान् शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्नाः, एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः, एकविंश-तिधा बाह्वृच्यम्, नवधाऽथर्वणो वेदः, वाकोवाक्यमितिहासः पुराणं वैद्यकमित्येता-वान् शब्दस्य प्रयोगविषयः। किञ्च, बहवः शब्दा देशान्तरे नियतविषयाः। शवतिर्गति-कर्मा कम्बोजेष्वेव, विकार एवैनमार्या भाषन्ते शव इति। हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमगधेषु, गमिमेव त्वार्याः प्रयुञ्जते। दातिर्लवनार्थे प्राच्येषु, दात्रमुदीच्येषु" इति। अस्यैव भाष्योक्तस्यार्थस्याधारमाश्रित्य संस्कृतग्रन्थेषु तत्तद्देशभेदभिन्नेषु भाषासु

प्राकृत-पाली-अवेस्ता—इत्यादिषु तेषां तेषां धातूनां प्रयोगप्रदर्शनेन 'विद्यावारिधिः' इत्याख्यायोपाधये साफल्यमाप्नुवता धातुपाठसमीक्षकेणानुसन्धात्रा स्वकीये निबन्धे स्पष्टीकृतः सर्वेषु धातुषु धातुपाठपठितेषु समादरः, निराकृतश्च ह्विट्नीमहोदयस्य सिद्धान्तः। परीक्षकाणां संवेदनेन विषयस्यावलोकनेन चास्य लेखकस्य परिश्रमो बंहिष्ठां प्रशंसामर्हति। प्रयासेनानेन च जिज्ञासूनां धातुविषयकज्ञाने महानुपकारः सम्भाव्यते। ग्रन्थेऽस्मिन् धातवो धातूनामर्थास्तत्समधातवस्तदर्थाः प्रयोगस्थलानि च तत्तत्साङ्केतिकशब्दैः प्रकाशितानि। ते च सङ्केताः सूच्याद्यवलोकनेन ज्ञाता भविष्यन्ति। निबन्धस्यास्यानुसन्धानात्मकस्य प्रकाशनमिदं बाहुल्येनोपयोगितां भजेदिति कामयमानः स्वकीयैराशीःसंतानैः संयुनक्ति।

केन्द्रीयविश्वविद्यालयानुदानायोगस्य आर्थिकेन साहाय्येनास्य ग्रन्थस्य मुद्रणं संजातमिति विश्वविद्यालयस्य पक्षेण तत्रत्येभ्योऽधिकारिभ्यः साधुवादान् वितरन् विरमति।

सुरतिनारायणमणित्रिपाठी
वाराणसेयसंस्कृतविश्वविद्यालयस्य
उपकुलपतिः।

प्रवृत्तिनिमित्तम्

श्रीनन्दनन्दनलीलाधाम्नि वृन्दावने १९५३ खीस्ताब्दे धातुपाठमनुशीलयता मया किमपि नवीनं समधिगतमिवानुभूतम्। विपश्चिद्भिः सह सम्भाषणप्रक्रमे जनेनानेनं धातुपाठधृताः प्रायशः समेऽपि धातवो व्यवहृताः। सम्भाषणमाकर्ण्य दोषज्ञाः "कोऽर्थः! कोऽर्थः!!" इति प्रण्यगदन्। बहुत्र तु "अप्रयुक्तताप्रयोगदोषः! अप्रयुक्तताप्रयोगदोषः!!" इत्येव समाकर्णि मया विद्वज्जनगणगीः। एवं सत्यपि नाहं मनागपि विचलितोऽभूवं निजपथात्। असकृन्मनसि समुदिता जिज्ञासा—यद्यस्त्यप्रयुक्तता तर्हि किमिति भगवता पाणिनिना संगृहीता धातव एते? "नूनं प्रयोगविषयाः सन्तीमे" इति दृढिष्ठा धारणा प्ररूढा चेतसि मदीये। १९५४ खीस्ताब्दे वाराणसीमुपेतो विद्वद्भिः समं सम्भाषमाणोऽहं बहुभिः प्रत्याख्यातः, अनेकैरुपहसितो भूरिभिश्च प्रतिघाभाजनतां नीतः। शब्दशास्त्रवित्प्रकाण्डा गुरुचरणा श्रीमद्रघुनाथशर्माणः समभ्यनन्दन् मामकीं वर्तनीम्, प्रोदसाहयंश्च द्वित्रॉंल्लोकप्रयोगान् निदर्शयन्त इति मन्मनोमयूरो भूयो नर्तितुं प्राक्रमत जलमुङ्नादमाकर्ण्येव। तदनु—"❀सर्वे देशान्तरे❀ सर्वे खल्वप्येते शब्दा देशान्तरेषु प्रयुज्यन्ते। न चैवोपलभ्यन्ते। उपलब्धौ यत्नः क्रियताम्। महान् शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती त्रयो लोकाः, चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रवर्त्मा सामवेदः, एकविंशतिधा बाह्वृच्यं नवधाथर्वणो वेदः, वाकोवाक्यमितिहासः पुराणं वैद्यकमित्येतावाञ्छब्दस्य प्रयोगविषयः। एतावन्तं शब्दस्य प्रयोगविषयमननुनिशम्य 'सन्त्यप्रयुक्ताः' इति वचनं केवलं साहसमात्रमेव" इति महाभाष्यमधीयानस्य मम चेतसि समजनि कोऽप्यपूर्वः प्रमोदः। मया १९५६ खीस्ताब्दतः १९५९ वत्सरं यावत् संस्कृतवाङ्मया हिन्दीवाङ्मयाश्च भूयिष्ठा ग्रन्थाः समधीता भाषाज्ञानवर्द्धनोपायाः। एतद्विषयका बहवो लेखा लिखिताः प्रकाशिताश्च। ततोऽपि मदिष्टं मम पुरस्तान्न मूर्तं जातम्। न च कामपि पद्यां दिङ्मूढोऽहमपारयन्निश्चेतुम्।

१९५९ खीस्ताब्दे वाराणसेयसंस्कृतविश्वविद्यालयमनुसन्धित्सया समुपेतेन मयाचार्यप्रवराणां श्रीमत्पण्डितक्षेत्रेशचन्द्राणां चट्टोपाध्यायानां सान्निध्यमुपालम्भि। तैर्विलियमड्वाइट्ह्विट्नीमहोदयस्य धातुपरिशिष्टं समुपस्थापितं यत्र ह्विट्नीर्नवशतसंख्याकानेव धातूनङ्गीचकार द्विसहस्रसंख्याकेषु धातुषु, इतरांश्च प्रक्षिप्तान् मेने। एतद्विषये मार्किनदेशस्य भाषाशास्त्रपत्रिकायाः पञ्चमे खण्डे चतुर्दशे च तेन ह्विट्नीमहाशयेन भूयो लिखितम्। तत्समा-

लोचनाप्रसङ्गेन "डब्ल्यू. जेड. के. एम्." इत्याख्यायाः पत्रिकाया अष्टमे खण्डे गेअर्ग बूइलर-महाशयेन यल्लिखितं तद्विषयेऽपि चट्टोपाध्यायमहाशयैर्मदीयमवधानं समाकृष्टम् । बूइलर-महाशयेन दर्शितं यद् ह्विट्नीद्वारा प्रत्यादिष्टा बहवो धातवः प्राकृतादिभाषासु प्रयुज्यमाना दृश्यन्ते । तदनु तस्यामेव पत्रिकायाम् ओतोफ्राङ्कमहाशयेनाप्येतद्विषये पालिभाषातः सामग्री-माहृत्य परिशिष्टरूपेण लिखितम् ।

श्रीमच्चट्टोपाध्यायानां निर्देशकत्वे (एप्रिल) १९६१ खीस्ताब्दात् १९६३ अक्तूबर-पर्यन्तं भारतशासनीयशिक्षामन्त्रणालयेन ३३०० मुद्रा धातुपाठसमीक्षाग्रन्थरचनार्थं मह्यं प्रदत्ताः (पारम्परिकसंस्कृतपाठशालानां परिणतियोजनायाम्) । श्रीमच्चट्टोपाध्यायैर्वाल्दे-पॉकर्नीरचितम्—**Alois Walde,** Vergleichendes Wörterbuch Indo-germnischen Sprachen : herausgegeben und bearbeitet Von Julius pokorny, 1930–1932 (3 Bde) इति कोशमन्यान् ग्रन्थान् दत्त्वा विषयं च निर्दिश्य यत् साहाय्यमाचरितं तदर्थं ते कोटिशो वन्दनीयाः । अत्र मया कियत् साफल्य-मासादितमितीह प्रेक्षकाः प्रमाणम् इति निवेदयते

वा० सं० विश्वविद्यालये;
संवत् २०२२
रथयात्रायाम्

विदुषां विधेयः—
भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
ज्येष्ठानुसन्धानपण्डितगणाभ्यन्तरः
(सीनियर-रिसर्च-फेलो)

संयुत्त. = संयुत्तनिकाय-

सद्दनी. = सद्दनीति-

सङ्केतबोधकसूची प्राकृतापभ्रंश-(भाषा)-ग्रन्थानाम्

अभि. = अभिज्ञानशाकुन्तल-
आचा. = आचाराङ्गसूत्र-
आवम. = आवश्यकसूत्र-(मलयगिरिटीका)
उप. = उपदेशपद-(हस्तलिखित-)
उपपृ. = उपदेशपद-(जैनविद्या-
प्रचारकवर्ग-, पालीताणा-)
उव. = उवएसमाला
उवा. = उवासगदसाओ
ओघ. = ओघनिर्युक्ति-
औप. = औपपातिकसूत्र-
कप्प. = कल्पसूत्र-
कप्पू. = कर्पूरमञ्जरी-
कस. = (बृहत्) कल्पसूत्र-
काल. = कालकाचार्यकथानक-
कुप्र. = कुमारपालप्रतिबोध-
कुमा. = कुमारपालचरित-
गउड. = गउडवहो
गा. = गाथासप्तशती
जी. = जीवविचार-
जीवस. = जीवसमासप्रकरण-
ठा. = ठाणङ्गसुत्त (स्थानाङ्गसूत्र-)
णाया. = णायाधम्मकहासुत्त-
णंदि. = णंदिसूत्र-
तंदु. = तंदुलवेयालियपयन्नो
ती. = तीर्थकल्प-
दस = दसवैकालिकसूत्र-
दसनि. = दसवैकालिकनिर्युक्ति-
दे. }
दे. ना. } = देशीनाममाला

देवे. = देवेन्द्रस्तवप्रकीर्णक-
धर्मवि. = धर्मविधिप्रकरण-(सटीक-)
धर्मसं. = धर्मसंग्रहणी
धर्मा. = धर्माभ्युदय-
* नाट. = नाटकीयप्राकृतशब्दसूची ।
* नाट-सा. = साहित्यदर्पण-
निचू. = निशीथचूर्णि-
निर. = निरयावलीसूत्र-
पंच. = पंचसंग्रह-
पंचा. = पंचासकप्रकरण-
पउम. = { पउमचरिअ / पउमचरिय }
पडि. = पंचप्रतिक्रमणसूत्र-
पण्ण. = पण्णवणासुत्त-
पण्ह. = प्रश्नव्याकरणसूत्र-
पव. = प्रवचनसारोद्धार-
पाअ. = पाइअलच्छीनाममाला
पा. स. म. = पाइअसद्दमहण्णवो
पिंग. = प्राकृतपिंगल-
पिंड. = पिंडनिर्युक्ति-
पिंडभा. = पिंडनिर्युक्तिभाष्य
पि. = ग्रामातिक देर प्राकृत स्प्राखन्
प्रयौ. = प्रतिज्ञायौगन्धरायण-
प्राप्र. = प्राकृतप्रकाश-
प्रामा. = प्राकृतमार्गोपदेशिका
प्रासू. = प्राकृतसूक्तरत्नमाला
भग. = भगवतीसूत्र-
भत्त. = भत्तपरिण्णापयन्नो
भवि. = भविस(य)त्तकहा

---

* द्र. 'पाइअसद्दमहण्णवो' इति प्राकृतशब्दकोशः ।

महा. = आउस् गेव्याल्ते एरस्यालुंगन् इन् महाराष्ट्री
मै. = मैथिलीकल्याण–
मोह. = मोहराजपराजय–
रंभा. = रंभामंजरी
रत्ना. = रत्नावली (नाटिका)
रयण. = रयणसेहरनिवकहा
राज. = अभिधानराजेन्द्र–
वव. = व्यवहारसूत्र–(सभाष्य–)
वाग्भ. = वाग्भटकाव्यानुशासन–
विक्र. = विक्रमोर्वशीय–
विपा. = विपाकश्रुत–
विसे. = विशेषावश्यकभाष्य–
वेणी. = वेणीसंहार–
वै. = वैराग्यशतक–
श्रा. = श्राद्धप्रतिक्रमणसूत्रवृत्ति–
सं. } संबो. } = संबोधसत्तरी
संक्षि. = संक्षिप्तसार–
संबोध. = संबोधप्रकरण–
संवेग. = संवेगमंजरी
स. = समराइच्चकहा
सट्ठि. = सट्ठिसयपयरण–
सण. = सनत्कुमारचरित–
सम. = समवायांगसूत्र–
सम्म. = सम्मतिसूत्र–
सम्मत्त. = सम्यक्त्वसप्तति–
सम्य. = सम्यक्त्वस्वरूपपच्चीसी–
सम्यक्त्वो. = सम्यक्त्वोत्पादविधिकुलक–
सिरि. = सिरिसिरिवालकहा–
सुख. = सुखबोधा टीका (उत्तराध्ययनस्य)
सुज्ज. = सूर्यप्रज्ञप्ति–
सुपा. = सुपासनाहचरिअ–
सुर. = सुरसुंदरीचरिअ–
सूअ. = सूअगडांगसुत्त–
सूअनि. = सूत्रकृताङ्गनिर्युक्ति–
से. = सेतुबंध–
हित. = हितोपदेशसारकुलक–
हेका. = हेमचन्द्रकाव्यानुशासन–

हिन्दीग्रन्थः

अ. अ. } अभि. अनु. } = अभिधान अनुशीलन

आंग्ल-शार्मण्यादि ग्रन्थानां सङ्केत-बोधकसूची

डब्ल्यू. जेड्. के. ऐम्. = विएना ओरिऐण्टल जर्नल्
अमे. ओ. सो. जर्नल = अमेरिकन् ओरिऐण्टल सोसाइटी जर्नल्।
जेड्. डी. डी. ऐम्. जी. = Zeitschrift der Deutschen Morgenländischen Gesellschaft
पी. टी. ऐस्. पालि–डिक्श. = पाली टेक्स्ट् सोसाइटी पालि डिक्शनरी
पि. = ग्रामातिक् देर् प्राकृत स्प्राखन्
पीटर्सब. = (सैंट) पीटर्सबर्ग (संस्कृत) व्योर्थर् बुख्—व्योथलिङ्क ऑत्तो : रॉथ रुडॉल्फ्।
महा = आउस् गेव्याल्ते–एरस्यालुंगन् इन महाराष्ट्री
मा. विलि. = मानियर् विलियम् : (संस्कृत-इँग्लिश्–डिक्शनरी)
B K A = Barret, (L. C.: The) Kashmirian Atharvaveda (with critical notes)

G R V = Geldner, (K. F.: der) Ṛgveda (i-iv übersetzt und erläutert)

G W. = Grassmann, (H.): Wörterbuch (zum Ṛgveda)

M V G = Macdonnell, (A. A: Vedic) Grammar

O R N = Oldenburg (H.): Vedic (Hymns, trans.)

W A G = Wackernagel, (J): Altindische Grammatik

सामान्यसङ्केताः

अक = अकर्मक—
अड्या. = अड्यारसंस्करणे (अप्रकाशितोपनिषद्)
आ.
आश्वा. } = आश्वासः
(आ) = आत्मनेपदम्
आन: = आनन्दाश्रमसंस्करण—
कवकृ. = कर्मणि वर्तमानकृदन्तः
कात = कातन्त्र (व्याकरणम्)
काकृ = काशकृत्स्न—
कृ. = कृत्यप्रत्ययान्तः
क्रि. = क्रियापदम्
क्षी = क्षीरस्वामी
क्षी. = क्षीरतरङ्गिणी
गी.प्रे.सं. = गीताप्रेसगोरखपुरीयसंस्करणम्
च = चन्द्रः (चान्द्रव्याकरणम्)
चौ.सं. = चौखम्बासंस्करणम्
जू. = जूलियस् (पॉकर्नीः)
जै = जैनेन्द्रव्याकरणम्
टी. = टीका
तु.
तुल. } = तुलनीय—(तुलना कार्या)
देश. = देशजः
तौदा. = तौदादिक—
द्र.
द्रष्ट. } = द्रष्टव्य—
धा. = धातुः
नाप. = नाम (परक) पद—
नाधा.
नामधा. } = नामधातुः ।
निसा. = निर्णयसागरसंस्करण—

(प) = परस्मैपदम्
पाठा. = पाठान्तरम्—
पाभे. = पाठभेदः
पुरुष. = पुरुषकारः
पृ. = पृष्ठम्
प्रपु. = प्रथमपुरुषः
प्रभृ. = प्रभृति—
प्रयो. = प्रयोजक—(प्रेरणार्थकणिजन्तः)
प्रे. = प्रेरणा (प्रेरक—)
ब्योथ. = ब्योथलिङ्क-(पीटर्सबर्गसंस्कृतकोशः)
भकृ. = भविष्यत्कृदन्तः
भवि. = भविष्यत्कालः
भाप. = भावपरकपद—
भूका. = भूतकालः
भूकृ. = भूतकृदन्तः
मपु. = मध्यमपुरुषः
मुपा. = मुद्रितपाठ—(प्राग्र—)
मै. = मैत्रेयः
यक्र. = यथाक्रम—
यु.मी.सं. = युधिष्ठिरमीमांसकसंस्करण—
लाल. = लालकविः([हि.] छत्रप्रकाशस्य रचयिता)
वकृ. = वर्तमानकृदन्तः
वा = वाल्दे (पॉकर्नीः)
वि.ब.शा. = विश्वबन्धुशास्त्री
वें = वेङ्कटात्मज-माधव-भाष्य—(ऋ.)
वैतु. = वैपरीत्येन तुलनीय—
वै.प.को.
वैदि.प.को. } = वैदिकपदानुक्रमकोषः
वो = वोपदेवः
श = शर्ववर्मा
शा = शाकटायनः

संकृ. = संबन्धकक्कृदन्तः
सा = सायणः
सू. = सूत्रम्
स्क. = स्कन्दस्वामिकृतभाष्य–.
ह.ले. = हस्तलेख–
हे = हेमचन्द्रः
हेकृ = हेत्वर्थकृदन्तः
हि. = हिट्नीः (विलियम् ड्वाइट्)

* एतच्चिह्नयुतस्य शब्दस्य प्रयोगो हिन्द्याः पद्य एव ज्ञेयः । भारोपीयभाषायाम् एतच्चिह्न-युतः शब्दः काल्पनिकोऽवधेयः ।

† एतच्चिह्नयुतः शब्दः प्रादेशिको निश्चेयः

‡ एतच्चिह्नाङ्कितः शब्दः ग्राम्यो निर्धारणीयः ।

—इदं चिह्नम् 'इति' इत्यर्थकम् ।

˘ अक्षराधोभागे लग्नमिदं चिह्नं तालव्यस्थान-बोधकम् ।

ˎ इदं चिह्नम् अर्द्धस्यैकारस्य बोधकम् ।

ॱ इदं चिह्नं ७ इत्यस्य बोधकम्

सङ्केतबोधकसूची भाषाणाम्

अप. = अपभ्रंश–
अफ़गा. = अफगान्–
अर्मे. = अर्मेनियन्–
अलेम. = अलेमनिक्–
अल्बे. = अल्बेनियन्–
अवे. = अवेस्ता–
आइस्. = आइस्लैण्डिक्–
आस्से. = आस्सेतन्–
इँग्लि. = इँग्लिश् –
इता. = इतालियन्–
इरा. = इरानियन्–
इरि. = आइरिश्–
एँग्लो-सैक्सॉ. = एँग्लो-सैक्सॉन् –
किम्रि. = किम्रिक्–
गॉथि. = गॉथिक् (Gothic)
गाथि -अवे. = गाथिक-अवेस्ता–
गुर्जरभा. = गुर्जरभाषा
च. स्ला. = चर्च-स्लावोनिक्–
डिंग. = डिंगल–
न. उ. ज. = नवीनोच्चजर्मन्–
न. पर्सि. = नवीनपर्सियन्–
न. ब्रेटॉ. = नवीनब्रेटॉनिक्–
नार्वे. = नार्वे (नार्वेजियन्–)
पु. आइस्. = पुरातन–आइस्लैण्डिक्–
पु. ऑस्क. (ao.) = पुरातन-आस्कन–
पु. इरि. = पुरातन-आइरिश्–
पु. उ. ज. = पुरातनोच्चजर्मन्–
पु. च. स्ला. = पुरातनचर्चस्लावोनिक्–
पु. नार्दि. = पुरातननार्दिक्–
पु. प्र. = पुरातनप्रशियन्
पु. बुल्गा. = पुरातनबुल्गारियन् –
पु. ब्रेटॉ. = पुरातन ब्रेटॉनिक् –
पु. म. उ. ज. = पुरातनमध्योच्चजर्मन्–
पु. रसन् = पुरातनरसन्
पुरा. हि. = पुरातनहिन्दी–
पु. लिथु. = पुरातनलिथुआनियन्–
पु. सैक्सॉ = पुरातनसैक्सॉन्–
बंगा. = बंगला–
बुं ख. = बुंदेलखण्डीय–
बुल्गा. = बुल्गारियन्–
बोहे. = बोहेमियन्–
ब्रेटॉ. = ब्रेटॉनिक्–
म. इँग्लि. (mengl.) = मध्य-इँग्लिश्–
म. इरि. = मध्य-आइरिश्
म. किम्रि. = मध्यकिम्रिक्–
म. ज. = मध्यजर्मन्–
म. नीदै. = मध्यनीदैर्लैण्डिक्–
मरा. = महाराष्ट्रिय–
मैथि. = मैथिल–
लिथु. = लिथुआनियन्–
लेट्टि. = लेट्टिश्–
लैति. = लैतिन्–
शौ. = शौरसेनी
सं. = संस्कृत–
सर्बि. = सर्बियन्–
सैर्बो-क्रोटि. = सैर्बो-क्रोटियन्–
स्वीडि. = स्वीडिश्–
स्ला., स्लावो. } = स्लावोनिक्–

विषयसूची

पाणिनीयधातुपाठसमीक्षा

रघुनाथं शिवं नत्वा क्षेत्रेशं च गुरुद्वयम् ।
धातुपाठसमीक्षेयं तन्यते लक्ष्यसाधना ॥

√अंह् (अहि) १/६२८ मत्तौ (आत्मनेपद)
श ×
क्षी-मै-सा-च-जै-
कात-शा-हे ।
वक्रगतौ—काकृ ।
मत्ते—वोपदेव

√अङ्ग् (अगि) १/१४५ गत्यर्थः (प) परस्मैपद
√अङ्घ् (अघि) १/१०५ गत्याक्षेपे (आत्मनेपद)
√अघ् १/४१३ मत्साक्षेपे (आ) काकृ ।
√अंह् १/३१९ कलुषे (प) काकृ ।
√अह् १/३१६ हिंसामत्सौ (प) काकृ ।
√अंह् (अहि) १०/ भासार्थः (प)

क—अंघु (अथवा एंघु) = संकीर्णम्, कारावासे, बन्धने । * अंघोस्—, अंघुस् = क्रूरता । लैति.—अंगार् = बन्धने, व्यग्रता, मनःशरीरवेदना, दुःखम् । अंगुस्—तुस् = संकीर्णम्, कारावासे, बन्धने । पु. फ्रि. अंगॉस्त्, (पु. उ. जे) अंगुस्त, म. उ. ज. अंग्स्त्, (पु. च. स्ला) अंजॉस्त् = कारा, बन्धनम् । लिथु. अंक्स्तस् = संकीर्णम्, कारावासे—वा. पॉकर्नीः ।

ख—अवे. अंजह् = अपेक्षा, आपत्, बन्धनम्, कारावासः ।

ग—अंहस् क ४, २, ९ । अंहतिः—ऋ ८, ६४, ९ । अह्नि काठ १, १२ ।

+√अक् (अक) १/७८६ कुटिलायां गतौ (प)
श ×
क्षी-मै-सा-च-जै-काकृ-कात-
शा-दे ।
वक्रगतौ—वोपदेव

√अच् (अचु) १/८४७ गतौ (प) इत्येके—क्षीरस्वामी
√अख् १/३८ गतौ (प)
काकृ

√अग् (अग) १/७८७
कुटिलायां गतौ (प)।
√अंक् (अकि) १/८४
लक्षणे (आ)।

× √अङ्क् १/८४ उत्तरधातोर्व्याख्यानमवलोकनीयम्।

√अक्ष् (अक्षू) १/६४५ व्याप्तौ संघाते च क्षी-मै-सा-जै-काकृ-कात-शा-हे। व्याप्तौ—च। व्याप्तिसंहत्योः—वो।
श ×

√अश् (अशू) ५/१८ व्याप्तौ (आ) क्षी-मै। व्याप्तौ संघाते च—सा-हे।
√अक्ष् ५/ व्याप्तिसंहत्योः (प) श-वो।
√अक्ष् १/५१५ खेलने (आ)।
आष्ट (निघ. २/१८) = व्याप्तिकर्मा।
√अह् (अह) ५/२६ व्याप्तौ (आ)।

क—अग् = प्रेरणे, उन्नतौ; शुद्धौ। अग् स्,—अक् स् = स्कन्धः, आधारः। लैति.—अक्सिस् = तनुदण्डः, पक्ष्ममध्यवर्तिनी नाडी। लिथु.—असिस्। लेट्टिश्—अस्स्। पु. च. स्ला.—ऑस। पु. उ. ज.—अहृस, न. उ. ज.—अछ्से = अक्षः—वा. पॉकर्नीः।

ग—(१) अक्ष्णुते, अक्ष्णुयात्—मै ४,२,९। (२) अक्षतु—पै १०,२,३। ब्रह्मलोकं समक्षसे—वा० रा० २, ५२, ८६।

√अक्ष्>√अश्>√अह् इति क्रमिको विकासो लक्ष्यते। भ्वादि-स्वादुभयत्रत्योऽयं धातुः सौविध्यार्थं भ्वादावेव पठितः पाणिनिना विकरणतश्नुतया चोपदिष्टः (पा. ३/१/७५)।

+√अग् (अग) १/७८७ कुटिलायां गतौ (प) क्षी-मै-सा-च-जै-कात-शा। अकवत् (=कुटिलायां गतौ) हे। वक्रगतौ—वो।
श ×

√अज् (अज) १/ गति-क्षेपणयोः (प)।
√अज् १/६०४ कुटिलायां गतौ (प) काकृ।
√अक् (अक) १/ कुटिलायां गतौ (प)।

(काक्ष — √अज्)	कुटिलायां गतौ—काक्ष।	√अग् १/४१० आदाने (आ) काक्ष।
संभवतो लैपिकी स्खलतिः।		अग्रम् — निरु. ६,३,१।

क—अग्रो—अथवा—ऑग्रो = निशितः कण्टकः, (उच्चम्, प्रथमम्) अग्रम्—वा. पॉकर्नी।

ख—अवे. अग्र = उच्चम्, परिधिः, स्थानम्।

ग—अग्निनाग्निः समिध्यते—ऋ. १, १२, ६। प्रत्यग्रं शृणीहि—ऋ ३, ३०, १७।

छ—अगग्ना ❀ = अग्रे गमनम्, अग्रे भवनम्।

छ—अगुआना (अग्रु—नि. १/१३–नदीनामधेयम्। २/५—अङ्गुलि-नामधेयम्) = अग्रेकरणम्।

+√अङ्क् (अकि) १/८४ लक्षणे (आ)		√अञ्च् (अचि) १/८४७ गतौ (उ)।
श ×	क्षी-मै-सा-च-जै-काक्ष-कात-शा।	√अञ्च् (अञ्चु) १/१८५ गतिपूजनयोः (प)।
	लक्षणे गतौ च—हे।	√अञ्च् (अञ्चु) १०/२११ विशेषणे (प)।
	लक्ष्मणि, गत्यां च—वो।	√अङ्ग् (अगि) १/१४५ गत्यर्थः (प)।
		√अङ्ग (अङ्ग) १०/३७३ लक्षणयोः (प)।
		√अङ्घ (अङ्घ) १०/३७२ पदलक्षणयोः (प) इत्येके —क्षी।
		√अङ्क (अङ्क) १०/३७३ पदलक्षणयोः (प) इत्यन्ये —क्षी।
(लक्षणम् =	चिह्नम् — क्षी)	

क—अंक्—न्युब्जीभावे, कौटिल्ये।

ख—अवे.—अक = वडिशम्, ग्रहणम्, विपत्, शङ्कुः, पिधानम्। अंक्सनेह् = कविका, शासनम्, संयम—वा. पॉकर्नी।

ग—अङ्का—ऋ १, १६२, १३।

छ—√अँकना ❀

छ—√ आँकना = (१) अङ्कनम्, (२) मापनम्, (३) अनुमितिकरणम्, निर्णयनम्।

अङ्गेति क्षिप्रनाम। अञ्चितमेवाङ्कितं भवति (निरु ५/१७) इत्यत्र धातुः √ अञ्च् १/८४७ गतौ, √ अङ्ग् १/१४५ गत्यर्थः, (√ अङ्क १०/३७३ पदलक्षणयोः) प्रभृतिधातुभिः संबध्नाति। जी. बुइलरमतेऽपि (डब्ल्यू. जेड्. के. एम्. — वियेना-शोधपत्रिकायाः अष्टमे बन्धे १८९४ ई., १७–४२ पृ.) जलमर एड्ग्रेन-महाशयस्य मतेऽपि च (अमे. ओ. सो. ज. एकादशे बन्धे, १–५४ पृ.) निरनुनासिका धातवः खलु सम्भवे सानुनासिका भवन्ति। व्याकरणदृशापि "अकाराः" निरनुनासिक-सानुनासिकभेदैः अष्टादशविधाः सम्पद्यन्ते — इति √ अच् धातुः √ अञ्च्, √ अक् धातुश्च √ अङ्क् इति भेदं प्रपद्येते। एवमेव सर्वत्रावगमनीयम्। शास्त्री विश्वबन्धुश्च वैदिकपदानुक्रमकोशे (संहिताभागे) अङ्कशब्दस्य टिप्पण्यां लिखति — "कौटिल्यार्थेन √ अक् इत्यनेनापि नुमागमनिपातनतो यथाकथमपि सम्बन्धः साध्यतामर्थानुसन्धानतः"। आवेस्ता "अक" शब्दोऽप्यङ्कशब्दस्य पूर्वावस्थां लक्षयतीति।

+√ अङ्ग (अगि) १/१४५ गत्यर्थः। √ अञ्च् (अचि) १/५४७ गतौ (उ)।

श ×	क्षी-सै-सा-च-कात। गतौ — जै-शा-हे। पत्याम् — वोपदेव	
		पूर्वधातुः। समग्रः ध्वनिर्बोधनीयः।
काश्-√ रिङ्ग् (रिगि) परन्तु टीकास्वमे	गतौ — काश।	अङ्क्यन् (= वर्णानालोडयन् शनैः शनैः) — शत्रा- १, ७, २, १७। पर्यङ्क्याते — ऋ. १०, १६, ७।
अङ्गति, इति तिष्ठति।		

क—अंक् = न्युब्जीभावे, कौटिल्ये; अंग् —। पु. उ. ज. एंक = ग्रीवापृष्ठदेशः, जङ्घा। पु. उ. ज. अंगो, अंगुल = कण्टकः। पु. आइस्. अंगि, एँग्लो-सै. ओंग् = अग्रम्, कण्टकः — वा. पॉकर्नीः।

ख—अवे. अंगुस्त = अङ्गुष्ठः — वा. पॉकर्नीः।

ग—पल्यङ्क्यन्ते — शत्रा० ३, ९, २, १६ अनवस्थाने। पल्यङ्क्यमाने ७, ३, ३, १२। (सा तेऽङ्गे त्वङ्गतु — नलोदये १/२३)। पल्यङ्क्य — १, ७, १, १८। काला. श्रौ. ८, २, १।

घ—अंग — जातक ५, १९, ७।

छ—ऑग * † = अङ्कम्।

छ—अँगवना ❀ = (१) अङ्गीकरणम्, (२) आच्छादनम्, (३) सहनम्।

+√अङ्घ् (अघि) १/१०५ श ×	गत्याक्षेपे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गर्तौ निन्दारम्भजर्वेषु—वो।	√अंहू (अहि) (१/६२८) गतौ (आ)। वक्रगताम्-काकृ। √अघ् १/४१३ गत्याक्षेपे (आ) काकृ।

गत्याक्षेपः = वेगगतिर्गमनारम्भो वा—क्षी।

क—द्रष्ट. √अंहू १/६२८।

ग—अङ्घ्रिः—मा २, ८।

अयम्, √अंहू १/६२८ (आ) धातुश्च मिथः संक्रान्तौ। अघशब्दोऽस्मात् उत्पद्यते—पचाद्यच् ३/१/१३४। आगमशास्त्रस्यानित्यत्वान्न नुम्। इह √अघ् १/४१३ गत्याक्षेपे (आ) काकृ-धातुस्तुलनीयः।

√अच् (अचु) १/८४७ श-च-जै-काकृ-कात-वो ×	गतौ (उ) इत्येके-क्षी क्षी-सा-हे। गतौ याचने च—मै।	<√अञ्च् (अचि) गतौ (उ)। √अज् (अज) १/२२६ गतिक्षेपणयोः (प)। √अच्छ् १/३५५ गतौ (प) काकृ। √अक् (अक) १/७८६ कुटिलायां गतौ (प)।

क—अंकू = न्युब्जीभावे, कौटिल्यम्—वा. पॉकर्नीः।

ग—पर्यचामि हृदा मतिम्—ऋ १०, ११९, ५। अङ्गुलीः—न्यचति—शब्रा. ३, १, ३, २५। अप··अच—ऋ ९, ९७, ५४ ; कौ २, ४५६; जै ३, ३४, १४।

√अज् (अज) १/२२६ श ×	गतिक्षेपणयोः (प) क्षी-मै-सा-जै। गतौ – च। गतौ क्षेपणे च – काकृ-कात-शा-हे। क्षेपे गते – वो।	√अच् (अचु) १/८४७ गतौ (प) इत्येके-क्षी। √अञ्च् (अञ्चु) १/१८५ गतिपूजनयोः (प)। √अञ्ज् (अन्जू) ७/२१ व्यक्तिम्रक्षणगतिषु (प)। √अग् (अग) १/७८७ कुटिलायां गतौ (प)। √अक् (अक) १/७८६ कुटिलायां गतौ (प)।

क—अग् = प्रेरणे। अगोः।
ख—अवे. अजैति = प्रेरणे—जू. पॉकर्नीः।
ग—अजन्ति-ऋ ९, ९१, १।

√अञ्च् (अञ्चु) १/१८५ गतिपूजनयोः (प) — √अच् (अचु) १/८४७ गतौ (प) इत्येके-क्षी।

श — क्षी-मै-सा-जै-काकृ-कात। — √अञ्च् (अचि) १/८४७ गतौ (उ)।

गत्यर्थे—च। — √अङ्क् (अकि) १/८४ लक्षणे (आ) लक्षणे।

गतौ पूजायां च—शा-हे। — गतौ च—हे।

पूजो गतौ च—वो। — √अङ्ग् (अगि) १/१४५ गत्यर्थः (प)।

क-अंक्, अंग्=न्युब्जीभावे कौटिल्ये-वा. पॉकर्नीः।
ग-आञ्चतु-शौ ११, १२, १६। आके - ऋ २, १, १०; अञ्चिताभ्याम्···गताभ्याम्—रघु. २, १८।

ङ-अंच (सक.) = गमने। अंचति (पंचा १६, २३)।
„ („) = पूजने। अंचए (भवि)।
० यंच („) = गमने पूजने च (ठा ५, १—पत्र ३००)।
ज-आचुर = गमने।

√अञ्च् (अचि) १/८४७ गतौ (उ) — √अञ्च् (अन्चु) १/८६५ गतौ याचने च (उ) मै।

पूजे—वो। — √अच् (अचु) १/८६५ गतौ याचने च (उ) इत्येके—मै।

मै-श-च-जे-क्षी-सा-हे-काकृ-कात-शा × — √अञ्च् (अन्चु) १/१८५ गतिपूजनयोः (प)।

इदित् पाठः पूजायां नलोपाभावात्—दुर्गादा.।
~~उदाहरणानि पूर्वधातोरचयन्त्यानि~~।

√अञ्च् (अन्चु) १/८६५ गतौ याचने च (उ) मै — √अच् (अचु) गतौ याचने च (उ) इत्येके—मै।

क्षी-श-जै-शा × — मै-सा।
गतौ—च-काकृ-कात।

गतौ अव्यक्तशब्दे—हे।

गतौ क्लिष्टोक्तौ च—वो। शेषः पूर्ववत्।

क्लिष्टोक्तिः = अव्यक्तशब्दः—दुर्गादासः।

पूर्ववदुदाहरणानि ज्ञेयानि।

छ—इँचना * / ऐंचना } (<अञ्चनम्) = आकर्षणे, गमने, प्रापणे, आकुञ्चने च।

उँचना (<उदञ्चनम्) = अधोवयनस्य दृढीकरणे कर्षणे च।

√अञ्ज् (अन्जू) ७/२१ व्यक्तिम्रक्षणगतिषु (प) | √अच् (अचु) १/८४७ गतौ (प) इत्येके—क्षी।

श व्यक्तिम्रक्षणकान्तिगतिषु | √अञ्च् (अन्चु) १/१८५ गतिपूजनयोः (प)।

मै-सा-काकृ-कात-हे। | √अज् (अज) १/२२६ गतिक्षेपणयोः (प)।

व्यक्तौ—च। | √अग् (अग) १/७८७ कुटिलायां गतौ (प)।

गतिव्यक्तिम्रक्षणेषु—जै-शा। | √अक् (अक) १/७८६ कुटिलायां गतौ (प)।

व्यक्तिगतिम्रक्षणे—वो। | √अञ्ज् (अजि १०/२२८ भासार्थः (प)।

क—आंगु = अभ्यङ्गे, अभिषेके। लैति. उंक्तुस्; उम्तु। पु. प्र. अंक्तन्, अंक्ते = म्रक्षणम् (नवनीतम्)। पु. उ. ज. अंखो; जर्मन, अंके = म्रक्षणम् (नवनीतम्)- वा. पॉकर्नीः।

ग—अनक्ति-ऋ १, १५३, २।

घ—अञ्जति (अञ्जेति)-संयुत्त २, २८१; जातक ४, २१९।

ङ—अंज (सक.) = म्रक्षणे (समवायांगसूत्र)।

छ—{ आँजना = म्रक्षणे कान्तौ। / ओंगना = म्रक्षणे (शकटाक्षस्य)।

√अट् (अट) १/२९२ गतौ (प) | √अत् (अत) १/३७ सातत्यगमने (प)।

श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। | √अठ् (अठ) १/२३२ गतौ (प)।

गमने—वो।

ग—अटसि—सार. २३० : ११। अटति सर्वशः—मभार. १, १०३१। पम्पामटति—वा. रा. ३, ७५, ६८।

ङ—अड (सक.) = भ्रमणे । अडंति संसारे (पण्ह १,१) (णाया १,१४) ।

छ— { अँटना (<√ अट् गतौ) = लये, (२) पूरणे, (३) चलने, (४) क्षपणे ।
अटना (<√ अट् गतौ) = भ्रमणे, (२) याने ।

ज—आड़ा = निर्मोचने ।

+√ अट्ट् (अत्ट) १/२५२ अतिक्रमहिंसयोः (आ) √ अट्ट १०/२७ मञ्जिकायाम्
१/२५२ श-च-जै- क्षी-सा । अतिक्रमणहिंसयोः- (प) काकृ । √ अन्त्
काकृ-शा × मै । हिंसातिक्रमयोः-हे । १/४३० क्रमहिंसयोः (आ)
अतिक्रमे वधे—वो । काकृ ।
[कात-√ अट्ट् अतिक्रमहिंसयोः—कात । √ अट्ट् (अट्ट)
(अट्ट)] । १०/२५ अनादरे (प)
इति च दुर्गः-क्षी । √ अट्ट्
(अट्ट) १/१०१ हिंसातिक्रमयोः (आ) जै ।
√ अट्ट् (अट्ट) १/६३
हिंसातिक्रमयोः (आ) शा ।
√ अट्ट् (अट्ट)अतिक्रमे
वधे (आ) वो ।

ग—साट्टप्राकारतोरणाम्—वा. रा. ५, ३, ३३ ।

अस्य धातोस्तिङ्रूपाणि नोपलभ्यन्ते । इदमीया व्युत्पत्तिस्तु √ अत् १/३७ > √ अन्त् १/४३०-काकृ । > √ अण्ट् १/२५८-सा । > √ अट्ट् इति बोधनीया । अतिशायने रोषे वधे हर्षे च प्रसक्तस्य वर्णस्य द्वित्वप्रवृत्तिर्नैसर्गिकी-इति √ अत् १/३७ > √ अट् १/२९२ > √ अट्ट् । यथा √ पट् > पट्टः, पट्टिशः, √ कुट् > √ कुट्ट् > कुट्टिमः, √ हट् > हट्टः, √ भट् > भट्टः, √ घट् > √ घट्ट् > घट्टः, √ चट् > चट्टः, √ खट् > √ खट्ट इति भूयिष्ठाः शब्दा धातवश्च ज्ञानीयाः ।

टे १. मेदिनीकोशेऽट्टशब्दस्यार्थाः—१. शुष्कम्, २. भक्तम् = अन्नम्, आटा (हिन्दी) । ३. क्षौमम्, ४. अत्यर्थम्, यथा—अट्टहासः । ५. गृहान्तरम्, यथा—साट्टप्राकारतोरणाम्—वा० रा० ५, ३, ३३ ।

+√ अड्ड् (अद्ट) १/२५२ अतिक्रमहिंसयोः (अ) <√ अट्ट् (अत्ट) अति-
श-जै-काकृ-कात-शा × अन्ये तु—क्षी । क्षी-सा । क्रमहिंसयोः (आ) ।
अतिक्रमणहिंसयोः—मै । √ अन्द् १/४३० a. क्रम-
अतिक्रमे—च । हिंसयोः (आ) काकृ ।
हिंसातिक्रमयोः—हे ।
अतिक्रमे वधे—वो ।

व्याख्यानं पूर्वधातुतो बोधनीयम्।

+√अठ् (अंठ) १/३३२ गतौ (प) √अत् (अ) १/३७ सातत्यगमने (प)।
मै-सा-श-च-काक्ट-कात× क्षी-जै-शा-हे। √अट् (अट) १/२९२ गतौ (प)।
गते—वो √अण्ठ् (अठि) १/२५८ गतौ (आ)।
√अण्ड् (अडि) १/४३५ गतौ (आ)।

√अत्>√अट्>√अठ् इति क्वचिद् देशविशेषे व्यवहृतः स्यात्। अस्यासार्वत्रिकत्वादेव मैत्रेयसायणादिभिः नैनमनुमोदयामासुः। मन्ये, एतत्प्रयोगविषयः पश्चिमोत्तरसीमा स्यात् भारतस्य, जैनेन्द्रहेमचन्द्रनिवासभूभागो वा।

+√अड् (अड) १/३५३ उद्यमे (प) √अल् (अल) १/५१६ भूषण-पर्याप्तिवारणेषु (प)।
श× क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे-वो। अल्ल् १/२२७ बन्धने पालने त्र (प) काक्ट।
√अड् ५/२६ व्याप्तौ (प) हे। व्यापे—वो।
√अठ् (अठ) १/३३२ गतौ (प)।

ग—अडः=वृश्चिकलाङ्गूलम् (धा. वृ., ८२ पृ.)। वृश्चिकलाङ्गूलमुद्यतं तिष्ठतीत्यडः। व्याडः>व्यालोऽपि तथा। √अड् √अल् इत्येतयोर्निकामं मिथः संक्रान्तिः। आडिर्नाम पक्षिविशेषः। वसिष्ठो विश्वामित्रं शशाप—वको भव। विश्वामित्रोऽप्याचुक्रोश वसिष्ठम्—आडिर्भवेति। यथा मार्कण्डेयपुराणे—"त्वमप्याडिर्भवस्वेति प्रतिशापमयच्छत्" (९/१०)।

छ—आड़त=उद्यम, आड़तिया=उद्यमशील।
ज—अड़ांग्=लक्ष्यसाधने।

+√अड्ड् (अड्ड) १/३४५ अभियोगे (प) √अट्ट् (अट्ट) १/२५२ अतिक्रमहिंसयोः (आ)।
श क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे-वो।
समन्ताद्योगे—गोविन्दभट्टः। (ब्योथ-रॉथ)
समाधाने—दुर्गादासः। (ब्योथ-रॉथ)।

छ—अड़ना=हठे।

अड़ाना = आश्चर्ये, अवरोधने। अड़ान (< √अड्ड् = समाधाने) = विश्राम-
स्थलम्।

? अड्डा।

ज—आडाओ = अनाज्ञाकारितायाम्।

+√अण् (अण) १/४३७	शब्दार्थः (प)	√अल् (अल) १/५१६ भूषणपर्याप्तिवारणेषु (प)। √अड् (अड) १/३५३ उद्यमे (प)।
श ×	क्षी-मै-सा-च	
	शब्दे—जै-काक-कात-शा-हे। रवे—वो।	√अण् (अण) ४/६७ प्राणने (आ) सा।

क—अल् = चूर्णने, अणुत्वे—वा. पॉकर्नीः।
ङ—अण (सक) = शब्दे, (२) गमने, (३) ज्ञाने। अणइ (विसे ३४४१)।

प्राकृते प्रयुक्तोऽयं लभ्यते धातुरिति प्रत्युक्तो ह्विटनीः

+√अण् (अण) ४/६७	प्राणने (आ) सा.	√अन् (अन) ४/७० प्राणने (आ) मै।
क्षी-मै-श-च-जै-काक-कात-शा ×	सा-हे। प्राणे—वो।	√अन् (अन) २/५९च = प्राणने (प)।

√अन् (अन) २/५९ प्राणने (प) धातोरयं देशविशेषे प्रयुक्तो दैवादिकेन भेदः साहित्ये नाभिमन्यते अतो वैयाकरणा अपि पाठे ऐकमत्यं भजन्ते। √अन् २/५९ इत्यनेन प्रोपसर्गयोगे कर्मणि—"प्राण्यते" इति रूपात् प्रोपसर्गस्थविच्छित्तौ "अण्यते" इत्यस्य [illegible] धातुत्वस्वीकारः।

+√अण्ठ् (अठि) १/२८	गतौ (आ)	√अत् (अत) १/३७ सातत्यगमने (प)।
(सा) √अण्ट् (अटि)	क्षी-मै-(सा)-च-जै-कात-शा-हे।	अठ् (अठ) १/२३२ गतौ (प)।
श ×	गते—वो।	अड् ५/२६ व्याप्तौ (प) हे। व्यापे-वो।
[काक-√अण्ड् (अडि)]	गतौ—काक।	√अण्ड् १/१७० आवरणे (प) काक।

ग—दाहपाकरुगण्ठिते गुल्मे—सुश्रुत. २,४५५,११।

छ—ऐंठना=वेष्टने (गतौ), (२) पीडायाम्।

+√अत् (अत) १/३७ सातत्यगमने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। अतति (निघण्टौ २/१४) गतिकर्मा √अट् (अट) १/२९२ गतौ (प)।

श×

क—अत्=गमने—जू. पॉकर्नीः। लैति. अन्तुस्—वा. पॉकर्नीः।

ग—समतसि कपोत इव गर्भधिम्—ऋ. १,३०,४। अतन्नहेव सूर्यः—ऋ. ६,६,९।

ज—आतु=उड्डयने, (२) भ्रमणे, (३) प्रवाहे।

√अद् (अद) २/१ भक्षणे (प) क्षी-मै-सा-च-काकृ-कात-शा-हे। भक्षे—वो। √खद् (खद) १/५० भक्षणे (प) सा। √जक्ष् (जक्ष) २/६० भक्षहसनयोः (प)।

श

क—एद्=भक्षणे। लैति. (एदो) एस्=अदने। स्ला.-*एद्मि। जस्ति=भक्षणे। गॉथि. इतन्, एतन्, एज्जन्=अदने। अर्मे. उतेम्=चुल्लिः—वा. पॉकर्नीः।

ग—अत्ति—ऋ. १,१६४,२०। भागवते भौवादिकोऽपि—"साकमन्नमदामहे"—३, २०, ५१।

घ—अदेमि—जातक ५,३१।

ज—{ आदू=हानौ। आदेर=प्रवेशे।

√अन् (अन) २/५९ च=प्राणने (पा) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। √अन् (अन) ४/७० प्राणने (प) मै। √अन्त्र् १०/५ जीवने (प) काकृ। √अनिति (निघण्टौ २/१४) गतिकर्मा। √अन्त् (अति) १/५९ बन्धने (प)।

श

क—अन=प्राणने, श्वसने—जू. पॉकर्नीः।

ग—(अनिति)-अनन्-शब्रा. २,५,३,३; अन्यात्-तैआ. ८,७,१। अपानिति-काठ २९,६।

√अन् (अन) ४/७० क्षी-श-च ×	प्राणने (आ) मै। मै-सा-जै-काकृ-कात-शा-हे-वो।	√अन् (अन) २/५९ प्राणने (प)। √अण् (अण) ४/६७ प्राणने (प) सा।

क्षीरचन्द्राभ्यामपठितोऽयम् असार्वत्रिकत्वं व्यनक्ति। अपोपसर्गविशिष्टस्य "अपान्यते" इति कर्मणि प्रयोगस्योत्तरांशग्रहणप्रचारोऽप्येनं पुष्णाति।

+√अन्त् (अति) १/५९ श-जै-शा ×	बन्धने (प) क्षी-मै-सा-च-काकृ-कात—हे। बन्धे—वो।	√अन्द् (अदि) १/६० बन्धने (प)। √इन्त् (इति) १/६० (प) अन्ये-क्षी। √अम् (अम) १/४५९ गत्यादिषु (प)।

ग—अन्तकः-वा. रा. ३,३,१४ (गी. प्रे. गो. सं.)।

√अन्द् धातोश्चर्त्वादयं धातुः। अत एव सायणः-"अत्र धनपालः-तान्तं द्रविडाः पठन्ति। आर्यास्तु दान्तमिति। उभयमिति मैत्रेयस्वामिकाश्यपसम्मताकारादयः"-१/६१। √अन्त्√अन्द्,√इन्द्,√बिन्द्√गण्ड्-पञ्चैते न तिङ्विषयाः-इति काश्यपः। अविगीतमन्ये सर्वेषां तिङमुदाहरन्ति-सा. १/६१।

√अन्द् (अदि) धातोस्तिङ्प्रयोगविषयत्वात् (हिन्द्याम्) (प्रेक्षणीय उत्तरधातुः)√अन्त् धातोश्चातथाभूतत्वान्नूनमेष परवर्ती। अतो हेतोः पुरुषकारः स्वामिनो मतमुल्लिलेख-"अतेः पाठोऽनार्षः। अन्ये 'अदि इति बन्धने' इति पेठुः" (पुरुष० ७५ पृ०)। नायं पाठः क्षीरतरङ्गिण्यां लभ्यते।

[अन्तः (अन्तनम्-घञ् ३/३/१८। "अन्तः स्वल्पे निकटे प्रान्ते निश्चय-नाशयोः। अवयवेऽपि" इति हेमः। अन्तकः=यमः (अन्तं करोति-अन्तयति। "तत्करोति (वा० ३/१/२६) इति ण्यन्ताद् ण्वुल्)। एवमेव—अन्तरम्, अन्तरा, अन्तरायः, अन्तरालम्, अन्तर्, अन्तरिक्षः, अन्तिकम्, प्रभृति-शब्दाः सम्बध्नन्त्यनेन। अन्त्रम्=पुरीतत् (आंत-हिन्दी)-शब्दोऽप्यस्माद् व्युत्पद्यते। यथा-उणा० ४/१५९ ष्ट्रन्। काशकृत्स्नस्तु√अन्त्र १०/५ जीवने धातुं पृथक् पठति। दशोणादौ√अम् १/१५९ धातुतो व्युत्पत्तिः (४/१५८) ष्ट्रन्; उणादावपि ४/१२३। अन्त-शब्दोऽपि √अम् धातुतो व्युत्पद्यते-(उणा. ३/८६) इति तन्। इत्थम्√अन्त् धातुः सर्वथा निरस्तो भवति]

+√अन्द् (अदि) १/६० बन्धने (प)
श ×
क्षी-मै-शा-च-जै-काकृ-
कात-शा-हे ।
बन्धे-वो ।

√अन्ध (अन्ध) १०/३७०
दृष्ट्युपसंहारे (प) ।

घ–अन्दु = शृङ्खला–विनय १,१०८ ।

छ–अँदाना (<सं.√अन्द् बन्धने) = वारणे । रक्षणे ।

–आँदू = लौहशृङ्खला । अँदुआ (<अन्दुकः) = गजपश्वपादबन्धनाय कण्टकितं काष्ठयन्त्रम् ।

ज–अन्दूड़ (पन्दूड़) = उन्मत्तप्रलापे । उन्मत्तदोलने ।

+√अभ्र् (अभ्र) १/५५५ गत्यर्थः (प)
क्षी-मै-सा-च ।
गतौ—जै-काकृ-कात-
शा-हे ।
गत्याम्–वो ।

√अर्ब् (अर्ब) १/४११
गतौ (प) ।
अप्+√रा = अभ्र >
√अभ्र् ।

क—(एनेभ्) : नेभ्-, एम्भ्, मृभ्, एम्ब् (आम्ब्) = अभ्रम् । किम्रिक-अम्ब्यूर्, अमिर्, अम्यू् = यथाशीघ्रम्; अम्पेर् तथा एम्मेर् ।

ख—अवे. अब्र=अभ्रम्—वा. पाकर्नीः ।

ग—[अभ्रम्-"अभ्रं व्योमपुष्करमम्बरम्" (अ० को० १/२/१) । अत्र भानुजिदीक्षितश्चतुर्विधां व्युत्पत्तिं दर्शयति—१. न बिभर्ति किञ्चित् । मूलविभुजादित्वात् (वा० ३/२/५) कः । २. आपो भ्रश्यन्त्यस्मात् । अन्येभ्योऽपि (वा० ३/२/१०१) । अत्र पक्षे-अब्भ्र इति स्यात् (मुकुटः) । ३. अभ्रति = स्थैर्यं गच्छति । अच् (३/१/१३४) । ४. (स्वामिमते) न भ्राजते । √भ्राज् (भ्राजृ) दीप्तौ । अन्येभ्योऽपि (वा० ३/२/१०१) इति डः । "अभ्रं मेघो वारिवाहः" (अ. को. १/३/७) इत्यत्र अपो बिभर्ति । (३/२/५) इति कः । अत्र स्वामी—"अभ्रति, अपो राति वा—अभ्रम् । न भ्रश्यन्त्यापोऽस्माद् इत्येके, यदुक्तम्—न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः (पुराणम्)" ।

अभ्राद् वृष्टिः—शब्रा. (Apte's Practical Sanskrit English Dictionary); शिशु. ९,३ ।

√अम् (अम) १/४५९ गत्यादिषु (प)
श
क्षी-मै-सा ।

√अण्ड् (अण्ड) १/१७०
आवरणे (प) काकृ ।
√अम्म् १/२२५ गतौ (प)
काकृ ।

आदिपदेन–शब्दे संभक्तौ
(भक्तौ–क्षी) च ।
गतिभक्तिशब्देषु–जै-शा ।
गतौ–काकृ-कात ।
गतौ भजने शब्दे–वो ।

न कम्यमिचमाम्–८०३
श-जै-शा-हे-वो ×

क–ऑमो–, आम=तीव्रगतौ, पुनःपूरणे । दारुणवेदनायाम्, हानौ, बाधायाम् ।

ख–अवे.–अम=शक्तौ–वा. पॉकर्नीः ।

ग–अभ्यमीषि–ऋ. १,६४,९; आमयति–ऋ. १०,९७,९ ।

ङ–अम (सक)=१–गमने, २–शब्दे, ३–अभ्यवहारे, ४–पीडने, ५–(अक) रोगितायाम् । अमइ (विसे ३३५३) ।

+ √अम्ब (अबि) १/३७५ शब्दे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।

अम् (अम) १/४५९ गत्यादिषु (प) आदिपदेन–शब्दे संभक्तौ (भक्तौ–क्षी) च ।
√अम्भ् (अभि) १/३८२ शब्दे (आ) इति दुर्गः–क्षी ।
√रम्भ् (रभि) १/ शब्दे (आ) इति दुर्गः–क्षी ।

क—(एनेभ्–) : नेभ्–, एम्भ्–, मृभ् । एम्ब् (आम्ह्)=अभ्रम् । अर्मे. अम्प्=पाने–वा. पॉकर्नीः ।

ग—पञ्चस्रोतोऽम्बुम्—श्वेता. उ. १,५; सुश्रु. २,४९३ । अम्बु (निघण्टौ १/१२) । अम्बा स्यालं भवतीति–निरुक्ते ९/१० । अम्ब–वा. सं. ६,३६ ।

यद्यपि नोपलभ्यते धातोरस्य क्रियापदम्, तथाप्येषोऽपलपितुं न शक्यते । अनार्यभाषाप्रभावोऽपि नात्र वक्तुमुचितः, वेदातिरिक्तानां भूरीणां शब्दानामार्यभाषात एव विकसितत्वात् । √अम् १/४५९ धातुरस्ति प्रयुक्त ऋग्वेदे । शब्दार्थकोऽप्येष धातुः–√अम् √अम्ब् इति सुज्ञेयं विकासमाप । ये हि "म्ब"युताञ्छब्दान् अनार्यभाषाप्रभवान् भणन्ति ते निकामं प्रत्यादिष्टाः । स्वरा रेफोत्तरा अपि जायन्ते, यथा–√अण् शब्दार्थः √रण् शब्दार्थः । √इ २ / गतौ < √रि ६ / गतौ । √इङ्ख् (इखि) १ । गत्यर्थः > √रिङ्ख् (रिखि) गत्यर्थः । अत एवोक्तं काव्यमीमांसायाम्—

ललल्कारया जिह्वां जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभव्यधियो न तु ॥ ७ ।

अयं श्लोको रेफप्रयोगाधिक्यं निर्दिशति । √अम्> √अम्ब्>√रम्ब् १/३७३ । अन्त्यवर्णस्य महाप्राणतया √अम्ब्>√अम्भ् १/३८२ इति, √रम्ब्>√रम्भ् १/३८२ इति विकासं पेदाते । स्रोतस उपलभ्यमानत्वादनार्यभाषाप्रभवत्वं क्लिष्टकल्पनामात्रम् ।

ज—अ॒इउम् = श्रवणे ।

+√अम्ब् (अम्ब) १/४११ गतौ (प)
मै-श-च-जै-काकृ-कात-शा ×
क्षी-सा-हे-वो ।

<अर्ब् (अर्ब) १/४११ गतौ (प) ।
अम् (अम) १/४५९ गत्यादिषु (प) ।
अम्म् १/२२५ गतौ (प) काकृ ।

अर्वेत्यादौ रेफस्थाने नकारं कौशिको मन्यते—क्षी । अर्बादयो नोपधा इति कौशिकः—सा १/४१२ ।

ग—पूर्ववदुदाहरणानि बोध्यानि । √अम् १/४५९ गत्यादिषु>√अम्ब् गतौ ।

एकस्मादेव धातोरर्थभेदादुभयतः√अम्ब (अबि) शब्दे, √अम्ब् गतौ चेति विकासः ।

+√अम्भ् (अभि) १/३८२ शब्दे (आ) इति दुर्गः-क्षी.
मै-श-च ×
क्षी-सा-जै-काकृ-कात-शा-हे ।
ध्वनौ—वो ।

√रेभ् (रेभृ) १/३८२ शब्दे (आ) ।
√रम्भ् (रभि १/३८२ (आ) ।
√अम्ब् (अबि) १/२७५ (आ) ।
√आप् (आप्लृ) ५/१४ व्याप्तौ (प) ।
√अम् (अम) गत्यादिषु (प) ।

क—द्रष्ट. √अम्ब् १/३७५ ।

ग—अम्भः किमासीद् गहनं गभीरम्-ऋ. सं. ८,७,१७,१ । आप्नोति, आप्यते वा । उदके नुम्भौ च (उ० ४/२१०) इत्यसुन् ह्रस्वो भान्तादेशो नुमागमश्च । (२) अम्भते वा । असुन् (उ० ४/१८९) ।

देशोच्चारणविशेषेण, अल्पप्राणे प्रयोक्तव्ये महाप्राणप्रयोगात् (√अम्)> √अम्ब्>√अम्भ् इति जातम्। अनयोर्मूले√अम् विराजते। उपरितनी व्युत्पत्ति-र्नौचितीमावहति। विकासशृङ्खलां विचारयन् क्षीरस्वामी अमरकोशटीकायाम् अम्भस्-शब्दस्य व्युत्पत्तिम् अमति-इत्यम्भः इति दर्शयति। एषा व्युत्पत्तिर्भानुजिदीक्षितेन स्वाम्याकूतमनवबुध्य निराकृता प्रमाणान्यनुपस्थाप्य। विशेषः √अम्ब् शब्दे धातुतो ज्ञानीयः।

√अय् (अय) १/४७० गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। वो ×, श

√इ (इण्) २/३४ गतौ (प)।
√इ १/३२० गतौ (प) मै।
√ई १/३१७ गतौ (प) अन्ये ई च प्रश्लिष्टमाहुः—क्षी।
√ई २/३८ गतिप्रजनकान्त्यसनखादनेषु (प) सा।
√ई (ईङ्) ४/३४ गतौ (आ)।
√अय् (अय) १/८६८ गतौ (उ)। अयते (निघण्टौ २/१४) गतिकर्मा।
√अज् (अज) १/२२६ गतिक्षेपणयोः (प)।

ग—अयते-ऋ. १,१२७,३।
ङ—अय (सक)=(१) गमने, (२) प्रापणे, (३) ज्ञाने (सम ९३)।
ज—आयोन्, एओन् } = गतिकरणे।

√अय् (अय) १/८६८ गतौ (उ) क्षी-सा-वो। मै-श-च-जै-काकृ-कात-शा-हे ×

पूर्वसूत्रवत्।

ग—अयति-शौ १३,१,५८; अयाम–तै ७,४,९,१। अयन्तम्–बाष्कलोप. ४।
ङ—अय (सक)–गमने, (२) प्रापणे, (३) ज्ञाने (सम ९३)।

+√अर्घ् (अर्घ) १/७३१ ××× (प) मूल्ये–वो। मै-सा-श-च-जै-काकृ-कात-शा ×, क्षी-हे

√अर्ह् (अर्ह) १/७३१ पूजायाम् (प)।
√अर्घ (अर्घ) १०/१६८ × × श।
√ऋह् (ऋह) ६/२७ कत्थनयुद्धहिंसादानेषु(प) क्षी।

क—अरगुह्=अर्जने, प्राप्तौ, जये । लिथु. अल्ग्=अर्जनम्, प्राप्तिः ।

ख—अवे. अर्जह्=अर्घः, मूल्यम्—वा. पॉकर्नीः ।

ग—कलां नार्हन्ति षोडशीम् (मभार. सभा. ३८/२६)–ईजर्टनसम्पादिते पूना-संस्करणे । नार्घन्ति रत्नानि समुद्रजानि—पञ्चत. १,८८ ।

घ—अग्घति—जातक १,११२ ।

ङ—अग्घ (सक) (१) सुमूल्येन विक्रये, (२) समादरे (सुपा ५०१) ।

छ— { आघ॰ =मूल्यम् ।
आघु॰ (स्त्री) = ,, ।

√अर्च् (अर्च) १/२०१ शX	पूजायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । पूजे (उप)–वो ।	√ऋच् (ऋच) ६/२३ स्तुतौ (प) । √अर्च् (अर्च) १०/२५९ पूजायाम् (प) । √अर्क् (अर्क) १/४१० आदाने (आ) काकृ । √अर्क् (अर्क) १०/१०३ स्तवने (प) । अर्चति (निघण्टौ ३/१४) अर्चतिकर्मा ।

क—एर्क=द्युतौ । अर्मे.–एर्ग्=अर्कः–वा. पॉकर्नीः ।

ग—अर्चति—ऋ. ७,२२,३ ।

घ—अच्च् (अच्च) अच्चने—धा. म. ५४; अच्च पूजायां—सद्दनी. १३६, १३४१ अच्चति (दाठावंस ५,६६) ।

ङ—अच्च (सक)=पूजने । अच्चेइ (औप) (सुपा ७८) (दे. ना. २/३५) ।

छ—अरचना ॰=पूजने ।

ज—आर्जि=प्रार्थने (संथाली, हिन्दी) ।

√अर्ज् (अर्ज) १/२१९	अर्जने (प) क्षी-मै-सा-च-काकृ-कात-शा-हे-वो । सर्जने–जै । बा. ग. प. मुद्रणदोषमाह तन्न समीचीनम्, सर्ज-अर्जने इति धातोः सत्त्वात् ।	√ऋज् (ऋज) १/१७३ गतिस्थानार्जनोर्जनेषु (आ) । √सर्ज् (सर्ज) १/२२० सर्जने (प) । √अर्ज् (अर्ज) १०/१९३ प्रतियत्ने (प) । √राज् (राजृ) १/८०५ दीप्तौ (उ) ।

क—अल्गुह्=अर्जने—वा. पॉकर्नीः।

ग—यद्घमर्जति—नैष. ५/८४।

घ—अज्जति—जातक ३,२६३ (?)।

ज—अर्जाओ=अर्जने, अन्नोत्पादने।

√अर्द् (अर्द) १/५३ शX	गतौ याचने च (प) क्षी-मै-सा-काकृ-कात। गतियाचनयोः-जै-शा-हे। यातने, च=गतौ याचने इत्येके-क्षी। गतियातनयोः-हे। गतौ-च। यातनागतियाचने-वो।	√ऋ १/९२० गतिप्रापणयोः (प)। √ऋत् (ऋत) १/ जुगुप्सायाम् (आ) सौ. धा.। √अर्थ (अर्थ) १०/३४९ उपयाञ्चायाम् (आ)। √अर्द् (अर्द) १०/२७७ हिंसायाम् (प)। अर्दयति (निघण्टौ २/१९) वधकर्मा। अर्दति (निघण्टौ २/१४) गतिकर्मा।

क—एर्-एर्द्=विकिरणे, धावने-वा. पॉकर्नीः।

ग—आर्दन्-ऋ. ४,१७,२। वेदे-ऋदति प्रयोगोऽपि लभ्यते-विग्रीवासो मूरदेवा ऋदन्तु-ऋ. ७,१०४,२४; शौ (अ.वे.) ८,४,२४; श्रोणया कटमर्दति-शौ (अ. वे.) १२,४,४; अर्दति-रघु. ५,१७=याचते (सं.)।

+√अर्ब् (अर्ब) १/४४१ श-काकृX	गतौ (प) क्षी-मै-सा-च-जै-शा-हे। गतौ हिंसायां च-कात। हिंसे गतौ च-वो।	√अम्ब् (अम्ब) १/४११ गतौ (प)। कौशिको मन्यते-क्षी।

ग—महान्तं चिदर्बुदं निःक्रमीः पदा-ऋ.१,५१,५; अर्बुदिर्नाम यो देवः-अ. वे. ११,९,४।

अर्बुदनिरुक्तिः-अर्बुदो मेघो भवति। अरणमम्बु, तद्दोऽम्बुदः, अम्बुमद्भातीति वा। अम्बुमद्भवतीति वा। स यथा महान् बहुर्भवति वर्षस्तदिवार्बुदम् (निरुक्ते ३,१०,१)।

[स्वामी व्युत्पत्तिं न दर्शितवान्। भानुजिदीक्षितेन तु-"अरं बुन्दति", √बुन्द् (उबुन्दिर) निशामने +मूलविभुजादिः (वा. ३,२,५), पृषोदरादिः (६/३/१०९) इति व्युत्पादितम्। "अर्बुदो मांसपुरुषे दशकोटिषु न स्त्रियाम् (अर्बुदो मांसकीले स्यात् पुरुषे दशकोटिषु)। महीधरविशेषे ना" (मेदिनी, दे १९,२०)।]

यदि पिण्डः पुमान् स्त्री चेत् पेशी नपुंसकं चेदर्बुदमिति-सुश्रु. १,३२२,७। सुश्रुते-नासार्बुद-१,२५,६; मांसार्बुद-१,३००,१; मेदोर्बुद-२,१०९,११। शोणितार्बुद-१,२९९,१; द्विरर्बुद-१,२८८,११।

+√अर्व् (अर्व) १/५८०	हिंसायाम् (प)	√ऋ ५/२९ हिंसायाम् (प)।
श×	क्षी-मै-सा-च-जै-	√ऋ १/९२० गतौ (प)।
	काकृ-हे।	√अर्ब् (अर्ब) १/४११
	वधे-वो।	गतौ (प)।
(कात-√अर्ब्)	गतौ हिंसायां च-	√अव् (अव) १/५९६
	कात।	रक्षणगतिप्रीतितृप्त्यवगम...
		हिंसादानभागवृद्धिषु (प)।

ग—अर्वतीः-ऋ. १,१४५,३; अर्वति-ऐब्रा. ३,३४; अर्वस्व-मै ४,१२३। अर्बुकाश्चैव राजानः-मभार. २,१११९।

बवयोरभेदादयं धातुः पूर्वधातुश्च मिथः संक्रान्तौ। अत उभयत्र गतौ हिंसायां चेति पाठो दृश्यते। अस्य धातोर्गत्यर्थकत्वम् "अर्वन्" (ऋ. सं. ४,५,१४,४) शब्दे स्पष्टम्। यथाह दुर्गाचार्यः-(ऋच्छति)=गच्छत्यध्वानं प्रापयत्यध्वनः पारम् इति वा। √ऋ १/९२० गतिप्रापणयोः। (उ. ४/१०९) इति वनिप् प्रत्ययः।" निरुक्ते (१०/३१) तु-"अर्वेरणवान्" इत्यस्ति। एतद्भाष्ये स्कन्दस्वामी प्राह-"भाष्ये तु-अर्वेरणवान् इत्यर्थप्राप्तवचनं द्रष्टव्यम्"। एवं विचारणया ज्ञायते-द्विधा विकासं प्राप्त एष धातुः-१-√ऋ>अर्>√अर्व्। २-√अव् १/५९६ हिंसायाम् (मध्ये रकारे प्रयुक्ते)>√अर्व् इति।

[अर्वन् = इन्द्रः, गोकर्णपरिमाणं च-इति विश्वः। घोटके, कुत्सिते च-इति मेदिनी, वे ३६। अर्वती = घोटकी-इति हलायुधः, "कुट्टनी" इति त्रिकाण्डशेषः। यथाह मेदिनीकारः-"अर्वती कुम्भदास्यां च वडवायां च योषिति-ते ८६। अत्र सर्वत्र हिंसागत्यर्थकत्वे संनिविष्टे।]

√अर्ह (अर्ह) १/७३१	पूजायाम् (प)	√अर्घ् (अर्घ) १/७३१
	क्षी-मै-सा-	

श×	च-जै-काक्र-कात-शा-हे । योग्यत्वे पूजने-वो ।	(प) क्षी. । मूल्ये-वो । √ऋह (ऋह) ६/२७ कत्थनयुद्धहिंसादानेषु (प) क्षी । √ऋ १/९२० गतिप्रापणयोः (प) । √अर्ह् (अर्ह) १०/१९९ पूजायाम् (प) ।

क—अल्गुह = तुल्यमूल्यकम् । योग्यत्वे, औचित्ये ।

ख—अवे. अर्‍जैति = आदरे, पूजायाम्, योग्यत्वे (न. पर्सि. अर्जीदन् = योग्यत्वे, औचित्ये)-वा. पॉकर्नीः ।

ग—अर्हति—ऋ. २, १४, २; १०, १५८, २; १०, ८५, ३ ।

घ—अरह्ह (अरह) पूजायां—धा. पा. ३३०, धा. म. ४८७, सद्दनी. १०१३, १६७० अरहेति । अरहति—सुत्तनिपात ४३१,५५२ । जातक १,२६२ ।

ङ—अग्घ (सक) = योग्यत्वे (णायाधम्मकहासुत्त १,८) ।

ङ—अरिह (”) = योग्यत्वे, (२) पूज्यत्वे, (३) पूजायाम् । अरिहइ (महा) ।

ज—आर्जि = प्रार्थने (संथाली, हिन्दी) । तुलनीयः- (ख-) ।

√अल् (अल) १/५१६	भूषणपर्याप्तिवारणेषु (प)	√ऋ १/९२० गतिप्रापणयोः (प) ।
श-च×	क्षी-जै-शा-,मै-सा-काक्र-कात-हे (उप) । वारणपर्याप्तिभूषासु-(उप)-–वो ।	√अड् (अड) १/३५३ उद्यमे (प) । √अल्ल् १/२२७ eबन्धने पालने च (प) काक्र ।
(क्षी-√अल् (अलँ)-	अल्तः प्रयोगसिद्धये ।	√अलर्क् १/४१० gआदाने (आ) काक्र ।

ग—अलकं पूरयामास मैथिल्याः—वा. रा. २,९६,२०; रघु. १,४२;४,५४ (भूषणेऽर्थे) ।

[“अलकाश्चूर्णकुन्तलाः” (अ. को. २,६,९६)-अलति, अल्यते वा । अल+उणा । ५/४५ वुन् । “अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले-(मेदिनी, के ४१)]

अलातृणः—ऋ. सं. ३,२,२,५। "अलातृणोऽल्पमातर्दनो मेघो वलः"-निरुक्ते ६,२। अलम्-(अलति। बाहुलकादम्)। "अलं भूषणपर्याप्तिवारणेषु निरर्थके। अलं शक्तौ च निर्दिष्टम्" इति विश्वः। अलम् इति योगेनैव "अलङ्कार"-शब्द आभूषण-वाचको भवति।

[अलिः-(अलति = दंशे समर्थो भवति। √अल्+'सर्वधातुभ्य इन्'—उणा. ४/११८) "भृङ्गवृश्चिकयोरलिः"-इति रभसः। अलीकम् (उ. ४/२५) इति साधु। "अलीकमप्रियेऽपि स्यादिव्यसत्ये नपुंसकम्"-मेदिनी—के, ४२। "अलीकसहितेऽपि"-इति काव्यः (भानुजिदीक्षितः—अ. को. २/६/९२)]

छ—अड़ना (<√अल् वारणे) = (१) गतिरोधे, (२) हठे।

छ—आड़ना (<√अल् वारणे) = (१) वारणे, (२) बन्धने, (३) निषेधे, (४) निधिनिक्षेपणे।

ज—आलिच = अङ्कुशप्रयोगे।
आलु = हस्तेन जलपरिष्कारे।
आलांग् = हललौहोपकरणादीनां निशाने (प्रताप्य)।

√अव् (अव) १/५९६ शX	रक्षणगतिकान्तिप्रीतितृप्त्यवगम-("न"-जै-शा-हे)-प्रवेशश्रवणस्वाम्यर्थयाचन-क्रियेच्छादीप्त्यवाप्त्यालिङ्गन-हिंसाऽऽदानभाग-(दान-भागयोः स्थाने 'दहन-भाव' —जै-शा-हे)-वृद्धिषु (प)	√अप् १/२२८a पालने (प) काक्र। √अप्प् १/२२८b पालने (प) काक्र। √अव्व् १/२२७d बन्धने पालने च (प) काक्र। √अव्य् १/२२७e बन्धने पालने च (प) काक्र।
	क्षी-मै-सा-जै-शा-हे। रक्षणे—च। पालने—काक्र-कात। रक्षे गतौ कान्तौ प्रीतौ तृप्तौ द्युतौ श्रुतौ प्राप्तौ श्लेषेऽर्थने वेशे भागे वृद्धौ ग्रहे वधे स्वाम्यर्थेऽवगमे कामे कृतौ—वो।	√अव् १०/१७५ अवकल्पने (प) काक्र। अवति (निघण्टौ २/१४) = गतिकर्मा। आवयति (...२/८) अत्तिकर्मा। √अब्ब् १/२२९ जनने (प) काक्र।

क—अउ = श्रवणे, रक्षणे, अवधाने। पु. च. स्ला. उम = ज्ञानम्, निर्णयः। लैटि.-अवुस् = पितामहः ?-वा. पॉकर्नीः।

ग—अवति—ऋ. ७,१०४,१२। तेन मामवति—रघु. ११/७५=प्रीणाति (सं०)।

ङ—अव (सक)=उपरितनेपु सर्वेष्वर्थेषु। अव—(श्रा २३; विसे २०२०)।

ज—आउ=अवाप्तौ।

झ—अव्व=प्रवेशे—"आलार अव्वम जन्ठरा" (प्रसङ्ग-पारिजाते ३/७)।

√अश् (अशू) ५/१८ व्याप्तौ (आ) क्षी-मै-च-जै-काकृ-कात-शा। व्याप्तौ संघाते च—सा-हे। व्याप्तिसंहत्योः—वो।

श

√अक्ष् (अक्षू) १/६४५ व्याप्तौ संघाते च (प)। √अह् (अह) ५/२६ व्याप्तौ (प)। अशत् (निघण्टौ २/१८) व्याप्तिकर्मा। आनशे (निघण्टौ २/१८) व्याप्तिकर्मा। अश्नुत (निघण्टौ २/१८) व्याप्तिकर्मा।

क—एनेश्-(enek̂) नेश्-, एश-, नंश्=प्राप्तौ, दाने, उपस्थितौ, पूर्तौ।

ख—अवे.-अश्नओइति=प्राप्तौ, उपस्थितौ—वा. पॉकर्नीः।

ग—अश्नोति—ऋ. १,९४,२; अश्नुते—ऐब्रा. १,६; अनन्तं सुखमश्नुते—मनु ४/१४९।

ज—आसि=लिप्सायाम्, (२) याचने।

√अश् (अश) ९/५१ भोजने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

√अश् (अशू) ५/१८ व्याप्तौ (प)। √अद् २/१ भक्षणे (प)।

क—अश् (ak̂) अशो (ak̂o)=अशने (अदने)-जू. पॉकर्नीः।

ख—अवे.-अश्नओइति=प्राप्तौ, उपस्थितौ—वा. पॉकर्नीः।

ग—अश्नाति-ऋ. ९,६७,३१।

घ—अस् (अस) अदने—धा. पा. २९२, धा. म. ४३०; भोजने—धा. पा. ५०६, सद्दनी. १२५९, मक्खणे—धा. म. ७३०, अस्नाति—जातक १,४७२। अस्नातु—जातक ५,३७६।

ङ—अस (सक) भोजने। असइ (सार्ध १०९; भवि)।

ज—आसादि=अतिभोजने, अतितृप्तौ।

+√अष् (अष) १/८९० क्षी-श-च-जैं-कात ×

गतिदीप्त्यादानेषु (उ) इत्येके-मै ।
मै-सा-शा ।
गतौ दीप्त्यादानयोश्च —काकृ ।
दीप्तौ गत्यादानयोश्च —हे ।
दीप्तौ ग्रहे गतौ—वो ।

√अस् (अस) १/८७२ गतिदीप्त्यादानेषु (उ) ।
√अस् (अस) २/५४ भुवि (प) ।
√अस् (असु) ४/९६ क्षेपणे (प) ।
√अक् (अक) १/७८६ कुटिलायां गतौ (प) ।
√अग् (अग) १/७८७ कुटिलायां गतौ (प) ।
√अव् (अव) १/५९६ रक्षण··दीप्ति····आदान··· (प) ।

ग—प्राषितः—पै २०, २६, २ ।

अशतर>कर्माषतरास्मै–साय. (ब्योथ-रॉथ.)=अषतर– =व्याप्ततर- ।

+√अस् (अस) १/८७२ श–जै-शा ×

गतिदीप्त्यादानेषु (उ) क्षी-मै-सा ।
गतौ दीप्त्यादानयोश्च —काकृ-कात ।
दीप्तौ गत्यादानयोश्च—हे. ।
गतौ—च ।
अषार्थे (दीप्तौ ग्रहे गतौ) —वो ।

>√अष् (अष) गतिदीप्त्यादानेषु (उ) इत्येके—मै ।

ग—रिपुरास भूभृताम्—रघु. ११/८१=बभूव (सं.) । "आस" इति तिङन्तप्रतिरूपकमव्ययम्, दीप्त्यर्थकस्यास्ते रूपं वा"–(सं.) ।

√अस् (अस) २/५४ श

भुवि (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
भावे—वो ।

क—एस्=सत्तायाम् । लिथु.-एस्मि, एस्त् (इ); पु. प्रशियन्-अस्मइ, अस्त्, एस्त्; पु. च. स्ला. जेस्म, जेस्त ।

ख—अवे. अह्मि, अस्ति—वा. पॉकर्नीः ।

ग—अस्ति—ऋ. १,२७,८; आस-ऋ. ४,३५,४ ।

छ—अछना *=भुवि । बंगा. आछे, मैथि. छै, मरा.-आहे, पुरा. हि.-अहै ।

आछना *
आथना } = भुवि ।
आसनां *

√अस् (असु) ४/९६ श	क्षेपणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । क्षेपे—वो ।	√अस् (अस) १/८७२ गतिदीप्त्यादानेषु (उ) ।

क—एंस् ।

ख—अवे. अंह्येइति-, अंस्त् =शत्रुता, अनुसरणम्-वा. पॉकर्नीः ।

ग—अस्यति-ऋ. ३, ५३, २२ । भौवादिकोऽपि—आत्मारामः समभ्यसत्-श्रीमद्भागवत. १,७,९ ।

+√अह् (अह) ५/२६ श-च-जै-काकृ-कात-शा × (हे-वो-√अड्) लैपिकी त्रुटिः । √अह् इति स्यात् ।	व्याप्तौ (प) क्षी-मै-सा । हे । व्यापे—वो ।	√अक्ष् (अक्षू) १/६४५ व्याप्तौ संघाते च (प) । √अश् (अशू) ५/१८ व्याप्तौ (आ) क्षी । अह् १/३१६ । हिंसागत्योः (प) काकृ ।

ग—अंहू-ऋ. १, ४२, १ । √अहू इत्यस्यैवानुनासिकोपक्रमं प्रकारान्तरमित्य-र्वाचाम् अभिसन्धिर् भवति (तु० Gw.) अयं च धा० २ अह इति च यक्र. √अङ्घ् इत्यनेन √अघ् इत्यनेन च समानं समूलतया प्रतिपत्तव्यौ भवत इति तु तत्त्वम् अववेयम् इति शास्त्री विश्वबन्धुः । अस्माकं मतेन तु √अक्ष् १/६४५ व्याप्तौ संघाते च (प) अयम् √अह् धातुः, √अश् ५/१८ व्याप्तौ (आ) च मिथः संक्रान्ताः सन्ति । √अङ्घ्, √अघ् धातू न व्याप्त्यर्थकौ न च सौवादिकौ-इति तयोरत्र संक्रान्तिश्चिन्त्या । विकल्पितशप्श्नुतया चोपदिष्टः (पा० ३/१/७५) √अक्ष् धातुः । अक्ष्णोति > अह्नोति इति विकासः सुबोध्यः ।

√आञ्छ् (आछि) १/२०६ श× (जै)	आयामे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	आ+यम्=आयच्छ् > √आञ्छ्-(वागीशः) । √अञ्च् (अचि) १/८४७ गतौ (उ) ।

ग—आञ्छेद् ऊर्ध्वमधो वापि कटिभग्नं तु मानवम्—सुश्रु. चिकि. ३,२८। आञ्छेत्=बध्नीयात्। (डल्हणाचार्यो निबन्धसंग्रहाख्यव्याख्यायाम्); आञ्छन्-सुश्रु० २, ८१, १।

√आप् (आप्लृ) ५/१४	व्याप्तौ (प) क्षी-मै-सा-च-जै,काक्र-(उप), कात-शा-हे। व्यापने-वो।	√आप् (आप्लृ) १०/२८६ लम्भने (प) आधृषाद्वा। अप्-शब्दो जलवाची व्याप्त्यर्थकः।

क—अप्=प्राप्तौ, उपस्थितौ; एप=प्राप्तौ, उपस्थितौ, ग्रहणे।

ख—अपयेइति=प्राप्तौ-वा. पॉकर्नीः।

ग—आप-ऋ. ४, १, ९; आप्नोति—मा १९, १९।

घ—√अप्प् (अप्प) पापुणे-सद्दनी. १२८७ अप्पोति-विसुद्धिमग्ग ३५०।

ज—आपिर्=उड्डयने।

√आस् (आस) २/११ श	उपवेशने (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। उपवेशे-वो।	आ+√स्था १/९१२ गतिनिवृत्तौ (प)। आ+√सद् (षद्लृ) १/८३९ विशरण० (प)। √अस् २/५४ भुवि (प)।

क—सेद्=उपवेशने। * एस्=उपवेशने। * ए-स् (द)

ख—अवे.-आस्ते=उपवेशे। अंहे॰न्ते=उपवेशे-वा. पॉकर्नीः।

ग—आस्ते-ऋ. १०, ७१, ११।

घ—अच्छति-विनय १, २८९।

ङ—√आस (अक)=उपवेशने (पि ५७८)।

,,—√अच्छ (अक)=उपवेशने। अच्छइ (णाया १,१)।

√इ १/३२० क्षी-श-जै-शा ×	गतौ (प) मै। मै-सा-च-काक्र-कात-हे-वो।	√अय् (अय) १/८६८ गतौ (उ)।

ग—अयति-पै १०, २७, २; जैब्रा. १५५।

√इ १/३२०, √अय् १/८६८ द्वावेव धातू अभिन्नौ ज्ञेयौ। क्षीरसायणवोपाः √अय् १/८६८ धातुं पेठुः, मैत्रेय-सा-च-काक्र-कात-हे-वोपाश्च √इ धातुम्। सायण-वोपशेद्वावेव मतौ।

४

√इ (इण्) २/३४ श	गतौ (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो ।	√गा (गाङ्) १/९३५ गतौ (आ) । √इ २/३६ स्मरणे (प) । √अय् १/४७० वत् (शेषः) । एति-(निघण्टौ २/१४) ।

क—एइ् =गतौ । लिथु.-एइमि (एइनु) गतिकर्मा ।
ख—अवे. अएइति । पु. पर्सि.-ऐतिय् =गतौ-वा. पॉकर्नीः ।
ग—एति-ऋ. १, २३, ११ । इनोति ऋ. ८, ३९, ५ ।
ङ—√इ (सक)=गतौ, (२) ज्ञाने । एइ (कुमा) ।

?+√इ (इङ्)२/३५ श अधि+इ	अध्ययने (आ) क्षी-मै- सा-च-जै-काकृ-कात-शा-हे । -वो ।	√इ (इक्) २/३६ स्मरणे (प) । अधि+√इ (इण्) २/२४ गतौ (प) ।

ग—अधीते-ऐआ. ३, १, ६ ।
घ—अधीयति-विनय. १, २७० ।

√इ (इक्) २/३६ श अधि+√इ " "	स्मरणे (प) क्षी-मै-सा- च-जै-कात-शा-हे । स्मरणे-काकृ । स्मृत्याम्-वो ।	√इ (इण्) २/३४ इत्यस्यैवार्थभेदार्थं प्रपञ्चः ।

? ग-अध्येति-ऋ. ४,१७,१२; मै ३, ३, ६। अध्येति-मभाष्ये ६. ४. २२. ३/३०; १.३.१. २५/६ ।

+√इख् (इख) १/१४० मै-श-च- जै-काकृ-कात-शा×	गत्यर्थः (प) क्षी-सा । गतौ-हे-वो ।	<√इङ्ख् (इखि) गत्यर्थः (प) इत्येके-क्षी । √ईङ्ख् (ईखि) १/१४१ गत्यर्थः (प) । √इ (इण्) २/३४ गतौ (प) । √इ १/३२० गतौ (प) मै । √रिङ्ख् (रिखि) १/१५३ गत्यर्थः (प) ।

√इ १/३२० इत्यनेन व्यञ्जनद्वितीयाक्षरयोगे सति √इख् धातुः सानुनासिकत्वे >√इङ्ख् निष्पद्यते ।

+√इङ्ख् (इखि) १/१४० शX	गत्यर्थः (प) इत्येके-क्षी क्षी-मै-सा-च-कात। गतौ—जै-काकृ-शा-हे-वो।	<√इख् (इख) गत्यर्थः (प)। √ईख् (ईख्) १/१३९ गत्यर्थः (प) √ईङ्ख् (ईखि) १/१४१ गत्यर्थः (प)। √इङ्ग् (इगि) १/१५२ गत्यर्थः (प)।

ग—"प्रेङ्खत्काञ्चीकलापाः"-भर्तृ. सु. सं. ९७; "प्रेङ्खयन् परिजनापविद्धया"-रघु. १९,४४ = चालयन् (सं०) इति प्रयोजकप्रयोगमन्तरा च नान्यद् रूपम् अक्षिपथमुपगतम्। ऋग्वेदे-"प्र प्रेङ्ख ईङ्खयावहै"-७, ८८, ३ इत्यत्र प्र+√ईङ्ख् धातुर्भवितुमर्हति, उभयत्रापि तथा। ततोऽपि वेदेषु√ईङ्ख् धातोः (प्रयोजकस्य) प्रयोगाधिक्यात् तत्र प्राय उपसर्गराहित्याच्च सोपसर्गे प्रयोगे√इङ्ख् धातोरौचिती। एवमपि √इङ्ख √ईङ्ख् इत्युभयोर्मिथः सुनिर्भरं संक्रान्तेः कारणात् पृथक्कृतौ सन्दिहन्त्येव मनीषिणः।

√इङ्ग् (इगि) १/१५२ शX	गत्यर्थः (प) क्षी-मै-सा-च-कात। गतौ—जै-काकृ-शा-हे।	√इङ्ख् (इखि) १/१४० गत्यर्थः (प)। √ईङ्ख् (इखि) १/१४१ गत्यर्थः (प)। √एज् (एजृ) १/२३० कम्पने (प)।

क—ऐग् = दोलने, प्रस्पन्दने। पु. उत्त. जर्म. एइकेन्न = ग्राम्यम् (:), क्रोधिन्, धर्मध्वजिन्। लिथु. ऐक्रिटस् = उत्कण्ठा, क्रोधः। पु. च. स्ला. इग्र=क्रीडा—वा. पॉकर्नीः।

ग—इङ्गयन्ति—ऋ. १, १६४, ४५; इङ्गते—छाग. २५ : ९; गी. ६, १९; इङ्गति—म० भार० ३, ८७२६।

√इट् (इट) १/३१५ शX	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।	√अट् (अट) १/२९२ गतौ (प)। √इण्ड् १/१८३ √हिंसागत्योः (प) काकृ। √ईट् १/११३ गतौ (प) काकृ। √इ १/३२० गतौ (प) मै। √इड् १/२१६ धारणे (प) काकृ।

ग—त्वमिटतो रथमिन्द्र प्रावः सुतावतः—ऋ, १०, १७१, १। इटस्य ते—अ. वे. ९, ३, १८। वैतस इटसून्—शब्रा. १३, २, २, १९।

+√इन्त् (इति) १/६० बन्धने (प) <√अन्त् (अति) बन्धने (प)।
मै-सा-श-च-जै- अन्ये—क्षी।
काकृ-कात-शा× क्षी-हे-वो।

अत्र धनपालः—तान्तं द्रविडाः पठन्ति। आर्यास्तु दान्तमिति। उभयमिति मैत्रेयस्वामिकाश्यपसम्मताकारादयः (धा. वृ. ५३ पृ.)।

+√इन्द् (इदि) १/६१ परमैश्वर्ये (प) क्षी-मै-सा- √इन्त् (इति) १/६०
श× च-जै-काकृ-कात-शा-हे-वो। बन्धने (प)√इण्ड्
१/१८३।। हिंसागत्योः (प)
काकृ।

क—नेर-अनेर् (एनेर ?) = मनुष्यः, पतिः। जर्म. नेरथुस्; पु. उत्त. जर्म. न्जॉर्द्र (= प्रसेवः)-जू. पॉकर्नीः।

ग—शरद इन्दुरिन्द्रः-ऋ. ६, ३९, ३; आपद्घ्योकमिन्द्रियं पूयमानः-ऋ. ९, ९०, १। इन्द्रियम् (= रसः) ऋ. ९, १३, ५; (= सोमः) ऋ. १०, ६५, १०।

√इन्ध् (ञिइन्धी) ७/११ दीप्तौ (आ) क्षी-मै-सा-च- √इन्द् (इदि) १/६१
श× जै-काकृ-कात-शा-हे। परमैश्वर्ये (प)। √एध्
द्युतौ-वो। १/२ वृद्धौ (आ)।

क—(ऐ) ऐद्-, ऑइद्-, ऐध्, इ-ध्; नासिक्यम्-इन्ध् = दीप्तौ-जू. पॉकर्नीः।

ग—इन्धते-ऋ. १, ४४, ८; ईधे-ऋ. १, ३६, ११; इध्यते-जै १, २, १०; एधस् (ः)—मा २०, २३। इध्मः-षव्रा. ३, ८।

√इन्व् (इवि) १/८२ व्याप्तौ (प) √ई २/३८ कान्तिगतिव्याप्तिक्षेप-
श-जै× क्षी-मै-सा-च-काकृ- √प्रजनखादने (प) वो।
कात-शा। √इन्वति (निघण्टौ २/१४) गतिकर्मा।
व्याप्तौ प्रीणने च—हे। इन्वति (निघण्टौ २/१८) व्याप्ति-
व्याप्तिप्रीणनयोः—वो। कर्मा।
√इ १/३२० गतौ (प) मै।

क—ऐ = ग्रहणे, कम्पने, विदारणे।
ख—इनओइति, (अएनन्हे) = बलात्कारे, क्लेशने, पीडने-वा. पॉकर्नीः।
ग—इन्वति-ऋ. १,१८,७; इनोषि-ऋ. ४,१०,७।

√इन्व् (इवि) १/५८६ प्रीणने (प)
क्षी-सा।

साय. पूर्वपक्षत्वेनोपस्थापयति (धा. वृ. ११२ पृ.)। पूर्ववत्।
ज्याप्तौ प्रीणने च—हे।
ज्याप्तिप्रीणनयोः—वो।
पूर्वधातोरभिन्नोऽयमर्थभेदार्थं पृथगुपन्यस्तः।

√इल (इल) ६/७९ स्वप्नक्षेपणयोः (प) | √इ १/३२० गतौ (प)।
क्षी-मै-सा-जै-शा। | √ईर् (ईर) २/८ गतौ कम्पने च (आ)।
श × गतौ धारणे च-काक्ृ। | √इड् (इड) १/२१६ धारणे (प)
गतौ च-कात। | काक्ृ।
गतिस्वप्नक्षेपणेषु-हे। | √इल (इल) १०/१२० प्रेरणे (प.)।
शये गतौ क्षेपे-क्षी।

क—एल्=विश्रामे, शयने ? अल = पूरणे, भोजने। द्-विस्तारः-ग्रीकभाषायाम् एलैनो=क्षेपणे, वृद्धौ; शक्तिः (तेजः)—वा. पॉकर्नीः।

ग—इळा देवी भारती विश्वतूर्तिः-ऋ. २,३,८; इडाः-ताब्रा. १४,५,३१।
इलयति-मै ३,४,६; शौ १०,७,३७; पै १७,१०,८।

छ—{ अडलना * (उत्=उच्चैः+√इल=प्रक्षेपणे) उड़ेलना, ढालना-इति हिन्दी। उड़ेलना

√इष् (इष) ४/२० गतौ (प) | √इ १/३२० गतौ (प)।
क्षी-मै-सा-च-जै-काक्ृ- | √इष् (एषृ) १/६१३ गतौ (आ)।
श कात-शा-हे। | √ईष् (ईष) १/६०६ गतिहिंसादर्शनेषु (आ)।

क—एइस्=तीव्रम्, क्रोधिन्—वा. पॉकर्नीः।
ग—इष्यसि-ऋ. ९,६४,९; इष्यति-शब्रा. ६,१,२५।

√इष् (इषु) ६/७२ इच्छायाम् (प) | √इ (इक्) २/३४ स्मरणे (प) +ष्>छ्।
श क्षी-मै-सा-च-जै-काक्ृ- | √इष् (इष) ४/२० गतौ (प)।
कात-शा-हे। | √इष् (इष) ९/५३ आभीक्ष्ण्ये (प)।
वाञ्छे-वो। | इषति (निघण्टौ २/१४) गतिकर्मा।

क—ऐस्=इच्छायाम्। पु. बुल्गारियन्—इस्कति।
ख—अवे. इसैति=अन्विष्यति, इसैति=इच्छति-वा. पॉकर्नीः।

ग—(* is-sk^o^) इच्छन्ति-ऋ. ३,३०,१; इच्छते-तै १,६,७,३ ।

घ—√इस्(इस) इच्छायं-धा. पा. २९५; इसु इच्छायं-धा. म. ३४३, सद्दनी. ९८९. इच्छति-संयुत्त १,२१० ।

ङ√इच्छ (सक)=इच्छायाम् । इच्छइ (उव, महा) ।

छ—इच्छना *
ईछना * } =इच्छायाम् ।

√इष्(इष) ९/५२ आभीक्ष्ण्ये (प)
श क्षी-मै-सा-च-कात-शा-हे-वो ।
अभीक्ष्णे-जै ।
अभीक्ष्णे-काक्व ।

आभीक्ष्ण्यम्=पौनःपुन्यम्-क्षी ।

√इ १/३२० गतौ (प) मै ।
√इष्(इष) ४/२० गतौ (प) ।
√ईष्(ईष) ६/७२ इच्छायाम्(प) ।
√ईष्(ईष) १/३०६ गतिहिंसादर्शनेषु (आ) ।
√ईष्(ईष) १/६७५ उञ्छे (प) ।

क—इष्यतिवद् बोध्यम् ।

ग—इष्णामि-पै. १६,३०,४; इषाण-मा. ३१,२२; का. ३५,२,६; इष्णन्ति-शत्रा. ७,१,१,२४ ।

+√ई १/३१७ गतौ (प) अन्ये 'ई' च
श-च-जै-काक्व- प्रश्लिष्टमाहुः-क्षी ।
का-त-शा-हे-वो । क्षी-मै-सा ।

√कट्(कटी) १/३१७ गतौ (प) ।
√इ १/३२० गतौ (प) ।
√ई (ईङ्) ४/३४ गतौ (आ) ।
√अय् (अय) १/८६८ गतौ (उ) ।

ग—उदयति विततोर्ध्वरश्मिरज्जौ—शिशु. व. ४/२० । √इ १/३२० गतावित्यस्यैव प्रपञ्चः । उदयन्तं दिनकरं दृष्ट्वा-वा. रा. ३,८,४, (गी. प्रे. सं.) ।

√ई २/३८ गतिप्रजनकान्त्यसनखादनेषु (प)
क्षी-मै-श-च-जै- प्रश्लिष्टनिर्देशात्-सा ।
काक्व-शा-हे × गतौ प्रजनकान्त्यसनखादनेषु च-कात ।
कान्तिगतिव्याप्तिक्षेपप्रजनखादने-वो ।

√वी २/३८ गतिप्रजन...(प) ।

ग—ईमहे-ऋ. १,१०,६; खि. ३,१,९; ईयाम्-जैत्रा. १७७ ।

√ई (इङ्) ४/३४ श	गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।	

ग—ईयते—ऋ १, ४८, ५; अन्तरीयते—ऋ. २, ६, ३; अधीयति—ऋ. १०, ३२, ३।

√ईक्ष् (ईक्ष) १/६०५ श ×	दर्शने (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे-वो। दृष्टौ—जै।	ईष् (ईष) १/६०६ गतिहिंसादर्शनेषु (आ)। इक्ष् १/५२१ आस्वादने (आ) काकृ।

क—ऑक्उ=दर्शने। ऑक्उ्-, ऑक्उ्इ-, ऑक्उ् (ए) न्—ऑक्उ्(ए) स्=अक्षि—वा. पॉकर्नी:।

ग—ईक्षते-शब्रा. ६, ३, ३, ४; अभ्यैक्षेताम्-ऋ. १०, १२१, ६; ईक्षेण्यासः-ऋ. ९, ७७, ३।

घ—√इक्ख् (इक्ख) दस्सने—धा. पा. १५; दस्सन-अङ्केसु-धा. म. १९, इक्खति-जातक ५, १५३।

ङ—√इक्ख (सक)=दर्शने। इक्खइ (उव)।

ङ—√ईह (सक)=दर्शने। ईहए (विसे ५६१)।

छ—ईखनाक्ष (<ईक्षणम्)=दर्शने (डिंगल)।

+√ईख् (ईख) १/१३९ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	गत्यर्थः (प) सा। सा।	उत्तरधातुवत्।
√ईङ्ख् (ईखि) १/१४१ सा-श-काकृ-कात×	गत्यर्थः (प) क्षी-मै-च। गतौ–जै-शा-हे-वो।	√इख् (इख) १/१४० गत्यर्थः (प)। √इङ्ख् (इखि) १/१४० गत्यर्थः (प) इत्येके। √ईख् (ईख) १/३३९ गत्यर्थः (प) सा। ईङ्खते (निघण्टौ) २/१४ गतिकर्मा।

ग—ईङ्खयन्ति—ऋ. १, १९, ७; पै. ६, १७, ७; ईङ्खितम्—ऐब्रा. १, ११। प्रप्रेङ्ख ईङ्खयावहै—ऋ. ७, ८८, ३।

√ईज् (ईज) १/१७९ श×	गतिकुत्सनयोः (आ) क्षी-मै-सा-जै-शा। गतौ—च-काकृ-कात। कुत्से गतौ—वो।	⊲√ईञ्ज् (ईजि) गति-कुत्सनयोः (आ) इति दुर्गः—क्षी। √एज् (ऍजृ) १/२३० कम्पने (प)। √इज् (इज) १/४२५ c गतौ (आ) काकृ; ३४६ कात।

ग—अपेजते—ऋ. ६, ६४, ३; ईजते—मै. ४, ५, ६। ईजानाः—मभार. १२, १७, १५=वर्णा—श्रमाद्यभिमानिनः (नील.)।

√ईड् (ईड) २/९ श	स्तुतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√ई २/३८ गतिप्रजनकान्त्य-सनखादनेषु (प)। ईट् १/२१६b गतौ (प) काकृ। ईळ् २/४१b स्तुतौ (आ) काकृ। ईड् (ईड) १०/१३० स्तुतौ (प)।

क—ऐस्=पूजायाम्। पु. उ. ज. एर्, आधु. ज. एह्रे, पु. सैक्स. एर्=दया, उपहारः। ड् (द्)-विस्तारः, गॉथि.-ऐस्तन्, ऐद=भये, संकोचे, समादरे। ग्रीक-ऐदोस्=पूजा—वा. पॉकर्नीः।

ग—ईडते—ऋ. १, १५, ७; ईट्टे—ऐआ. १, ५, २; ईळे—मा. १३, ४३; का. १४, ४, ६।

ज—इक्ड्डुम्=नमस्कृतिवेलायां जानुपातने।

ज—इदु=धर्मोपदेशने।

√ईर् (ईर) २/८ श	गतौ कम्पने च (आ) मै-सा-काकृ-कात। गतौ—च-जै-शा।	इर ? (निरुक्ते ५/२७)। √ऋ १/९२० गतिप्रापणयोः (प)।

	गतिकम्पनयोः—हे। कम्पगत्योः—वो।	√ईर्/३८ गतिप्रजनकान्त्यसनखादनेषु (प) सा। √इल् (इल) ६/७९ स्वप्नक्षेपणयोः (प)। √ईड् (ईड) २/९ स्तुतौ (आ)। ईर्ते (निघण्टौ २/१४) गतिकर्मा। √ईर् (ईर) १०/२६१ क्षेपे (प)।

क—ऐला=प्रेरणे, कम्पने।

ख—गाथा-अवे. ईरतू=उन्नतौ-वा. पॉकर्नीः।

ग—ईरते-ऋ. १,१४०,५; ईर्ते-शब्रा. १,४,१,१२; जैब्रा. १६४।

ङ—√ईर (सक)-(१) प्रेरणे, (२) कथने, (३) गतौ, (४) प्रक्षेपणे। ईरेइ (विसे. १०६०)।

+√ईक्ष्यँ् (ईक्ष्यँ) १/५११ श×	ईर्ष्यार्थः (प) क्षी-मै-सा-च-जै-कात-शा-हे। ईर्षायाम्-काकृ। ईर्ष्ये-वो।	√ईर्ष्यँ् (ईर्ष्यँ) १/५१२ ईर्ष्यार्थः (प)। √ईर् (ईर) २/८ गतौ कम्पने च (आ)। √ईर्ष् (ईर्षा) १/५२७ गतिहिंसादानेषु (आ) काकृ।

√ईष् १/६०६ गतिहिंसादर्शनेषु (आ)>मध्ये रेफप्रवेशे>√ईर्ष्+य>√ईर्ष्यँ्,√ईक्ष्यँ् इति वागीशः।

√ईर्ष्यँ् (ईर्ष्यँ) १/५१२ श-जै-काकृ×	ईर्ष्यार्थः (प) क्षी-मै-सा-च-कात-शा-हे। ईर्ष्ये—वो।	√ईर् (ईर)। २ गतौ कम्पने च (आ)। √ईष् १/५२७ गतिहिंसादानेषु (आ) काकृ। √ईक्ष्यँ् (ईक्ष्यँ) १/५११ ईर्ष्यार्थः (प)।

√ईष् १/६०६ गतिहिंसादर्शनेषु (आ)>मध्ये रेफप्रवेशे>√ईर्षँ् १/५२७ गतिहिंसादानेषु (आ) काकृ। प्रयोगो यथा–"कथमीर्षां न कुरुषे"–वा. रा. ४, २४,

३७; "रक्षेद् दारान् त्यजेदीर्षाम्"–मार्क. पु. ३४,७८। √ईर्ष्+य (दैवादिकः श्यन् प्रत्ययः) > (वेदेषु √ईर्ष् धातोः प्रयोगो लुप्तः) √ईर्ष्य् इति व्युत्पत्तिः। विलोमक्रमोऽपि स्यादालम्बनीयः। दैवादिकात् प्रत्ययात् पुनर्भ्वादेर्निदर्शनं यथा–√शुच्य् (शुच्यी) १/५१४ अभिषवे (प), √चुच्य् (चुच्यी) १/५१४ (प), √प्याय् (ओप्यायी) १/४८५ वृद्धौ (आ)।

ख—अवे. अर्ष्येइति=ईर्ष्ये–पी. टी. एस. पालि-डिक्श., 'इस्सति' इत्यस्य प्रसङ्गे।

ग—ता ईर्ष्यन्तीः पुनरगच्छन्–तै. २, ३, ५, १।

घ—इस्सति (नामधा.–इस्सा। अर्षतिः √ऋष् (ऋषी) इत्यनेनापि सम्बद्धः। लैति. एर्रो तथा सं. इरस्यति=क्रोधे)–जातक ३, ७।

ङ—√ईस (सक)–ईर्ष्यार्थः। ईसाअंति (गा. २४०)।

√ईश् (ईश) २/१० श	ऐश्वर्ये (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√ई २/३८ गतिप्रजनकान्त्यसनखादनेषु (प) सा।

ग—ईशे–ऋ. ३, १६, १; ईष्टे–शब्रा. १, ८, ३, १२; काब्रा. १, ४, २, २; छान्दो. १, ६, ८।

√ईष् (ईष) १/६०६ श×	गतिहिंसादर्शनेषु (आ) क्षी-मै-सा-हे।	√ई १/३१७ गतौ (प)।
	गतौ—च।	√ईक्ष् (ईक्ष) १/६०५ दर्शने (आ)।
	दृष्टौ गतिहिंसयोश्च—जै।	√एष् (एषृ) १/६१३ गतौ (आ)।
	गतिहिंसादानेषु—कात।	
	दर्शने हिंसागत्योश्च—शा।	√इष् (इष) ४/२० गतौ (प)
	सर्पणे दानेक्षहिंसे च—वो।	ईषते=पलायते (निरुक्ते ४/२)।
काकृ–√ईर्ष् (ईर्ष)	गतिहिंसादानेषु—काकृ।	ईषति (निघण्टौ २/१४) गतिकर्मा।

क—√इष् (इष) ४/२० गतौ (प)–स्थले प्रेक्षणीयम्।

ग—ईषते–ऋ. १, ८४, १७; पै. ७, ८, ७; तैआ. १, ३, १, ईषते वयः–ऋ १, १४१, ८।

+√ईष् (ईष) १/६७५ श×	उञ्छे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√इष् (इषु) ६/७२ इच्छायाम् (प)।
		√इष्१/२९१a उञ्छे (प) काकृ।

√ईषॣ (ईष) १/६०६ गति-
हिंसादर्शनेषु (आ)।

ग—ईषादण्डौ-शिशु. १८, ४३=दारुविशेषौ (सर्वङ्कषा)।

√ईहॣ (ईह) १/६२५ श	चेष्टायाम् (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। चेष्टे—वो।	√इषॣ (इषु) ६/७२ इच्छायाम् (प)। √इषॣ १/२९१ उञ्छे (प) काकृ। √ईषॣ (ईष) १/६०६ गति-हिंसादर्शनेषु (आ)।

चेष्टा=शरीरक्रिया। प्रमाणम्-(पा. अ. २/ ३/ १२)।

क—इअघ्=अनुसरणे, इच्छायाम्।

ख—अवे. इज्येइति=ईहते-वा. पॉकर्नीः।

ग—ईहते-गौडपादकारिका ४, ८५; महा. ३, २३; भव. १, ४२; गी. ७, २२।

घ—√ईहॣ (ईह) चेटायं-सद्दनी. १०१५ ईहति-विनय ३,२६८।

ङ—√ईह (सक) (१) विचारणे, (२) चेष्टायाम्। ईहए (विसे ५६१)।

√उ (उङ्) १/९३८ श× (जै-√तु [तुङ्]) मुद्रणदोषः। उङ् इति भाव्यम्।	शब्दे (आ) क्षी-मै-सा- च-काकृ-कात-शा-हे-वो। जै।	√वच् (वच) २/५२ परि-भाषणे (प)। √ऊ (ऊङ्) १/५५१ f शब्दे (आ) काकृ। √ओ (ओङ्) १/५५१ m शब्दे (आ) काकृ। √औ (औङ्) १/५५१ n शब्दे (आ) काकृ। √अव् (अव) १/५९६ रक्षण····श्रवण····(प)।

ग—ऊवे अम्ब सुलाभिके-ऋ. १०, ८६, ७।

अयं धातुः शब्दानुकृतिर्विद्यते। हर्षे दुःखे वा 'उ'-शब्दः सहसा मुखान्निर्गच्छति। काशकृत्स्नधातुपाठे√ऊ,√ओ,√औ शब्दे इति धातवो विकासं लक्षयन्ति। रोषेऽपि 'उ'-शब्देन स्वतो व्यज्यते रोषः। तदुक्तं मेदिनीकारेण—

सम्बोधनरोषोक्त्योरनुकम्पानियोगयोः।
पदस्य पूरणे पादपूरणेऽपि च दृश्यते॥ अव्य. ४-५।

वेदेष्वनेकत्र 'उ' इत्यस्य कृतोऽस्ति प्रयोगः—क उ तच्चिकेत–ऋ. १, १६४, ४८; स उ वायुरेव–केनो. २; अ. वे. ६, २६, २; स उ श्वः—कठोप. ४, १३।

√उक्ष् (उक्ष) १/६४८ सेचने (प)
श×
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
वृषि—वो।

√विष् (विषु) १/६८९ सेचने (प)।
√वृष् (वृषु) १/६९७ सेचने (प)।
√उक्ष् १/५२४ वहने (आ) काकृ।
√उच् (उच) ४/११० समवाये (प)।
√वच् (वच) २/५२ परिभाषणे (प)।

क—उ॒एग्॒उ॒—ःऊ॒ग्॒उ॒=आर्द्रीकरणे, सेचने। सू—विस्तारः।

ख—अवे.-वक्स्॒उ॒=सेचने—वा. पॉकर्नीः।

ग—उक्षन्ति–ऋ. १,१६६,३; उक्षतु–मै. ४,१४,११; शौ. १२,१,७; पै. ५,६,५।

ङ—√उक्ख (सक) सेचने–सूअ. २,२,५५।

छ—ऊकना=विस्मरणे, स्खलतौ (<क्षरणे<सेचने)।

छ—बु. ख.-उसनवौ (<उसन<उक्सन<उक्षण)=गोधूमचूर्णादिक्लेदने, जलेन मिश्रणे।

+√उख् (उख) १/१२८ गत्यर्थः (प)
श×
क्षी-मै-सा-च-कात।
गतौ—जै-काकृ-शा-हे-वो।

√वख् (वख) १/१३० गत्यर्थः (प)।
√उङ्ख् (उखि) १/१२९ गत्यर्थः (प)।
√वुख् १/४६० a चलने (आ) काकृ।

क—अउंकु(ह्॒)–तथा उएक्॒उ॒ (ह्॒)=उखा (स्थाली) गॉथि. अउहून्स्=चुल्लिः। लिथु. अउक्स्॒ल्यॅस्॒ =पिटः–वा. पॉकर्नीः।

ग—उखा (=मांसपचनी)–ऋ. १,१६२,१३; यज्ञोखा–निरुक्ते १०,४५; कृत्वाय सा महीमुखाम्–शब्रा. १,७,१,७०; उख्यान् अग्नीन् हस्तेषु बिभ्रतः–अ. वे. ४,१४,२। (उखायां भवस्तान्)।

"अथापि प्रकृतय एवैकेषु भाष्यन्ते विकृतय एकेषु"–(निरु. २,२,८) इति दृशेह विकृतिः प्रयुक्ता लभ्यते, न प्रकृतिः।

छ—ओखा*=मिषः।

{ ओख=शोषणम्। औंखा=अरालम्, कठिनम्, रूक्षम्, शुष्कम्, अचोक्षम् } [<उष् दाहे]

+√उङ्ख् (उखि) १/१२९ गत्यर्थः (प)
मै-श-च-जै-काक्- क्षी-सा।
कात-शा-हे× गतौ—वो।

√उख् (उख) १/१२८ गत्यर्थः (प)।
√वङ्ख् (वखि) १/१३१ गत्यर्थः (प)।

न्यूङ्खयन्ति-ऐब्रा. ५,३५; शांब्रा. २२,६; गोब्रा. २,६,८।

"उखिरिदन्तोऽनार्षः, न्यूङ्खा ओङ्काराः षोडशेत्याद्यर्थमुन्नीतः" इति तरङ्गिण्यां क्षीरस्वामिमतेन न्यूङ्खशब्द एवास्य प्रयोगविषयः, परन्तु कथमनार्ष इति न साधितम्। अमरकोशटीकायामसौ न्यूङ्खशब्दस्य व्युत्पत्तिं न दर्शितवान्। भानुजिदीक्षितस्तु-न्युङ्खयते। उखि+३/३/११८ घः। न्यूङ्ख इति दीर्घपाठे तु पृषोदरादित्वात् (६/३/१०९), यज्ञकर्मण्यजपन्यूङ्खसामसु (१/२/३४) इति निर्देशाद्वा दीर्घः"-इत्याह। मेदिनीकारोऽप्येनं ह्रस्वोकारं पपाठ—

न्युङ्खः सम्यङ् मनोज्ञे च साम्नः षट्प्रणवेषु च॥ मे. खे २।

वस्तुतोऽयं न्यूङ्खशब्दो दीर्घोकारान्तो वेदे लक्ष्यते। स्वार्थे णिच्त्वात् प्रयोजकत्वाद्वा—न्यूङ्खयतीति प्रयोग उपलभ्यते। क्षीरस्वामी उखिधातुमनार्षमाह। ततोऽपि न्यूङ्खमेव साधयितुं तं पपाठापि। एतत् सर्वं न सध्रीचीनम्, पठितेऽप्युखिधातौ दीर्घकल्पना करणीया भवत्येव। मन्ये, अतो हेतोः "उखिरनार्षः" इति स्वामिनः पूर्ववर्तिना केनचन विदुषा प्रतिपादितं वचनं स्वामिना समुद्धृतं स्यात्। अस्मन्मतेन √ऊङ्ख् (ऊखि) धातुः स्यात् समीचीनः। उखिरपि देशप्रयोगभेदात् स्यादिति वक्तुं न प्रभवामि, प्रयोगानुपलब्धेः। मेदिन्यादिपठितं प्रमाणं चेदस्त्येव।

√उच् (उच) ४/११० समवाये (प)
श
क्षी-मै-सा-च-जै-काक्-
कात-शा-हे।
समवायने—वो।
प्रसन्नतायाम्—ह्रि.।
(सेवने) वि. ब. शा.।

√वच् (वच) २/५२ परिभाषणे (प)।
√वज् (वज) १/२५० गतौ (प)।

समवायः=ऐक्यम्—क्षी।

क—ऐउक्=परिचये, अभ्यासे। अर्मे. उसनिम्=अध्ययने, अभ्यासे। गॉथि. बि-ऊहृत्स्=परिचये, अभ्यासे। लिथु. जू—उंक्स्तु, जुंक्ति—वा. पॉकर्नीः।

ग—उवोचिथ हि मघवन्–ऋ. ७,३७,३; अभ्युच्यति–मै. १,८,९। उग्रम् (उच्यति=क्रुधा सम्बध्यते। उणा. २/२८)–ऋ. १,८४,९; खि. १,११,५। हिंसायां वृद्धौ प्रभृ. वृत्तिर्द्रष्टव्या।

उग्रः शूद्रासुते क्षत्राद् रुद्रे पुंसि त्रिषूत्कटे।
स्त्री वचाक्षुद्रयोः………… ॥ (मेदि. रे, ९-१०)

+√उछ् (उछी) १/२१३ विवासे (प)
श-जै-शा-वो×
क्षी-मै-सा-च-हे।
विपाशे—काक्र-कात।
निवासे—ब्योथ-रॉथ।

√वस् (वस) १/९८९ निवासे (प)।
√उष् (उष) १/६८७ दाहे (प)।
√उज्झ् (उज्झ) ६/२५ उत्सर्गे (प)।

विवासः=विनाशः, समाप्तिः–क्षी।

क—अउएस् =द्युतौ।*उस्–, अथवा *उस्–स्, स्—स्त्।

ख—अवे. उसैति=दीप्तौ–वा. पॉकर्नीः।

ग—उच्छन्तु–ऋ. १,१२४,९; मा. ३४,४०; शौ. ३,१६,७; पै. ४,३,१,७। स्वरभेदार्थं तुदाद्यतिरिक्तो भ्वादिपाठः।

√उछ् (उछी) ६/१६ विवासे (प)। पूर्ववत्।
श
क्षी-मै-सा-च-जै-शा-हे।
विपाशे—काक्र-कात।
बन्धसमापने वर्जनेऽतिक्रमे—वो। दीप्तौ—ह्वि.।

क—,ख—,पूर्ववत्।

ग—उच्छन्ती–कौ. १,३०३; जै. १,३२,१।–नुमभावरूपं नोपलभ्यते।

√उज्झ् (उद्झ) ६/२५ उत्सर्गे (प)
श-जै-काक्र-कात-शा× क्षी-मै-सा-च-हे।
त्यागे—वो।

उज्झ् (उज्झ)६/४३ उत्सर्गे-(प)।
क्षी-मै-सा-च-हे-वो× जै-काक्र-कात-शा।
श ?

उद्+√हा (ओहाक्) ३/८ त्यागे (प)=√उज्झ्। घञर्थे कः (वा. ३/३/५८)। सोपसर्गकमिमं धातुं ज्ञात्वा 'उज्झित्य' इति दे० भा० ७, ३९, २५ प्रयोगः।

ग—उज्झता–संन्या. २, ४१; उज्झितम्–अन्न. ४, ६८; उज्झाञ्चकार–रघु. ५, ७५; उज्झति–नैष. २, २७।

ङ—√ उज्झ (सक) उत्सर्गे। उज्झइ (महा)।

छ—बुं. ख.-औंझवौ (ओंझना)=उदकुम्भे पात्रकमप्रवेश्य घटं न्युब्जीकृत्य पात्राद्यन्तरे जलपातने।

उत्+√ हा (ओहाक्) ३/८ त्यागे (प)-"घञर्थे कः" (वा. ३/३/५८)=√ उज्झ् धातुः। ननु (झयो हः ८/४/६२) पूर्वसवर्णत्वाद् उद्ध् इति भाव्यम्, उज्झ् कुत इति चेन्न, भिद्योद्ध्यौ नदे (३/१/११५) इति सूत्रेण झकारस्य धत्वनिपातनात् क्यपश्च सत्त्वाद् यथा 'उद्ध्य' इति प्रयोगो भवति 'उज्झ्य' इति भवितव्ये; तथात्रापि विपरीतं जातम्, सूत्रस्य दिङ्मात्रदर्शकत्वात्।

+√ उञ्छ् (उछि) १/२१२ उञ्छे (प) <उत्+√ चि=उच्चि—न्यासः
शा-वो×. क्षी-मै-सा-च-जै-काकृ- (पा. ४, ४, ३२)।
कात-शा-हे।

ग—उञ्छन्–मभार. ३, १५४२३; १४, २७१८। शिलानप्युञ्छतः—मनु. ३, १००; कथमुञ्छेन वर्तयेत्–वा. रा. २, २४, २। इति पादेन लिखितं प्रोञ्छति–मृच्छ. १४०, २३।

घ—√ उञ्छ् (उञ्छ) उञ्छे–धा. पा. ५२, सद्दनी. १७२; उञ्छने–धा. म. ६६; उञ्छति–विसुद्धिमग्ग ६० (=गवेसति)।

छ—√ ऊँछना (<उञ्छनम्=उच्चयनम्) कङ्कतिकया केशप्रसाधने।

√ उञ्छ् (उछि) ६/१५ उञ्छे (प) <उत्+√ चि (चिञ्) ५/५
जै-शा× क्षी-मै-सा-च-काकृ- चयने (उ)।
कात-हे-वो।

ग—पूर्वधातुवदुदाहरणानि बोध्यानि।

+√ उठ् (उठ) १/३३५ उपघाते (प) √ ऊठ् (ऊठ) १/३३८ उपघाते
शा-च-काकृ-कात× क्षी-मै-सा-जै-शा-हे-वो। (प) इत्येके–सि. कौ.।
√ रुठ् (रुठ) १/३३५ उपघाते
(प) इति दौर्गाः–क्षी।
√ लुठ् (लुठ) १/३३५ उपघाते
(प) इति दौर्गाः–क्षी।
√ उट् १/११३J गतौ (प)
काकृ।
√ उड् १/ संहतौ (प)
सौ. धा.—वो।

√उद् आघाते–सौ. धा.–वो।
√उण्ड् १/१८३ हिंसागत्योः
(प) काक्व।

नास्य धातोः प्रयोगोपलब्धिः। सम्बन्धकल्पना तु–√उट् १/११३ गतौ–काक्व।>√उठ् १/३३५ उपघाते>√उड् १/ संहतौ–वो,>√उण्ड् १/१८३–काक्व, >√उद् आघाते–वो., इति स्यात्। अत्र √उट्, √उड्, √उण्ड् धातूनां विकृतयो लभ्यन्ते। तद्यथा—

ग—उटजः (उटः=तृणपर्णादिः [देशीकोशः]। उटाज्जायते–३/२/९८ इति डः)–वा. रा. १, ४८, २२; मभार. १३, १४७। ब्रह्मोडुपेन प्रतरेत–श्वेताश्व. २, ८ (अत्र यद्यपि–डयते–डुः, उश्च डुश्च इति व्युत्पत्तिर्भवितुं शक्यते, तथापि सारल्याद् √उड् धातुरङ्गीकरणीयः)। सहितांश्चोड्रकेरालैः–मभार. २, ११७४; सपौण्ड्रोड्रान्–मभार. ३, १९, ८८। केशोण्डुक०–(√उण्ड् धातुः)–सुश्रु. १, १०१, १५; १, ३२७, १७; २, १८, ७। उण्डेरकस्रज्–याज्ञ. १, २८७।

छ—ओट (<उटः=तृणपर्णादिः)=रोधः, व्यवधानम्।

+√उध्रस् (उध्रस) ९/५४ श-च-जै-काक्व-कात-शा× (क्षी-हे)	उञ्छे (प) मै (क्षी)-मै-सा-हे-वो।	<उद्+√ह्रस् इति वागीशः। √ध्रस् (ध्रस) ९/५२ उञ्छे (प)।
√उन्द् (उन्दी) ७/२० श	क्लेदने (प) क्षी-मै-सा-च-जै-काक्व-कात-शा-हे। क्लेदे—वो।	√उन् १/२२० f संभक्तौ (प) काक्व। √उण्ड् १/१८३ हिंसागत्योः (प) काक्व।

क—उएद्=आर्द्रीकरणे, सेचने। r/n-st. उ̥एदोर्–, उ̥ओदोर्, उदेन् (इ), उद्नेस्=वारि।

ख—अवे. वैदि=जलमार्गः–वा. पॉकर्नीः।

ग—अभ्युन्दतः–ऋ. ९, ६१, ४; अभि…उनत्त–ऋ. ५, ४२, ३।

["उन्नं क्लिन्ने च सुरते स्यात्" (मेदिनी, ने २)]

√उब्ज् (उब्ज) ६/२४ श	आर्जवे (प) क्षी-मै-सा-च-जै-काक्व-कात-शा-हे-वो। शक्तौ—ह्वि.।	उद्+√जन् (जा)=√उद्ज्।

√उद्ज् (उद्ज)- सा ।
उपध्मानीयोपधः- क्षी-सा ।
आर्जवम् = स्पष्टता-क्षी ।

क—उब्=प्रेरणे, उत्तेजने, शक्तौ । लिथु. उब्यूति=प्रेरणे उत्तेजने ।

ख—उब्ज्याइते=सत्तायाम्, वृद्धौ । योग्यत्वे-वा. पॉकर्नीः ।

ग—उब्जन्तु तं सुभ्वः पर्वतासः-ऋ ६, ५२, १; इन्द्राणी रक्ष उब्जतम्-ऋ. १, २१, ५ ।

[ओजः उब्जेर्बले बलोपश्च (उ. ४/१९२)] ।

छ—वुं. ख.-औजबो (ना) = बले, शक्तिप्रदर्शने ।

√उभ् (उभ) ६/४० पूरणे (प) √उम्भ् (उम्भ) ६/४१ पूरणे (प) ।
श क्षी-मै-सा-च-काकृ-कात-शा-हे ।
पूर्तौ—वो ।
निगडे—ह्वि. ।
जै-√तुभ् (तुभ) पूरणे—जै ।

मुद्रणदोषः । उभ् इति भाव्यम् ।

ग—अरज्जौ दस्यून् समुनप्—ऋ. २, १३, ९ ।

√उम्भ् (उम्भ) ६/४१ पूरणे (प) √उभ् (उभ) ६/४० पूरणे (प) ।
श क्षी-मै-सा-च-काकृ-कात-शा-हे ।
पूर्तौ—वो ।
(जै—√तुम्भ् [तुम्भ]) पूरणे—जै ।

मुद्रणदोषः; √उम्भ् इति भाव्यम् ।

क—उएभ्=तन्तुसन्ताने । वेष्टने, योजने ।

ख—अवे. उब्दएन=ऊतम्, तन्तुसन्ततं वस्त्रादि—वा. पॉकर्नीः ।

ग—उब्धं गा येमानम्—ऋ. ४,१,१५; क्रैयादिकोऽपि—औभ्नाद् उश-मान ओजः—ऋ. ४,१९,४ । अपौम्भत्—मै. २,१,१२; काठ. ११,४; अपोम्भत्—शौ. ८,८,११; पै. १६,३०,१ ।

ङ—√उंभ (सक) पूरणे-राज. ।—'पाइअ-सद्द-महण्णवो'—ग्रन्थेऽयं देशी ख्यापितः । तन्निरस्तम् ।

६

छ—√ ऊमना = वेगात् प्रवर्तने (उमड़ना – इति हिन्दी) ।

+√ उर्द् (उर्द) १/२० माने क्रीडायां च (आ)
श-कात-वो× क्षी-मै-सा-काक्र-शा ।
मानें—च-जै ।
मानक्रीडयोश्च—हे ।
कात-वो-√ ऊर्द् (ऊर्द) माने क्रीडायां च—कात ।
मितिक्रीडास्वादे—वो ।

√ उर् गतौ – सौ. धा.—वो ।
क्+√ उर्द् = √ कुर्द् १/२१ क्रीडायामेव (आ) ।
ख्+√ उर्द् = √ खुर्द् १/२२ क्रीडायामेव (आ) ।
ग्+√ उर्द् = √ गुर्द् १/२२ क्रीडायामेव (आ) ।

मितिः = मानमिति मुख्योर्थः—क्षी ।

चकाराद् आस्वादनेऽपि इति दुर्गः—क्षी ।

चकाराद्-आस्वादनेऽपि—सा । आस्वादने—हे ।

इह मानम् = सुखम् इति सम्मतायाम्—सा २० ।

ग—तमूर्दरं न प्रणता यवेन—ऋ. २,१४,११ (ऋ. सं. २,६,१४, ५) ।

निरुक्ते—ऊर्दरं कृदरमित्यावपनस्य । ऊर्दरमुद्दीर्णं भवति, ऊर्जं दीर्णं वा-३,२० । ऊर्दर-शब्द इह मानार्थकः कुशूलादिवाचकः । अस्मादेव शब्दादयं धातुर्निष्कासितः स्यात् । ऊर्दरमुद्दीर्णं भवतीति व्युत्पत्तिदर्शनान्नूनमेष √ उर्द् मूलधातुर्नास्ति । माने उत्थापन-स्थापनाभ्यां क्रीडा भवतीति गौणः क्रीडार्थः । व्याकरणे 'उपधायां च' (पा. ८/२/७८) इति दीर्घत्वात् √ ऊर्द् । व्युत्पत्तीनां वैविध्यादस्मादपि धातोः ऊर्दर-शब्दः शक्यः साधयितुम् ।

+√ उर्व् (उर्वी) १/५६७ हिंसार्थः (प)
श-जै× क्षी-मै-सा-च ।
हिंसायाम्—काक्र-कात-शा-हे ।
हिंसे—वो ।

√ अर्व् (अर्व) १/५८० हिंसायाम् (प) ।
त्+√ उर्व् = √ तुर्व् (तुर्वी) १/५६८ हिंसायाम् (प) ।
थ्+√ उर्व् = √ थुर्व् (थुर्वी) १/५७० हिंसायाम् (प) ।
द्+√ उर्व् = √ दुर्व् (दुर्वी) १/५६९ हिंसायाम् (प)

धृ+√उर्व्=√धुर्व्
(धुर्वी) १/५७०
हिंसायाम् (प)।

क—रेउ=चूर्णने, गर्तस्य खनने, त्रोटने, दारणे। लिथु.—उर्वस्, उर्व=गह्वरम्, रन्ध्रम्—वा. पॉकर्नीः।

ग—ऊर्व इव पप्रथे-ऋ. ३,३०,१९। ऊर्वः=अग्निः (निरुक्तभाष्ये दुर्गा. ६/६)।

(१) समानमूर्वं नद्यः पृणन्ति-ऋ. २,३५,३।

(२) प्रातः सवन ऊर्वा माध्यन्दिने—ऐब्रा. ७, ३४; शाङ्खश्रौ. ७,५,२४।

√उष् (उष) १/६८७ दाहे (प)
श-जै-काकृ-शा× क्षी-मै-सा-च-वो।
(कात-हे—टीकायामेव)
वधे दहि—वो।

√वष् (वष) १/६८१
हिंसार्थः (प)।
√वस् (वस) १०/२०४ स्नेहच्छेदापहरणेषु (प)।
√उल् (उल) १/ दाहे
(प) सौ. धा.—वो।

√उष् (उषु) दाहे (प)
क्षी-मै-सा-श-च-कात-×(जै) (जै) काकृ-(टीकायामेव)
शा-हे।
(जै—√तुष्) वधे दहि—वो।

क—एउस्=दाहे। लैति. उस्तुम्=(उष्टम्) उषितम्—वा. पॉकर्नीः।

ग—ओषति-ऋ. १,१३०,८; उष्णाति-पै. ९,१६,५।

छ—√ऊकना-दाहे, तापे। "लूकैं वसन्त की ऊकन लागीं"-पद्माकरः।

+√उह् (उहिर्) १/७३० अर्दने (प)
श-च-काकृ-कात-× क्षी-मै-सा-च-जै-शा-हे।
अर्दे—वो?

√दुह् (दुहिर्) १/७३०
अर्दने (प) इति
चन्द्रदुर्गौ—क्षी।
√उष् (उष) १/६८७
दाहे (प)।

क—एउएगुह्=विकत्थने (प्रसन्नम्)। एउगुह्-, उएगुह्ः

ख—अवे.-अओग् (ज्)—(अओजैते, अओक्स्त्, अओगद्)=घोषणे, प्रकाशने—वा. पॉकर्नीः।

ग—नैशमेनो व्यपोहति—मनु. २, १०२=नाशयति (मन्वर्थ.)।

वेदे भिन्नार्थक उभयपदी च—
ओहते—ऋ. ५,४२,१०; ७,६६,१२; ७,१६,११; ५,५२,१०।
अत्यौहीत्—मै. ४,३,८।

+√ऊय् (ऊयी) १/४८० तन्तुसन्ताने (आ)
श×
क्षी-मै-सा-च-जै-काक्व-कात-शा-हे।
सेवने—वो।
√वे (वेञ्) १/९९० तन्तुसन्ताने (उ)।

अयं धातुः √वे (वेञ्) १/९९० तन्तुसन्ताने (उ) धातोः कर्मणि प्रयोग-रूपः। तस्यात्र कर्तरि संक्रान्तिर्भाति। दिवादावित्थं बाहुल्येन लभ्यन्ते निदर्शनानि।

ग—[उपोयते (वेञः कर्मणि) म. भाष्ये १.१.५. ८.११.७४]।

√ऊर्णु (ऊर्णुञ्) २/२८ आच्छादने (उ)
श
क्षी-मै-सा-च-जै-काक्व-कात-शा-हे-वो।
√वृ (वृञ्) ५/८ वरणे (उ)-वृणु (ते) > ऊर्णु।
√वृ (वृञ्) ९/१४ वरणे (उ)।

क—वूएल्=केशः, ऊर्णा-जू. पॉकर्नीः।

ग—अपोर्णुते-ऋ. १, १५६, ४; अभ्यूर्णोति-ऋ. ८, ७९,२; ऊर्णोति-शौ. १८, ४, ५९।

छ—√ओढ़ना=आच्छादने। हिन्दीशब्दसागरकारोऽस्य व्युत्पत्तिं कृतवान्-उपवेष्टन>प्रा. ओवेड्डन>ओढ़ना, इति, तन्न समीचीनम्, क्लिष्टकल्पनत्वात्।

छ—√ओड़ना-वारणे, छादने।

√ऊष् (ऊष) १/६७४ रुजायाम् (प)
श-कात-×
क्षी-मै-सा-च-जै-काक्व-शा-हे।
रोगे—वो।
√वष् (वष) १/६८१ हिंसार्थः (प)।
√उष् (उष) १/६८७ दाहे (प)।
√उष् (उष) १/२२३ रुजायाम् (प) कात।
√ऊष (ऊष) १०/३८५ क्षुरणे (प) क्षी-हे।

ग—ऊष इवैष पिस्यति-शब्रा. ९, ५, १, १७; तस्मात् पशव्यमूषरमित्याहुः-शब्रा. २, १, १, ६।

छ—√ऊकना-द्र.√उष्।

√ऊह् (ऊह) १/६४० श×	तर्के (आ) क्षी-शा-हे-वो । वितर्के—मै-सा-च-जै-काक्र-कात ।	√वह् (वह) १/ प्रापणे(उ) । √उह् (उहिर) १/७३० अर्दने (प) ।

क—ऊ॒घ्=प्रेरणे, रेखायाम्–वा. पॉकर्नीः ।

ग—(ऊहति–ऋ. ५, ३४, ३); ऊहे—ऋ. ५, ३, ९; १, १८१, ४ ?

ङ—√ऊह (सक)=तर्के, (२) विचारणायाम् । ऊहइ (विसे ८३१)

छ—√ऊढना (<ऊहनम्)=तर्के, (२) विचारणायाम्, (३) अनुमाने ।

√ऋ १/९२० श	गतिप्रापणयोः (प) क्षी-मै-सा । गतौ प्रापणे च—जै-काक्र-शा-हे-वो । प्रापणे—च-कात ।	√ऋ १/५५१ शब्दे (आ) काक्र । √ऋ १/३५१ (प) काक्र-अरति ।
काक्र–३५०. (काक्र-कात- √ऋच्छ् [ऋछ])	–(गतौ) प्रापणे–च-कात । गतौ—काक्र-कात ।	√री ९/३० गतिरेषणयोः (प)

क—एर्=अपनये, कम्पे । –स्कु(ह्)ऑ–(सं. ऋच्छति)–वा. पॉकर्नीः ।

ग—अभ्यारुः–ऋ. ३, १, ४; ऋच्छ–मा. १२, २४, का. १३, २, ७; तै. ४, २, २, २ । अर्पयति–तै. २, ६, ४, ४; मै. २, २, ३ । क. २९, ७ ।

ङ—√रि (सक) गमने । कर्मणि–अज्जए (विसे १३६९) ।

ङ—√उप्पि (सक) दाने । उप्पिउ (कप्प.) ।

छ—√अरपना* = अर्पणे, उपहारे ।

एष धातुरेषु धातुष्वनुगतः सम्प्राप्यते-√ऋक्ष्, √ऋच्, √ऋच्छ्, √ऋण्, √ऋत्, √ऋद् (वेदे), √ऋध्, √ऋन् (वोपदेवः), [√ऋप् (अर्प्–अर्पय्)] √ऋफ्, √ऋम्फ्, √ऋष्, √ऋह् ।

√ऋ ३/१६ श	गतौ (प) । क्षी-मै-सा-जै-काक्र-शा-हे-वो । प्रापणे—च-कात । गत्याम्—वो ।	पूर्ववत् । इयर्ति (निघण्टौ २/१४) गतिकर्मा ।

क—द्रष्ट. √ईर (ईर्) २/८ गतौ कम्पने च (आ)।

ग—इयर्ति वाचमरितेव नावम्-ऋ. २, ४२, १; १, ७, ८; मा ३३, ७८।

√ऋ ५/२९ हिंसायाम् (प) इत्येके- ऋणोति (निघण्टौ २/१४) गतिकर्मा।
मै-सा-च-जै-काकृ-कात- क्षी
शा× क्षी-हे।
हिंसे—वो।

क—√ऋ गतिप्रापणयोः (प) इति द्रष्टव्यो धातुः।

ग—यदीमृण्वन्ति वेधसः-ऋ. ९,७,५; अभि···ऋणोति-ऋ. १,३५,९। वेदेष्वयं गत्यर्थको भाषायां च हिंसार्थकः स्यात् परन्तु भाषाप्रयोगो न दृश्यते।

√ऋक्ष् ५/२९ हिंसायाम् (प) दुर्गस्तु—क्षी
मै-सा-श-जै-काकृ- क्षी-च-हे।
कात-शा× वधे—वो
√ऋ५/२९ हिंसायाम् (प) इत्येके—क्षी।
√ऋष् (ऋषी) ६/गतौ (प)।
√ऋभुक्ष् १/५१८ घातने (आ) काकृ।
√ऋक्ष् (ऋक्षि) ५/२९ हिंसायाम् (प)।

ग—ऋक्षः (√ऋक्ष्+अच्)=पर्वतविशेषः-इति सिद्धान्तशिरोमणिः।

ऋक्षः=भल्लूकः-मनु. १२, ६७।

ऋक्षम् (√ऋष् ६/७ गतौ+उणा. ३/६६-इति सः) = नक्षत्रम्। यथा-मनु. २,१९१।

+√ऋक्ष् (ऋक्षि) ५/२९ हिंसायाम् (प)
मै-सा-च-जै-काकृ- क्षी। पूर्ववत्।
कात-शा-हे-वो× पुरुषकारः (२४ पृष्ठे)।

√ऋच् (ऋच) ६/२३ स्तुतौ (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
तुत्याम्—वो।
दीप्तौ स्तुतौ—ह्वि.।
√अर्च् (अर्च) १/२०१ पूजायाम् (प)।
√अर्क् (अर्क) १०/१०३ स्तवने (प)

ग—आनृचुः-ऋ. ८, ५१, १०; खि ३, ३, १०; ऋच्यन्ते-ऋ. ७, ७०, ६।

√ऋच्छ् (ऋछ) ६/१७ इन्द्रियप्रलयमूर्त्तिभावयोः (प) √ऋ १/९२० गतिप्रापणयोः
श क्षी-जै-शा-हे। (प) >√ऋच्छ्।

गतीन्द्रियप्रलयमूर्त्तिभावेषु-	√ ऋष् ६/७ गतौ (प)।
मै-सा-काक्र-कात।	√ ऋच् (ऋच) ६/२३
गतौ—च-हे-ह्वि.।	स्तुतौ (प)।
मूर्त्तौ गमनमोहनयोः—वो।	ऋच्छति (निघण्टौ २/१४) गतिकर्मा।
	ऋच्छति (निघण्टौ ३/५) परिचरणकर्मा।

क—√ ऋ १/९२० धातुर्विलोकनीयः।

ग—ऋच्छतु-ऋ. १०, १६४, ५; सह वाव तामार्तिमृच्छति-ऐब्रा. २, ३१ आर्छेतां बाहुसंरम्भात् केशाकेशि रथारथि-मभार. ४, १०५६।

√ ऋज् (ऋज) १/१७३ शX	गतिस्थानार्जनोर्जनेषु (आ) क्षी-सा-हे।	√ ऋ १/९२० गतिप्रापणयोः (प)।
	गतिस्थानार्जनोपार्जनेषु—मै-सा।	√ ऋच्छ् (ऋछ) गतीन्द्रियमूर्तिभावेषु (प) मै।
	गतिस्थानोर्जनेषु—जै।	√ अर्ज् (अर्ज) १/२१९
	गतौ—च-काक्र-कात।	अर्जने (प)।
	गतिस्थैर्योर्जनार्जने—वो।	भ्+√ ऋज=√ भृज् (भृजी) १/१७४ भर्जने (प)।

क—रेगु्=परिवर्तने, आदेशे, निर्देशने, विस्तारे।

ख—एर्ग्जु=ऋजु, समीचीनम्, सरलम्, साधु—वा. पॉकर्नीः।

ग—मनुष्य ऋञ्जते गिरा-ऋ. २, २, ५; ६, १५, १; ऋज्यन्तो वहेयुः-ऋ. ६, ३७, ३; ऋञ्जतिः प्रसाधनकर्मा। ऋजुरित्यप्यस्य भवति—निरु. (६/२१)। अवार्जति-काठ. २८, १; अवार्जेयुः-तै. ७, ५, ३, २; काठ. ३३, ५; यदघमर्जति-नैष. ५, ८४।

√ ऋञ्ज् (ऋजि) १/१७४ शX	(भर्जने आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।	√ ऋ १/९२० गतिप्रापणयोः (प)।
	भृजि—वो।	√ ऋज् (ऋज) १/१७३ गतिस्थानार्जनोर्जनेषु (प)।
भर्जनम् =	पाकप्रकारः—क्षी।	

क—पूर्ववत्।

ग—निरुक्तव्याख्यातः प्रसाधनकर्मा (६/२१) √ऋञ् धातुः शब्दशस्त्वत्र दृश्यते। स गतिप्राप्तिकर्माप्यस्ति–ऋ. ४, ४८, ५; ३, ८७, ५। पाकप्रकारोऽपि सूक्ष्मदृशा प्रसाधनमेव। इदमेव प्रसाधनं भाषायां पाकप्रकारेण विकसितम्। नन्वयं पाकप्रकारो यास्केन कुतो नोल्लिखितः; निरुक्तस्य भाषाविषयत्वाभावात्। ननु पाणिनिना प्रसाधनमर्थः कुतो नोद्धृतः; पाणिनिसंगृहीतधातूनां प्रामुख्येन वेदविषयत्वाभावात् तदानीन्तनप्रचलितभाषाविषयत्वाच्च। यास्केन निरुक्तोपोद्घाते भाषासम्बन्धे प्रतिपादितम्–"अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते दमूनाः क्षेत्रसाधा इति (२/२/६)। "अथापि प्रकृतय एवैकेषु भाष्यन्ते विकृतय एकेषु। शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते। विकारमस्यार्येषु (जनपदेषु) भाषन्ते—शव इति। दातिर्लवनार्थे प्राच्येषु दात्रमुदीच्येषु (२/२/८)। इत्थं प्रचलितसंस्कृतभाषां संक्षेपेण परिचाय्यापि विषयवर्णने नैतदीयं वर्णनीयं किमपि प्रतुष्टाव, तस्य भाषाविषयत्वाभावात्। एवमेव पाणिनिनापि संक्षेपेण वैदिकधातून् निर्दिश्य जुहोत्यादौ स्वादौ च, बहवः सन्तोऽपि, वेदधातवो न विवृताः, प्राधान्येन तस्य तद्विषयत्वाभावात्। विविधप्रदेशप्रचलितसंस्कृतभाषासंगृहीतत्वादेव दृश्यन्ते धातुपाठे भूरिपाठभेदाः।

ग—पिष्टपचनार्थकम् ऋजीषं तान्त्रिकाः पठन्ति–इत्यमरकोशे क्षीरस्वामी (२, ९, ३२)। इत्ययमर्थस्तात्कालिको भाति धातोः। क्षीरतरङ्गिण्याम् ऋजीकम् इति पाठः। उणादौ तु–"अर्जेर्ऋजश्च" ४/२२ इतीषन् भवति। सिद्धान्तकौमुदीतत्त्वबोधिन्याम्–"उद्धृतरसः सोमलतायाः शेषोऽपि 'ऋजीषम्'। एतच्च 'ऋजीषिणं वृषणसश्चत श्रिये' 'आसत्यो यातु मघवाँ ऋजीषि' इत्यादिमन्त्रभाष्ये स्पष्टम्"–५४९ पृ.। तुलनीयः–ऋबीस (निरु ६/३६)–शब्दः पृथ्वीवाचकः।

√ऋण् (ऋणु) ८/४	गतौ (उ)।	√ऋन् ८/ गतौ (उ) वो।
श	क्षी-मै-सा-च-जै-कात-शा-हे-वो।	√ऋ १/९२० गतिप्रापणयोः (प)।
	दुर्गतौ—काकृ।	ऋणोति–(निघण्टौ २/१४) गतिकर्मा।
		ऋण्वति–(निघण्टौ २/१४) गतिकर्मा।

क—√ऋ १/९२० धातुर्दर्शनीयः।

ग—अयं सौवादिकः प्रपञ्चः। अभि····ऋणोति–ऋ. १, ३५, ९; भौवादिकोऽपि प्रयोगः–ऋण्वति (रिण्व् ?)–ऋ. १. १४४, ५; कौ. १, ८३; जै. १, ९, ३।

√ ऋत् (ऋत) २/१ घृणायाम् (आ) सौ. धा.—सा।
पा. सू. ३, १, २९।
च. सू. १, १, ४८।

द्रष्ट० उत्तरधातुः।

√ ऋत् (ऋत) १/२९२ घृणागतिस्पर्धनेषु (प. आ.) शा। घृणागतिस्पर्धेषु—हे। स्पर्धनैश्ययोर्घृणागत्योः—वो। √ ऋ १/९२०+क्त=ऋत >√ ऋत्। ऋतम्=उञ्छशिलम्-मनु. ४, ४-५।

ग—ऋतीयते-शब्रा. ३, ४, २, ३। अन्वर्तिता-ऋ. १०, १०९, २। ऋतनामानस्त्वनेके प्रयोगाः-ऋतयन्-ऋ. १, ११३, १२; मै. ४, १४, १५; ऋतायते-(चतुर्थी)-बृहदारण्यकोप. ३, ६, ६; मना. २, ३९।

√ ऋध् (ऋध) ४/१३२ श वृद्धौ (प) क्षी-मै-सा-च-कात-शा-हे-वो। वर्धने—जै। √ ऋ १/९२० गतिप्रापणयोः (प)। ब्+√ ऋध्=√ वृध् (वृधु) १/७५१ वृद्धौ (आ)।

काकृ-√ रुध् [रुधु] स्याल्लैपिकी त्रुटिर् ऋधुस्थाने। वृद्धौ—काकृ।

क—अल्द = वृद्धौ।-ध्-विस्तारः। स्वीडिश्-अल्द = फलानां स्थितिः (छविः); पु. आइस्. अल्दिन्=वृक्षफलम्।

ख—अवे. अरेदत्, एरदात् =वृद्धौ-वा. पॉकर्नीः।

ग—ऋध्यन्ते-साब्रा. ३, ४, ८। (कर्मणि कर्तरि वा ?)।

घ—रिज्झति (वैदि. ऋध्यते)=सफलतायाम्-संयुत्त १,१७५।

ङ—रिज्झ (अक) १-वृद्धौ (२) प्रसादे। रिज्झइ (भवि.)।

छ—√ रीझना=प्रसादे, मोहने।

√ ऋध् (ऋधु) ५/२५ श वृद्धौ (प) क्षी-मै-सा-च-कात-शा-हे-वो। पूर्ववत्। ऋध्नोति (निघण्टौ ३/५) परिचरणकर्मा।

(काकृ-√ रुध् [रुधु]) वृद्धौ—काकृ।

क—ख—पूर्ववत् ।

ग—ऋध्नोति-ऋ. १,१८,८; मनु. ९,३३२ । अर्धयन्ति-अ. वे. ७,८०,४; अर्धयति-काठ. ८,१५ । भौवादिकोऽप्ययम्-ऋधते-जैब्रा. १५६ ? ऋधद्वारायाग्नये ददाश-ऋ. ६,३,२ ।

+√ऋफ् (ऋफ) ६/२८ प×	हिंसायाम् (प) क्षी-मै-सा-च-जै-शा । कत्थनयुद्धहिंसादानेषु–हे । भर्त्सनहिंसयोः—काकृ । कत्थनयुद्धनिन्दाहिंसादानेषु-कात । दानश्लाघनिन्दाहिंसाजौ–वो ।	√ऋ१/ गतिप्रापणयोः (प) । √५/२९ हिंसायाम् (प) इत्येके-क्षी । √ऋक्ष् ५/२९ हिंसायाम् (प) दुर्गस्तु-क्षी । √ऋङ्क्ष् ५/२९ हिंसायाम् (प) । √ऋम्फ् ६/२९ हिंसायाम् (प) । √ऋह् ६/२७ कत्थनयुद्धहिंसादानेषु (प)–क्षी । √रिफ् ६/२६ कत्थनयुद्धहिंसादानेषु (प)–मै-हे ।
+√ऋम्फ् (ऋन्फ) ६/२९	हिंसायाम् (प) क्षी-मै-सा-च-जै-कात-शा-हे । भर्त्सनहिंसयोः-काकृ ।	√ऋफ् (ऋफ) ६/२८ हिंसायाम् (प) । अन्ये ध्वनयः पूर्ववज्ज्ञेयाः । √रिम्फ् १/२०२1 हिंसायाम् (प) काकृ । √रिम्फ् ६/६६ हिंसायाम् (प) हे ।
√ऋष् (ऋषी ६/७ श (काकृ-√झष् (झषी) सम्भवतो मुद्रणदोष ऋषी-स्थाने । (कात-√रिष् [रिषी])	गतौ (प) क्षी-मै-सा-च-जै-शा-हे-वो । काकृ । कात ।	√ऋ १/९२० गतिप्रापणयोः (प) । √ऋक्ष् ५/२९ हिंसायाम् (प) । √ऋष् १/५७६ b संवरणे आदाने च (उ) शा ।

√ऋश् १/ गतिस्मृत्योः (प) सौ. धा.—वो।
ऋश्यः—ऋ. ८,४,१०।
ऋश्यः-मृगविशेषः-इति शब्दरत्नावली।

क—ऐरस्-(ऐर्स्, रस्)=प्रवाहे, धावने, तथा रेस्=मार्गप्राप्त्यर्थमितस्ततो भ्रमणे। ❀ एर्स्; ऋस्; पु. उ. ज. ऊर्, ऊरोहसो; म. उ. ज.-ऊर्हन्।

ख—पु. पर्सि.-अर्स्न्=मनुष्यः, पतिः-वा. पॉकर्नीः।

ग—श्रृङ्गाभ्यां रक्ष ऋषति-अ. वे. ९,४,१७; अर्षति-ऋ. ९,३,९; मा. ३३,५५।

+√ऋहू (ऋह) ६/२७ कत्थनयुद्धहिंसादानेषु (प) क्षी। मै-सा-श-च-जै-काकृ-कात-शा-हे-वो ×

>√रिहू (रिह) ६/२७ कत्थन-युद्धहिंसादानेषु (प) इति द्रमिडाः-क्षी।
√रिफ् (रिफ) ६/२६ कत्थनयुद्धहिंसादानेषु (प) मै-हे।
√ऋफ् (ऋफ) ६/२८ हिंसायाम् (प)।
√अर्हं (अर्ह) १/७३१ पूजायाम् (प)।

क—लेगुहू-सरलम्, स्वतन्त्रम्, प्रेरणे, उत्तेजने। नासिक्यम्-लेंग् उह्।

ख—अवे. एरयन्त्=भयपूर्णम्, भयानकम्-वा. पॉकर्नीः।

ग—आनृहुः-तै. ३,२,८,३। [सपा. आनृहुः>आनृधुः<>आनशुः इति पाभे०]ऋहते-ऋ. १०,२८,९। [धातुः कृशभावे वृत्तिः। विप.=ह्रस्व-([निघ ३/२ तु. तत्रैव बृहन्तम्])। WAG (१,२१४ a) MVG (५८, १ a)<ऋघ्: √रघ् इति दे.<√रुहू इति वा√रहू (त्यागे) इति वा, GW. √रंहू (गतौ) इति च]।

+√ऋ. ९/२६ श गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।

√री ९/ गतिरेषणयोः (प)।
√रिणाति (निघण्टौ २/१४) गतिकर्मा।
√ऋ १/९२० गतिप्रापणयोः (प)।
√लृ १/५५१ Jशब्दे (आ) काकृ।

+√एज् (एजृ) १/१७६ दीप्तौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे—वो।
श×

भ्+र्+√एज्=√भ्रेज् (भ्रेजृ) १/१७७ दीप्तौ (आ)।
र्+√एज्=√रेज् (रेजृ) १/१७८ दीप्तौ (आ)।
√अस् (अस्) १/८७२ दीप्तौ (उ)।
√इन्ध् (ञिइन्धी ७/२ दीप्तौ (आ)।

(ग—एजयतेऽक्षिणी मे- भा. पु. ५,२, १४)

√एज् (एजृ) १/२३० कम्पने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। कम्पे—वो।
श

√इङ्ग् (इगि) १/१५२ गत्यर्थः (प)।
√इख् (इख) १/१४० गत्यर्थः (प)।
√ईर् (ईर) २/८ कम्पने (आ)।
√एजति (निघण्टौ २/१४) गतिकर्मा।

क—ऐज्=इतस्ततो दोलने, कम्पने–वा. पॉकर्नीः।
ग—एजति-ऋ. ५,७८,८; मा. ८, २८; का. ९,५,१; तै. ४,७, १५, १।
ङ—√एय (अक) (१) कम्पने, (२) चलने। एयइ (कप्प.)।

+√एठ् (एठ) १/२६४ च=विबाधायाम् (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। बाधने—वो।
श×
विबाधनम्=शाठ्यम्।

ह्+√एठ्=√हेठ् (हेठ) १/२६३ विबाधायाम् (आ)
ह्+√एट्=√हेट् (हेट) १/५८६ विबाधायाम् (आ) जै-शा-हे।
ह्+√एड्=√हेड् (हेड) १/१९३ विबाधायाम् (प) हे।
√एड् १/२१६ c धारणे (प) काकृ।

विपूर्वोऽयमिति स्वामिकाश्यपौ। मैत्रेयादयस्तु केवलमेवोदाजह्रुः-सा१/२६४।

[छ—√ऐंठना=(<वेष्टनम् ?)=तथा भूतायां क्रियायां जीवेषु सत्यां शाठ्यं भवति ।]

√एध् (एध) १/२ •श

वृद्धौ (आ)
क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे-वो ।

√ऋध ५/२५ वृद्धौ
(प) ।
व् + √ऋध्=वृध् (वृधु)
१/७५१ वृद्धौ (आ) ।
√इन्ध् (इन्धी) ७/२
दीप्तौ (आ) ।
√अस् (अस) २/५४
भुवि (प) ।

क—ऐस्=सत्तायाम्—वा. पॉकर्नीः ।

ग—एधते-ऋ. २,२५,५; खि. ५,१०,४; नेहासौ सुखमेधते-मनु. ४/१७०=सुखयुक्तो वर्तते (मन्वर्थ.) ।

घ—√एध् (एध) बुद्धियं-धा. पा. १६५; धा. म. २४०; वुद्धियं लाभे च-सद्द=नी. ५०४; एधति-संयुत्त १,२१७; सुत्तनिपात २९८ ।

ङ—√एह (सक)=वृद्धौ । एहंता-(दस. ९) ।

+√एव् (एवृ) १/४९७
मै-सा-श-च-जै-काक्र-
कात-शा-हे-वो ×

सेवने (आ)
क्षी ।

क्+√एव्=√केव (केवृ)
सेवने (आ); सेचने-
काक्र-कात ।
क्+ल्+√एव्=क्लेव् (क्लेवृ)
सेचने (आ) सा ।
इत्थमेव-√खेव् सेवने (आ);
सेचने-मै ।
√गेव् सेवने (आ)
च-जै । सेचने-मै ।
√ग्लेव् सेवने (आ);
सेचने-मै ।
√ग्रेव् सेचने (आ)
काक्र ।

अत्र सर्वत्र ध्वनिषु√एव् धातुरनुसंगतः । इह १/४९७ धातुस्थाने स्वामिनमतिरिच्य सर्वे√गेव् धातुं पठन्ति ।

ग—रामस्तु भरते पापं कुर्यादेव न संशयः—वा. रा. २,८,३२; एवं ते-वा. रा. २,८,३४ ।

अवधारणार्थक 'एव'-शब्दस्तु—√इ (इण्) २/३४+इण्शीभ्यां वन् (उणा. १/१५२) इति सिद्ध्यति। इवार्थक 'एवम्'-शब्दसाधने तु—

१—'ए' इत्थं भवति। टुवम् उद्गिरणे (३,२,७५) विच्।

२—√इ (इण्)+बाहुलकाद् वम् इति भानुजिदीक्षितो नैकमत्यं भजते। क्षीरस्वामी व्युत्पत्तिमेव न दर्शयति। स्वीकार एव प्रायः सेवनम् इति स्यादनेन शब्देन √एव् १/४९७ धातोः सम्बन्धः। धरणिकोशे 'एवम्'-शब्दार्थः—

एवं प्रकारोपमयोरङ्गीकारेऽवधारणे।

√एष् (एषृ) १/६१३ श×	गतौ (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो।	√इष् (इष) ४/२० गतौ (प)। √इष् (इषु) ६/७२ इच्छायाम् (प)। √ईष् (ईष) १/६०६ गति-हिंसादर्शनेषु (आ)। √इषति (निघण्टौ २/१४) गतिकर्मा।
√इष् १/	अन्वेषणे—(उ) ह्वि.।	

क—√इष् ४/२० धातुः प्रेक्षणीयः।

ग—एषति (गतौ प्रेरणे बले प्रभृ. धा. वृत्तिः) पै. ३,४०,१; ऐब्रा. १,३०; एषतु-खि. ५,२,३ ? शौ. ६,६७,३। पर्येषते भक्तम्, पर्येषमाणः-सद्ध. पुण्डरीक.-४,३४. (b.)।

घ—√एस् (एसु) सद्दनी. ९३६, ९७७ एसति [आ+√इष्-वागीशः]= अन्वेषणे-सुत्तनिपात ५९२।

+√ओख् (ओखृ) १/१२१ श×	शोषणालमर्थयोः (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। शोषणे—च। शोषालमर्थयोः—वो।	√उष् (उष) १/६८७ दाहे (प)। √उख् (उख) १/१२८ गत्यर्थः (प)। √उ शोषणे—काक्र।

अलमर्थे=भूषणे सामर्थ्ये निवारणे।

छ—ओखा*(<√ओख्=वारणे)=मिषः।

छ—ओखा (वि॰) (<√ओख्=शोषणे। पाञ्चालभाषायाम्-ओंखा= जिह्मम्, कठिनम्)=(१) रूक्षम्; शुष्कम्, (२) कठिनम्; अरालम्, (३) अचोक्षम्, (४) विरलम्।

+√ओण् (ओणृ) १/४४६ श-काकृ×	अपनयने (प) क्षी-मै-शा-च-जै-कात-शा-हे । अपसारणे—वो ।	√ऊन् (ऊन) १०/ परिहाणे (प)।

ग—ओण्यौ-(द्यावापृथिव्योर्नामधेयम्-निघण्टौ ३/३०)। [√ओण् १/४४६+सर्वधातुभ्य इन् (उ. ४/११४), कृदिकारादक्तिनः (४,१,४५ वा.)-इति ङीष्। अपनयतः स्वाश्रितानां क्लेशान् इति दुर्गाचार्यः।] अभित्यं देवं सवितारमोण्योः (वा. सं. ४,२५)। प्र ते सोतार ओण्यः-ऋ९,१६,१।

घ—ओणि [(तुलनीयः-ऋ. ९,१६,१)=सोमपात्रविशेषः।] ओणिरक्ख=निक्षेप-(=धरोहर—हि.)-संरक्षकः-विनय ३,४७, ५३।

छ—√ओड़ना-(<ओणनम् =अपनयनम्)=रोधे, वारणे।

छ—ओना=तडागादिभ्यो जलादिनिष्कासनाय वर्तनी (प्रणाली)। अस्य उद्गमनम् >ओना इति व्युत्पत्तिः सुतरामसङ्गता।

छ—बु. ख.-औंड़ा=भित्तिभेदनम्।

+√कंस् (कसि) २/१४ श	गतिशासनयोः (आ) क्षी-सा। गतिनिशानयोः—मै। गतिसंतानयोः—जै। गतौ—च-काकृ-कात। गतिशातनयोः—शा-हे। गतौ शाते च—वो।	घ—अवकंस (अवकर्ष (ति))-दीघ. १,५४। √कश् (कश) २/२४ गतिशासनयोः-(आ) सा।

ग—शतं कंसाः शतं दोग्धारः-अ.वे. १०,१०,५; ऐब्रा. ८,१०। औदुम्बरे कंसे चमसे वा-शब्रा. १४,९,३,१।

[कंसम् =(कामयते काम्यते वा अनेन (अस्मात्—क्षीरस्वामी) पातुमिति शेषः। उणा. ३/६२ इति सः)=पानभाजनम्। पित्रादिबन्धुवर्गान् अभिभूय पापात्मकं राज्यविषयादिभोगं कामयते यः। √कम् +सः=कंसः—कृष्णमातुलः। एवं व्युत्पत्तिदृशाऽयं √कंस् (कसि) धातुः "शतं कंसाः शतं दोग्धारः" अ.वे. १०, १०, ५ प्रभृतिगतकंसशब्दैर्न सम्बध्नाति।]

ङ—कंसिआ (<कंसिका) (१) तालः; (णाया. १, १७); वाद्यविशेषः (आचा. २); कंस=महाग्रहविशेषः (ठा. २, ३-पत्र, ७८)।

+√कक्(कक) १/८७ लौल्ये (आ) क्षी-मै-सा-च-जै-काक्रु-कात-शा-हे।
इच्छागर्वचापले—वो।
इच्छा=इह तृष्णा—दुर्गादासः।
शX

√कर्क्(कर्क) १/४०९c लौल्ये (आ) काकृ।
√कक्क्(कक्क) १/४०९b लौल्ये (आ) काकृ।
√कक्ख्(कक्ख) १/११९ हसने (प) मै।
√कग्॰(कगे) १/५१२ हसने (प) कात।

लौल्यम् =गर्वः, चापल्यं च—क्षी।

क—कॅक् =बुभुक्षायाम्-वा. पॉकर्नीः।

ग—ककुहासः-ऋ सं. १, ३, ३३, ३।-ककुह इति महन्नामं (निघ. ३/३)। दुर्गाचार्यः √कक्(कक्) सहने इति धातुतः 'उह'-प्रत्ययं कल्पयति, तन्न विचारसहम्, एतादृशधातोरेवासत्त्वात्। महेच्छस्तु महाशयो महान् भवत्येव। ककुहः सोम्यो रसः—ऋ. ९, ६७, ८; ककर्दवे वृषभो युक्त आसीत्-ऋ. १०, १०२, ६ (ककर्दवे=शत्रूणां हिंसनाय—सायणः)। ककजाकृता-अ.वे. ११, १०, २५; ककरघाटः-सुश्रु. २, २५१, १४; ककर०-वा. सं. २४, २०।

√कक्धातोरुपोत्तमे रेफे सति लौल्यार्थकः √कर्क् १/४०९ c काकृ-धातुर्निष्पद्यते। पुनः स एव संयोगे गुरुत्वात् ककारतां प्राप्तो रकारः पालिप्राकृतवत्-४०९ b काकृ; इत्येतेषामस्ति कश्चन विकाससम्बन्धः। हसनं चापल्यमेवाङ्गस्य-(मुखस्य) इति स एव √कक्क् धातुः काशकृत्स्नीयो लौल्यार्थकोऽन्त्ये बलाघाते सति हसनार्थकः √कक्ख् संवृत्तो मैत्रेयेण (१/११९) पठितः। इत्थमेष √कक् १/८७ वेदप्रयुक्तो धातुरेतज्जातीयकानां हसनार्थकानां समग्राणां धातूनां मूलाधारः। नन्वयं विकासो विलोमोऽपि भवितुमर्हतीति चेन्न, √घग्घ् √गग्घ् √खक्ख् √कख् इति धातूनां वेदे तदनुवर्ति साहित्ये वा प्रयोगानुपलम्भात्। √कक् धातोस्तु तथा सत्त्वात् तत एव विकास आस्थेयः।

+√कक्ख्(कक्ख) १/११९ हसने (प) मै।
क्षी-सा-श-जै-काकृ-कातX
मै-च-शा-हे।
हासे—वो।

√कक्(कक) १/८७ लौल्ये (आ)।
√कर्क् १/४०९ c लौल्ये (आ) काकृ।
√कर्क् हासे—सौ. धा.—वो।
√कक्क् १/४०९ b लौल्ये (आ) काकृ।

√कक्क् १/३२b हसने (प) कात।
√खक्ख् (खक्ख) १/१२० हसने (प) क्षी।
√खर्ख् (खर्ख) १/१२० हसने (प) क्षी।
√कग् (कगे) १/५१२ हसने (प) कात।

क—ख ख—शब्दात्मकोऽयं हसने (समीचीनतरम्—हह, हु अथवा क्स्)। अर्मे. क्सक्संक्ह; पु.च.स्ला. छोछोतति=हसने; लिथु. किक्नोति=अट्टहासे, उपहासे। गु. उ. ज. हुऑहोन् =उपहासे—वा. पॉकर्नीः।

[ग—"कक्खटं कठिनं क्रूरम्" (अ. को. ३/७६)-√कक्ख्+अटन्। हासा भवन्ति विविधाः। राक्षसादीनामट्टहासेन क्रूरताभिव्यज्यते। अतस्ते कक्खटाः कर्कशाः।]

घ—कक्खळ (<कक्खट)। कक्खळता=कठोरता—धम्मसंगणि ८५९; विभंग. ८२।

ङ—√खिंख (अक)=खिंखि-शब्दे। खिंखेइ—सुख. २, ३३।

विशेषः √खक्ख्-धातौ द्रष्टव्यः।

+√कख् (कखे) १/७७८ हसने (प)।
श× क्षी-मै-सा-च-जै-काक्-शा-हे।
हासे—वो। पूर्ववत्।
(कात√कग् [कगे]) हसने— कात।
√कख् (कख) इत्यतिरिक्तः सायणीयः पाठः—११७।

क—पूर्ववत्। लिथु. किकेन्ति, किक्नोति=अट्टहासे। लैति. चछिन्नरे; इँग्लि. कक्क्ल्—जू. पॉकर्नीः।

ग—किखिः=लोमशः-भोजीयोणादौ (स. क. २/१/१६६); त्रिका. २, ५, ७।
ग—किखिः=लोमासका, हेमोणादौ (६/२६ सू.)।
ग—किखी=अपचितपरिमाणः शृगालः—इति हरदत्तः (पदमञ्जरी २/१/६)।
शब्दानुकृतिः।

ङ—पूर्वधातुर्विलोकनीयः।

ज—किकि=ह्रेषायाम् (बं. हिन्हा)। तुलनीयः—किखिः, किखी (ग—कोष्ठे)।

+√कग् (कगे) १/७८५ नोच्यते (प)।
श-च-जै-द्रा-हे× क्षी-मै-सा-कात।
गतौ—काकृ।
क्रियासु—वो।

अस्यायमर्थ इति नोच्यते, अनेकार्थत्वात्-क्षी। 'नोच्यते' इति योऽर्थस्तत्रार्थे कगिरित्येके-क्षी। अस्यायमर्थ इति नोच्यते-मै=क्रियासामान्यमर्थ इत्यर्थः-सा। "इह शास्त्रे कगे नोच्यते" इत्येके-सा ७७९।

अयं धातुः क्रियासामान्यार्थकः सकलानर्थानभिधातुमर्हति। √कृ (डुकृञ्) धातोरप्यस्ति क्रियासामान्यार्थवाचकता-(वाक्यपदीये, उपग्रहे प्रकीर्णटीकायां १४) तदेवाभिव्यनक्ति वोपदेवः 'क्रियासु' इत्यर्थमास्थाप्य। दुर्गादासस्तु तट्टीकायां क्रियामात्रे-कगति="लोको गच्छति" इति प्रत्यपादयत् (श. क. द्रु.); काशकृत्स्नोऽपि तथा। एवं सत्यपि नैतस्य प्रयोगोपलब्धिः कापि मन्मार्गिता। कातन्त्रे एष हसनार्थकोऽपि १/५१२। नूनमेष हसनार्थकैः √कक्क् √कक्ख् √खक्ख् √गग्घ् प्रभृतिभिर्धातुभिः सम्बध्नाति तत्संक्रान्तः।

+√कङ्क् (ककि) १/९१ गत्यर्थः (आ)
श× क्षी-मै-सा-च-कात।
गतौ—जै का-काकृ-शा-हे।
व्रजने—वो।

√कक् (कक) १/८७ लौल्ये (आ)।
√कन् (कनी) १/४५४ दीप्तिकान्तिगतिषु (प)।
√कङ्क् १/४६० d चलने (आ) काकृ।
√खिङ्क् १/४१२ cc गतौ (आ) काकृ।

क—कॅक्=दहने, शुष्कतायाम् (यथा-कङ्कालः)। क्राक् (अथवा-कौंक्?), नासिक्यम्-कुंक्=शाखा-वा. पॉकर्नी:।

ग—कङ्कत०-ऋ. १,१९१,१। (कङ्क+बाहुलकादतच्), (२) अ.वे. १४,२,६८। कङ्कतान्-वा.रा. २,९१,७७=केशमार्जनानि (तिल.), कर्णाभ्यां ते कङ्कूषेभ्यः कर्ण-

शूलं विशल्यकम्-अ. वे. ९,८,२; कङ्कवाससः-वा. रा. ६,१९,६३; तरक्षवः कङ्काः-वा. रा. ३,४६,३०।

[कङ्कश्छद्मद्विजे ख्यातो लौहपृष्ठकृतान्तयोः॥ मेदि. के. १९।

=(कङ्कते=उद्गच्छति, कङ्कः=पक्षिविशेषः।)] कङ्कट-(√कङ्क्+शकाद्यटन्)-वर्मसन्धिषु-वा. रा. ५,८०,३२; कङ्कचित्-शब्रा. ६,७,२,८, कङ्का=गोर्शीर्षम्-भा. पु. ९,२४,२४; (कङ्कते=चापल्यं गच्छति या पित्राद्यादरवशात्-√कङ्क्+अच्)=उग्रसेनराजकन्या, वसुदेवानुजपत्नी-भा. पु. ९,२४,२५; गजः कङ्कणभूषणः-मभार. ३,१५७५७।

छ— { कंगल / कंग } (<कङ्कटः)=कवचः (डिंग)।
छ—कंगन, कँगना, ककना†(<कङ्कणम्)।
छ—खंख (<कङ्कः)=रिक्तम्।
छ— { कंगाल / खंक† } (<कङ्कालः) = बुभुक्षितः, दुर्बलः।

+√कच्(कच) १/१६६ श×	बन्धने (आ) क्षी-मै-सा-च-जै-काकृ-शा-हे बन्धत्विषोः—वो। शब्दे (प) -क्षी।	√कच्(कच) शब्द उदात्तेत् (प) क्षी। √खच्(खच) इति लौकिकोऽप्यस्ति-क्षी।
कात-√कञ्च्[कचि]	बन्धने—कात।	√कञ्च् (कचि) १/१६७ दीप्तिबन्धनयोः (आ)। √खच (खच)१०/३८४ बन्धने (प)।

क—कैंक्=बन्धने-वा. पॉकर्नीः।
ग—कचेषु च निगृह्यैतान्-मभार. १,४९८२; कचग्रहैः-रघु. १०;४८; १९,३१।
घ—कच (संज्ञा)-दाठावंस ४, ५१।
(छ—√कचोना=कोषणे, प्रवेशे)।
ज—√कच्-कच्=पीडायाम्, (२) ऊर्णाशणयोः साधने (शोधने)।

+√कच्(कच) १/१६७	दीप्तिबन्धनयोः (आ) इत्येके-क्षी।	√कञ्च् (कचि) दीप्तिबन्धनयोः (आ)।
मै-श-च-जै-काकृ-कात-शा-हे	क्षी-सा। बन्धत्विषोः—वो	

क—पूर्ववत्।

ग—काचानावयन्ति-शब्रा. १३,२,६,८; काचस्फटिकपात्रेषु (√कच् दीप्तौ+घञ्)-सुश्रु. १,२४०,१६।

+√कज् (कज) १/२२७ मदे (प)
मै-श-च-जैं-काक्र-कात-शा-हे-वो ×
क्षी-सा।

√खज् (खज) १/२२८ मन्थे (प)।
√गज् (गज) १/२४९ मदने, च=शब्दार्थः (प)।
√कड् (कड) १/३५५ मदे (प)।
√कण्ड् (कडि) १/३५५ मदे (प)।
√कञ्ज् १/३१३ d हिंसागत्योः (प) काक्र।
√कर्ज (कर्ज) १/२२३ व्यथने (प)।

ग—कजिङ्ग० (im Ind. कजिङ्ग०) M. Pl.N. eines volkes VP·196, N.163 (व्योथ-रॉथ)।

+√कञ्च् (कचि १/१६७ दीप्तिबन्धनयोः (आ)
श ×
क्षी-मै-सा।
दीप्तौ—च-काक्र-कात।
बन्धने दीप्तौ च—जै-शा-हे।
बन्धत्विषोः—वो।

>√कच् (कच) दीप्ति-बन्धनयोः (आ) इत्येके-क्षी।
√कन् (कनी) १/४५४ दीप्तिकान्तिषु (प)
√कञ्ज् नहे—सौ. धा.—वो।

क—केंक्=वेष्टने-वा. पॉकर्नीः।

ग—कञ्चुकोष्णीषिणस्तत्र-वा. रा. ६,९९,२३; विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीम्-अमरु. २३,।

छ—√काँछना (<कञ्चनम्)=बन्धने।
ज—√कांजु = गर्तपतने, जालबन्धे।

+√कट् (कटे) १/२९१ श	वर्षावरणयोः (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे ।	√चट् (चटे) १/२९१ वर्षावरणयोः (प) सा। √कट् (कटी) १/३१७ गतौ (प)। कृत् (कृती) ७/१० वेष्टने (प)।
	वरणे—च ।	
	वृतौ वृषि—वो ।	√कट्ट्=राशौ, (२) √भूद्वारके आवरणे-मॉनियर-विलियमः ।

क—केट्, केराट्=वेष्टने—वा. पॉकर्नीः ।

ग—काटे निबाळ्ह ऋषिरह्व दूतये-ऋ.सं. १.७,२४,६.=कूपः-निघण्टौ ३/२३ (कट्यते=आव्रियते जलार्थिभिः-दुर्गाचा.)। कट् > काट इति प्राकृतरूपम्-ब्योथ-रॉथ। वर्षासु क्लिन्नकटवत्तिष्ठन्-मभार. २,१९७३। बद्धकटाम्-वा.रा. २,६,२१=बद्धकवाटाम्। छान्दसो वर्णलोपः।-यद्वा बृहच्छदिषम्। बद्धः कटो वर्षावारको यस्यामित्यर्थात् (तिल.)। कटिश्च तस्यातिकृतप्रमाणा-मभार. ३,१००५४; कटीदेशे-मभार. १,६२९३। कटः (कटति=मदवारि वर्षति यः)=हस्तिगण्डस्थलम्-रघु. २,३७। कट्वरः, कट्वरी (उ. ३/१) > कढ़ी (हि.)—

दध्नः ससारकस्यात्र तक्रं कट्वरमुच्यते। वैद्य. (श. क. द्रु.)

कट्वराणि-सुश्रु. १,२४०, १३; कटुः (कटति=तीक्ष्णतया रसनां मुखं वावृणोति-उ. १/९)-मभार. १,७,१६; भा. पु. ३,२६,४२; कटोरा (कट्यते=वृष्यते=दीयते स्थाप्यते वा भक्ष्यद्रव्यादिकमस्याम्—√कट्+ओलच्। लस्य रत्वम्)=स्वनामख्यातपात्रम्—ब्र. वै. पु. (श. क.द्रु.)। शब्दे शब्दानुकृतिर्नामधातुः—कटकटाय्य-वा. रा. २,३५,१।=कटकटाशब्दवतः कृत्वा (तिल.)।

घ—कटकटायति=निष्पीडने, चूर्णे, नाशे-विसुद्धिमग्ग २६४।

+√कट् (कटी) १/३१७ मै-श-काकृ-कात ×	गतौ (प)। क्षी-सा-च-जै-शा-हे। गत्याम्—वो।	>√कण्ट् (कटि) गतौ-अन्ये इदितमेनमाहुः—क्षी।
(मै-कात-हे-वो-√कट् [कट]) ३१९	गतौ (प) मै। मै-कात-हे। गत्याम्—वो।	विकटो विक्रान्तगतिरित्यौपमन्यवः—(निरु. ६/३०)।

बुं. ख.—छ—√कड़ना-(<कटनम्)=गमने, निर्गमने।

ज—√काटाओ=हस्तपादक्षेपणे।

+√कठ् (कठ) १/३३१ श	कृच्छ्रजीवने (प)। क्षी-मै-सा-च-काकृ-कात-शा-हे। कृच्छ्रजीवे—जै। तङ्कने—वो।	√कट् (कटे) १/ वर्षावरणयोः (प)। √कण्ठ् (कठि) १/ शोके (आ)।

क—कर्-, द्वित्वे सति—कर्कर्=कठोरम्। केर्ट्=बन्धने, दाढर्ये-वा. पॉकर्नीः।

ग—कठिनम् (√कठ्+उणा. २/४९ इनच्)-वा. रा. २, ४०, १५; २, ५५, १७=खनित्रम् (तिल.)।

[कठमर्दः (<कठमुल्ला हि.)—(कठम् =कष्टजीवनं मृद्नाति इति √कठ+√मृद्+अण्)=शिवः इति त्रिकाण्डशेषः। महाराज-शब्दादिवदयं विपरीतार्थं भेजे हिन्द्याम्। "कठो मुनौ तदाख्यातवेदाध्येतृज्ञयोः स्वरे"-त्रिकाण्डशेषः—२, ७, २।]

छ—कठमुल्ला (<कठमर्दः ? कठम् =कष्टजीवनं मृद्नातीति, कठ+√मृद्+अण्)=शिवः।

ज—√कठुआओ=शीतकठोरतायाम्।

+√कड् (कड) १/३५५ शा-हे-वो×, श	मदे (प) इति दुर्गः-क्षी क्षी-मै-सा-च-जै-काकृ-कात।	<√कण्ड् (कडि) मदे (प)। √गड् १/ सेचने (प)। √कट् (कटे) १/ वर्षावरणयोः (प)। कटस्य = हस्तिगण्डस्थलस्य मदवर्षकत्वाल्लक्षणया कटोऽपि मदः— कट>√कड्। √कल् १/ शब्दसंख्यानयोः (आ)। √कज् (कज) १/ मदे (प)। √गज् (गज) १/ मदने (प)। √कडम्ब् १/२०६ cc मर्दने (प) काकृ।

क—केल्=उच्चैर्गमने, केला=ताडने। ड्-विस्तारः-वा. पॉकर्नीः।

[ग—कडः (>कड़ा-हि. ?) [कडति=माद्यति इति । √कड्+पचाद्यच् =मूर्खः—हलायुधः । कडम्बः=नालीशाकः (अ. को. २, ९, ३५)। कडम्बः-उ. ४/८२-इत्यम्बच् । काशकृत्स्ने-√कडम्ब् १/२०६cc मर्दने (प) । कडारः-"गडेः कड च"—दशो. ८/६५ । कलत्रम्—गडेरादेश्च कः-उ. ३/१०६ । √गड् धातोरेव सिद्धेः √गड् सेचने धातोर्गकारस्य ककारे को हेतुः ? नार्थाधारका ह्यत्र सर्वत्र व्युत्पत्तयः । मदः सेचनेऽपि वर्तते वर्षकत्वादित्यर्थसमानतापि विद्यते । पर्यन्ते, एतयोर्मिथो विकसन-सम्बन्धः सुतरां सिद्ध्यति]।

यथा कडा (काण्व-कला) अवदन्तो वाचा-शब्रा. १४, ९, २, ८ ।

छ—√अकड़ना (<आकडनम्)=गर्वे ।

छ—अकड़ (<आ+√कड्)=गर्वः, दर्पः, (२) धृष्टता, (३) आग्रहः !

+√कड् (कड) ६/१००	घसने (प)।	√कट् (कटी) १/ गतौ (प)।
च×श	(यु. मी. सं. एव)। मदे— क्षी-मै-सा-जै-काकृ-कात-शा-हे । अदने दर्पे च—वो ।	√कुड् ६/ घसने बाल्ये च (प) जै-कात-शा-हे । √कुड् ६/९७ घसने (प) काकृ । √कृड् ६/ घसने इत्येके (प) सा ।

कुटादौ फलाभावाद् यूथभ्रष्टोऽयम्–क्षी ।

कुटादिभ्योऽन्यत्र शक्यते पठितुम् । अयं भ्वादौ च । पुनः पाठफलमुञ्छति-वत्–सा ९८ । प्रयोगादर्शनात् शीनद्योर्नुम्विकल्पार्थः स्वरार्थश्च पाठो विचिकित्स्यः ।

ग—कडङ्गरीयैः (=बुसार्हैर्महिषादिभिः)–रघु. ५, ९ ।

+√कड्ड् (कड्ड) १/३५५	कार्कश्ये (प)।	√कड् (कड) १/ मदे (प) ।
श×	क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√कठ् (कठ) १/ कृच्छ्र-जीवने (प) ।
(कद्ड)····	इत्येके (यु. मी. सं. एव) ।	
√कड्ड् (कड्ड) १/३५१	अभियोगे (प) मै ।	√कल्ल् (कल्ल) १/ अशब्दे (आ) ।

छ—अकड़ना (<आकड्डनम्)=दृढीभावे, वक्रीभावे ।

छ—कड़ा=कठोरम् , कर्कशम् ।

छ—कर्रा (बुं. ख.)=कठोरम् ।

+√कण् (कण) १/४४१	शब्दार्थः (प)।	√कल (कल) १/ शब्द-संख्यानयोः (आ) ।
श×	क्षी-मै-सा-च ।	

	शब्दे—जै-काक्र-कात-शा-हे। आर्त्तस्वरे—वो।	√कल्ल (कल्ल) १/ अशब्दे (आ)। √कण् (कण) १/४४२ शब्दार्थः (प)। √अण (अण) १/ शब्दार्थः (प)। √घण् १/२०७ u शब्दे, घण्टानादे (प) काक्र। √घण् १/२०७ JJ शब्दे, घण्टानादे (प) काक्र।

ग—कणतिः शब्दाणूभावे भाष्यते ऽनुकणतीति वा–निरु. ६/३०। कण्वतमो नाम गृणाति नृणाम्–ऋ. सं. १, ४, ३, ४ (कणति=स्तोत्रलक्षणं शब्दं करोति, कण्यते स्तूयते वा–दुर्गाचार्यः)–निघ. ३/१५।

ङ—√कण (सक)=शब्दे। वक्र–कणंत–सुर. १०, २१८; वज्जा. ६६।

ङ—√कणकण=कणकणशब्दे–(आवम.)–शब्दानुकृतिः।

ङ—कणकणकण=कणकणशब्दे। कणकणकणंति–पउम. २६, ५३।

छ—कड़कड़ाना=शब्दे।

+√कण् (कण) १/७८८ श×	गतौ (प) मित्त्वम् क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो।	√कट् (कटी) १/ गतौ (प)। √कण्ट् (कटि) १/ गतौ (प)। √कन् (कनी) १/ दीप्ति-कान्तिगतिषु (प)। √कर्ब् (कर्ब) १/गतौ (प)। √कल (कल) १०/ गतौ संख्याने च (प)।

क—केल्=उच्चैर्गमने–वा. पॉकर्नीः।

ग—अकणीत्–महाभाष्ये ७,२,३. २८०[१६]; (कणति=अतिसूक्ष्मत्वं गच्छति। पचाद्यच्) कणः(=धान्यांशः)–मनु. ११,९२; कणूकयन्तीर्नृमेधः–ऋ. १०,१३२,७।

छ—कनूका (बुं. ख.)=कणिका।

+√कण्ट् (कटि) १/३१७ श-च-जै-काकृ-कात-शा×	गतौ (प)-अन्ये इदितमेनमाहुः—क्षी। क्षी-मै-सा-हे। गत्याम्—वो।	<√कट् (कटी) गतौ (प)। √कण् (कण) १/७८८ गतौ (प)। √कन् (कनी) १/ दीप्तिकान्तिगतिषु (प)। √कण्ट् १/१०० वेदनायाम् (प) काकृ। कण्टति (निघण्टौ) २/१४ गतिकर्मा।

क—स्कॅर्, कॅर्=कर्तने। स्कॅरॅ-ट् (*कृन्तक-)-सं. कण्टकः-वा. पॉकर्नीः।

ग—कण्टकः कन्तपो वा, कृन्ततेर्वा, कण्टतेर्वा स्याद् गतिकर्मणः-निरु. ९/३२; अकण्टका वृक्षाश्चौषधयश्च-अ. कौशि. ८३; कात्या. श्रौ. २२,३,२२; मृद्नन्ती कुशकण्टकान्-वा. रा. २,२७,७। कण्टकः (=सूच्यग्रम्, क्षुद्रशत्रुः)-मनु. ९,२५२; वि. पु. १,१९,३१।

ङ—कंटग (<कण्टकः)=सूच्यग्रम् (कस.); रोमोद्गमः-(गा. ६७)। सूच्यग्रभागः सर्वत्र गच्छति (प्रविशति) इत्ययं गतिकर्मा।

+√कण्ठ् (कठि) १/२६१ श	शोके (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। आध्याने—वो।	√कठ् (कठ) १/कृच्छ्रजीवने (प)। √कण्ट् (कटि) १/ गतौ (प)। √कण्ठ् (कठि) १०/ शोके (प) आधृषाद्वा। √कण्ठ् (कठि) १/१४६ गिळने (प) काकृ।

शोकः= आध्यानम्-क्षी।

आध्यानम् = उत्कण्ठापूर्वकं स्मरणम्।

ग—उत्कण्ठितुम् -वा. रा. २,५३,२। =नगरादि स्मर्तुम् (तिल.)। चेतः समुत्कण्ठते-का. प्र. १, १।

[उणादौ 'कण्ठ'-शब्दः√कण् शब्दार्थकधातुतो व्युत्पाद्यते-'कणेष्ठः' १/१०३। अयं शब्दः शोके संक्रान्तः स्यात् कालक्रमेण। शोकेऽपि क्रन्दनादिध्वनिर्भवत्येव। अत्र शोकपदेन क्रन्दनादिव्यापाराणां सूक्ष्मतमो व्यापारोऽभिप्रेयते। ध्वनौ कण्ठशब्दो यथा—

कण्ठो गले सन्निधाने ध्वनौ मदनपादपे॥ विश्वः।

९

ध्वनियन्त्रस्य बहिर्भागाभिप्रायेण होमकुण्डाद् बहिरङ्गुलिपरिमितस्थानार्थक एष जातः–"खाताद् बाह्येऽङ्गुलः कण्ठः"–इति तिथ्यादितत्त्वम् >काँठा (हि.)। गलस्य मुखसामीप्यादेष सामीप्यार्थको जातः, ध्वनियन्त्राकूतेन शब्दार्थकः, स्वराशयेन च मदनपादपार्थकः ।]

ङ—कंठ=गले (कुमा.), (२) समीपे, (३) अञ्चले (दे. २,१८)।

ङ—कंटी=उपकण्ठे, कण्ठिकायाम्, पर्वतसमीपवर्तिन्यां भूमौ (उपत्यकायाम्)–गउड. ।

छ—कठीर*(<कण्ठीरवः)=सिंहः (डिंग.)।

+√कण्ड् (कडि) १/२०८ मदे (आ)
सा×,श
क्षी-मै-च-जै-काकृ-
कात-शा-हे ।
दर्पे—वो ।

>√कड् (कड) मदे (आ)
इति दुर्गः—क्षी ।
√गण्ड् (गडि) १/वद-
नैकदेशे (प)।

√कण्ड् (कण्ड) १/२७९ मदे—सा ।

क—(स्) केल्=खण्डने (सं. कण्डुः)–वा. पॉकर्नीः ।

ग—कण्डुर्नामर्षिविशेषः–विष्णुपु. १,१५,११ ।

मदस्थानं गण्डस्थलम्। तात्स्थ्याद् गण्डोऽपि मदे। √गण्ड><√कण्ड् इति विकासः । उणादौ—कण्डु-प्रयोगः (कण्डते=शरीरं माद्यति, अस्मादुष्णशोणितत्वात्। यद्वा कण्डयति=कण्डयुक्तं करोति शरीरम्। √कण्ड्+उणा. १/३८ इति कुः)]।

छ—√कल्लाना (<कण्डनम्=ग्लेपने)=चपेटाहतिवत् सदाहपीडायाम्, (२) असह्यभावे ।

+√कण्ड (कडि) १/३५५ मदे (प)
मै-श-च-जै-
काकृ-कात×
क्षी-सा-शा-हे ।
दर्पे—वो ।

>√कड् (कड) मदे (प)
इति दुर्गः–क्षी ।
√कण्ड् १/१७७ मांसपृथुळे
(प) काकृ ।
√काण्ड् १/१७८ परिच्छेदे
(प) काकृ ।
√गण्ड् (गडि) १/३५६
वदनैकदेशे (प)।

पूर्वधातोरेवायं प्रपञ्चः। सर्वे वैयाकरणा मैत्रेयादयो नेहैकमत्यं भजन्ते। परस्मैपदाय निमित्ताय पृथक् कृतः स्यात् तदपि न हृदयावर्जकम्, उभयपदस्य विधानीयत्वात्।

√कत्थ् (कत्थ) १/३६ श्लाघायाम् (आ)
श× क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। श्लाघे—वो। विकत्थने—ह्वि.।

√कथ (कथ) १०/२९७ वाक्यप्रतिबन्धे (प)। कथ्यते>कत्थते ?–इति वागीशः। ङ-कत्थ(<कथ्य)- (ठा. ४,४-पत्र: २८७)।

नामधातुरयं प्राकृतस्वरूपः, परन्तु मूलशब्दव्युत्पत्तिरस्पष्टा-ह्वि.।

क—केत्- (?), कोत्-, कूत् =गल्पे, प्रलापे। लिथु. कतिलिन्ति= संभाषणे, प्रलापे, गल्पे–वा. पॉकर्नीः।

ग—कत्थनम्-१ योत ३०; १ संन्या २,८६। कत्थसे यच्च वीर्येण रामम्-वा. रा. ३,५५,८। कत्थयन् कत्थसे च यौ–मभार. १६, १५८; कत्थेथाः–मभार. १,५९९५; वा. रा. ६, ३६,७३;।

घ—√कत्थ् (कत्थ) सिलाघायं-धा. पा. १२८, धा. म. १८२, सद्दनी. ४१९, कत्थति–सुत्तनिपात ७८३।

√कद् (कद) १/५६५ मै-श-च-जै-काकृ-कात-शा× वैक्लव्ये (आ) इति नन्दी-क्षी। क्षी-सा-हे-वो। नाशे (वधे)–ह्वि.।

<√कन्द् (कदि) वैक्लव्ये (आ)।

क—कद्, काद् =वञ्चने, लोपे–वा. पॉकर्नीः।

ग—कदनम्–मभार. २,१,२५ =पीडनम् (नील.); वा. रा. ६,२८,२० = मर्दः। कदनम्-भा. पु. ७,९,१६ = पापम्; भा. पु. ७,२,१३ = युद्धम्। कदनम्-भूरिप्रयोगः, जटाधरश्च = मारणम् (श. क. द्रु.)।

√कन (कनी) १/४५४ दीप्तिकान्तिगतिषु (प)।
श× क्षी-मै-सा-जै-कात-शा-हे। दीप्तौ—च। व्याप्तिकान्तिगतिषु—काकृ। श्रीगतिद्युतौ—वो।

√कन् ८/१९ शोभायाम् (उ) काकृ।
√कम् (कमु) १/ कान्तौ (आ)।
√कञ्च् (कचि) १/ दीप्तिबन्धनयोः (आ)।
√चन्द् (चदि) १/ ह्लादने दीप्तौ च (प)।
√कनति, चाकनत्, कानिषत् (निघण्टौ २/६) कान्तिकर्मा।

क—केन्=पलायने, मुक्तौ, प्रक्रमे।

ख—कइन्या=कन्या, कइनी, कइनीन=कनीन-(कानीन-)-वा. पॉकर्नीः।

ग—अकानिषं पुनर्यन्-ऋ. ४,२९,९; तृतीये सवने हि कानिषः पुरोडाशम्-३,२८,५। सद्यो हि जातो वृषभः कनीनः-ऋ. ४,४८,१।

नूनमत्र√क्रम् (कमु) कान्तौ इति धातोः संक्रान्तिः। तथाहि निरुक्ते—कनीनके कन्यके। कन्या कमनीया भवति। क्वेयं नेतव्येति वा। कमनेनानीयत इति वा। कनतेर्वा स्यात् कान्तिकर्मणः-४/१५। जनिष्ट योषा पतयन् कनीनिका-ऋ. १०,४०, ९।

+√कन्द् (कदि) १/६७ शX	आह्वाने रोदने च (प) क्षी-मै-सा-कात। आह्वानरोदनयोः—जै-शा। रोदनाह्वानयोः—हे। आह्वाने—च। रोदने आह्वाने—वो।	√कद् (कद) १/वैक्लव्ये (आ)। √कन्द् (कदि) १/वैक्लव्ये (आ)। √क्रद् (क्रद) १/वैक्लव्ये (आ)। √क्रन्द् (क्रदि) १/आह्वाने रोदने च (प)। √क्लद् (क्लद) १/वैक्लव्ये (आ)। √क्लन्द् (क्लदि) १। वैक्लव्ये (आ)। √स्कन्द् (स्कन्दिर् १/गतिशोषणयोः (प)।

क—केन्=दमने, निश्चयोतने। कॉन्दॉ(<सं. कन्दः)। लिथु. कन्दुऑलस्=कन्दः, सारः, मृद्वन्तर्भागः-वा. पॉकर्नीः।

ग—[कन्दः-(कन्दति-कन्दयति=जिह्वाया वैक्लव्यं जनयति, रोदयति, वा भक्षयन्तं जनम्)=सूरणः—कन्दोऽस्त्री सूरणे शस्यमूले जलधरे पुमान्॥ मेदि. दे, ३। <काँदा (हि.)] कन्दमूलफलाशिनः-मभार. १३,७१२; प्रायः कन्दुकपातेन पतन्नार्यः पतन्नपि-कुमा. सं. ७,२९; कथास. सा. २०, २१३। गतिशोषणार्थकेन √स्कन्द् धातुनास्य सम्बन्धो ज्ञायते-कन्दु०—सुश्रु. १,२३०, १७। स्कन्देः सलोपश्च-उणा. १/१४।

घ—कन्दति-जातक ६,१६६।

ङ—कंदइ –पि. २३१।

छ√ काँदना=रोदने—सदलमिश्रप्रयोगः।

+√कन्द् (कदि) १/७६५ शजै-काकृ×	वैक्लव्ये (आ) क्षी-मै-सा-च-कात-शा-हे-वो।	>√कद् (कद) वैक्लव्ये (आ) इति नन्दी-क्षी। पूर्ववत्।

पूर्वस्यैव धातोः प्रपञ्चोऽयमात्मनेपदार्थः स्यात्।

+√कब् (कबृ) १/३७७ श×	वर्णे (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे। स्तुतौ वर्णे—वो।	√कब् १/ . वर्णे (आ) वो। क+√वृ ५/वरणे (उ)। √कर्ब् (कर्ब) १/ गतौ (प)। √कम्ब् १/ गतौ (प) वो।
जै-√कव् (कवृङ्) पवर्गादौ व्यवस्थापितोऽयं√कब् इत्येवावगन्तव्यः।	वर्णे—जै।	

वर्णनम् =वर्णः, शुक्लादिश्च-क्षी.।

क—कॅबेॅरॉ = कर्बुरम्-वा. पॉकर्नीः।

ग—(ओदनस्य) कब्रु पलीकरणाः शरोऽभ्रम्-अ. वे. ११,३,६; कबिलः (√कब्+इलच्)=कपिलवर्णः-इति भरतो द्विरूपकोशश्च (श. क. द्रु.)। शबलार्थकेन कर्बुर-(कुमा. सं. ४,२७)-शब्देनापि सम्बध्नात्ययं धातुः। √कब्, रेफोपान्त्यत्वात् √कर्ब् इति जातः।

√कम् (कमु) १/४३६ श	कान्तौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। स्पृहि—वो।	√कन् (कनी) दीप्तिकान्तिगतिषु (प)।

न कम्यमिचमाम् १/८०३z।

श-जै-शा-हे-वो×

क—का = इच्छायाम्, कम्, काम्=इच्छायाम्। लेट्टि.-कामेत्=बुभुक्षायाम्-जू. पॉकर्नीः।

ग—कामयते-ऋ. ६,७५,६; मा. २९,४३; अचीकमत-खि. ५,७,४,१६; कामयन्तु-पै. २,६२,२; कामयेत्-साब्रा. २,६,६।

घ—कामेति-थेरगाथा १,६३।

ङ—√कम (सक)=इच्छायाम्। कवकृ-कम्ममाण-दे. २, ८५। कृ-कमणीय-सुपा. ३४; २६२।

√कम्प् (कपि) १/३७२ चलने (आ)
शं-काकृ ×
क्षी-मै-सा-च-जै-
कात-शा-हे।
चाले—वो।
कम्पने—ह्वि.।

√कप् १/चलने (प)
सौ. धा.—वो।
√केप् (केपृ) १/ कम्पने
गतौ च (आ)।
√कम्प् १०/३५ c क्षान्तौ
(प) काकृ।
√कम्ब् १/ गत्याम् (प) वो।
√कम्पते (निघण्टौ २/१२)
=कुध्यतिकर्मा।

क--कम्प्=न्युब्जीभावे, कौटिल्ये। लैति. कम्पुस्=क्षेत्रम्, परिधिः। लिथु. कम्पस्=कोणः। लेट्टि.-कम्पिस्=घर्षणे; लिथु. कुम्प्ति=न्युब्जीभावे, कौटिल्ये-वा. पॉकर्नीः।

ग--कम्पते-षब्रा. ५,१२; प्रश्नोप. ५,६; हं. १८; वा. रा. २,९७,२५=चलति, आगच्छति (तिल.); कम्पति-षब्रा. ५,७; कम्पन्-पै. २,४५।

ङ--√कंप (अक)=कम्पने। वकृ-कंपंत, कंपमाण (महा; कप्प.)।

छ--√कँपना
छ--√काँपना } =चलने, कम्पने, (२) भये।

+√कर्ज् (कर्ज) १/२२३ व्यथने (प)
शं-च ×
क्षी-मै-सा-जै-कात-शा-हे।
पीडे—वो।
काकृ-√तर्ज् व्यथने—काकृ।
(तर्ज)।

√कज् (कज) १/ मदे (प)।
√खज् (खज) १/ मन्थे (प)।
√खर्ज् (खर्ज) १/ व्यथने
मार्जने च (प)।

क—क्रॆग् (ज्)-(तथा-कॆर्ग् (ज्-)?)=यातनायाम् = ?, पु. आइस्. ह्रेक्ज=यातनायाम्-जू. पॉकर्नीः।

+√कर्द् (कर्द) १/५७ कुत्सिते शब्दे (प)
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
कुत्सिते रवे—वो।

√गॄ ९/ शब्दे (प)।
√गर्द् (गर्द) १/ शब्दे (प)।
√गर्द् १/३९४ c कुत्सिते
शब्दे (आ) काकृ।
√शर्द् १/३९४ d कुत्सिते
शब्दे (आ) काकृ।

कुत्सितशब्दः =इह कौक्षः-सा।

[-कर्दनम्-(कर्दते इति । √कर्द् + ल्युट्) = उदरशब्दः—हेमचन्द्रः १४०३ । दर्कनम् > दाँकना, दलाँकना = गर्जने (बुं. ख.)। दर्कनम् > डक्कनम् > (डिक्कइ-प्रा. धा.) डाँकना = गर्जने (हि.) । दर्कनम् > दकरना > डकरना > डकारना (हि.) = उदरशब्दे । > डकराना = गर्जने ।]

ग—रसानां कर्दमा नद्यो बभूवुः-मभार. १४,२६८३; कर्दम.—कात्या. श्रौ. २५,८ ।

ङ—कद्दम (<कर्दमः) = कर्दमः-(पण्ह. १,४)-(२) देवविशेषः, नागराज-विशेषः-(भग. ६,३) ।

+√कर्ब् (कर्ब) १/४१३ शा-च× (काक्ट—√कर्व् [कर्ब])	गतौ (प) क्षी-मै-सा-जै-कात-शा-हे-वो । काक्ट ।	√कब् (कब्र) १/ वर्णे (आ) । √खर्ब् (खर्ब) १/ गतौ (प) । √गर्ब् (गर्ब) १/ गतौ (प) । √घर्ब् (घर्ब) १/ गतौ (प) । √कम्ब् (कम्ब) १/ गतौ (प) वो । √गम्ब् (गम्ब) १/ गतौ (प) वो । √घम्ब् (घम्ब) १/ गतौ (प) वो । √कम्ब् १/२०६९ मर्दने (प) काक्ट ।

(क—केर्बेरॉ = शवलम्-वा. पॉकर्नीः)

ग—कर्बुर० (कर्बति = नानावर्णतां गच्छति । √कर्ब् + उणा. १/४२ उरच् = किर्मीर०— कुमा. सं.४,२७ । (रश्मयः) सितासिताः कर्बुनीलाः कपिलाः पीतलोहिताः-याज्ञ. ३,१६६ ।

[कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः ।
कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ मेदि. रे. १२२]

कर्बूरः = नदीनिष्पावधान्यम्-राजनिर्घण्टः (श. क. द्रु.) । कर्बूरा-सुश्रु. १,४०,१२ ।

अस्य विकासक्रमः—√कब् वर्णे > √कम्ब् > √कर्ब् । उपान्ते मकार-रकारागमबाहुल्यम् । द्रष्टव्येयाताम्-√अर्ब् गतौ,√अम्ब् गतौ ।

+√कर्व् (कर्व) १/५८१ क्षी-श-जै× दर्पे (प) मै-सा-च-कात-शा-हे-वो।

(काक्ृ√ कर्व् [कर्ब] दर्पे—काक्ृ।

कर्वतीतीदित्स्वपि पठ्यते-सा ५७३।

√गर्व् (गर्व) १/ दर्पे (प)। √खर्व् (खर्व) १/ दर्पे (प)। √कॄ ६/ विक्षेपे (प)। (किरति=विक्षिपति चित्तं विषयेषु— √कॄ+उणा. १५५ वः) कर्वः=कामः। √कर्ब् (कर्ब) १/ गतौ (प)।

[कर्वुरम् (कर्वति=गर्वत्यस्मात्, यस्मिन् सति वा गर्वो भवति कर्वत्यनेन वा। √कर्व्+उणा. १/४२ उरच्)=स्वर्णम्, धुस्तूरवृक्षः-अ. को. २,९,९४।]

ग—कर्वटः (√कर्व्+अटन्)=चतुश्शतग्रामसंग्रहस्थानम् इति सार-सुन्दरी। तथाहि याज्ञवल्क्यः—२,१६७; (=देशभेदः)-मभार. २,३०,२०; कर्वरः कथितो व्याघ्रे शिवायामपि कर्वरी-मेदि. रे. १२४।

+√कल् (कल) १/४९३ श× शब्दसंख्यानयोः (आ) क्षी-मै-सा-शा-हे। संख्याने—च-काक्ृ-कात। शब्दे—च। संख्यारुतोः—वो। संख्याशब्दयोः—जै। प्रेरणे उत्पादे—ह्वि।

जै√कल्ल् (कल्लै) मुद्रणदोषः√कल् इति भाव्यम्।

√कॄ (डुकृञ्) ८/ करणे (उ)। √कण् (कण) १/ शब्दार्थः (प)। √कल् १/२४६० धारणे (प) काक्ृ। √गण (गण) १०/ संख्याने (प)। √कड् (कड) १/ मदे (प)। √गॄ ९/ शब्दे (प)।

ग—कलये (प्रे.) तैब्रा. ३,४,१६,१। कालयते-तांब्रा. ८,३,२; जैब्रा. ४६। कलाः-शांआ. ७,२१; तैआ. १०,१,२; कलयः-जैब्रा. ४७; कलम्-वा. रा. २,७१,२७=अव्यक्तम् (तिल.); कलकण्ठैः-सार. २२८ : ५।

[कला स्यान्मूलविवृद्धौ शिल्पादावंशमात्रके।
षोडशांशे च चन्द्रस्य कलनाकालमानयोः॥ मेदि. ले, ५।
कोलाहलः कलकलः (=कलादपि कलः)-अ. को. १,७,२५।]

छ—√कलक़ना*=(<कलकलः) तारस्वरे, चीत्कारे।
ज—काक्ला=सम्भाषणे, (२)तारस्वरे, (३) शब्दने।

+√कल्ल (कल्ल) १/४९४ श×	अशब्दे (आ) क्षी-हे-वो। अव्यक्ते शब्दे—मै-सा-च-काकृ-कात। अव्यक्तशब्दार्थे—हे। संख्याशब्दयोः—जै। शब्दे—शा। कूजने शब्देऽशब्दे—वो। अशब्दे=तूष्णीम्भावे—क्षी।	√कल (कल) १/ शब्दसंख्यानयोः (आ)। √कल्ल १/५४४dधारणे (प) काकृ।

नूनमयं धातुः√कल १/शब्दसंख्यानयोः(आ)-धातुतो विकासं प्राप्तः। धातोरन्त्यलकारे द्वित्वप्रवृत्तिः साधारणी। समीक्ष्यन्ताम्—√तिल १/ गतौ (प)—√तिल्ल १/ गतौ (प), √भल १/परिभाषणहिंसादानेषु(प), √भल्ल परिभाषणहिंसादानेषु (प) प्रभृतयः। √कल्ल धातुः कचित् प्रदेशविशेषेऽशब्दार्थको जातः क्षी-हे-वो-मतेन।

+√कव् (कव) १/७१९ मै-सा-श-च-जै-काकृ-कात-शा-वो×	शब्दे (प) क्षी-हे।	>√कश् (कश) शब्दे (प) इति कौशिकः—क्षी। √कु (कुङ्) १/ शब्दे (आ)। √कु २/ शब्दे (प)। √कु ६/ शब्दे (आ)। √कू (कूङ्) ६/ शब्दे (आ)। इत्येके—क्षी। √कव् १/ स्तुतौ वर्णे (आ) वो।

अयं धातुः√कु (कुङ्) १/९३७ इत्यस्यैव प्रपञ्चः क्षीरहेमाभ्यामेवाङ्गीकृतः।

+√कश् (कश) १/७१९ मै-श-च-जै-काकृ-कात-शा×	शब्दे (प) इति कौशिकः—क्षी क्षी-हे-वो। गतौ—इति कचित्पठ्यते-सा। तत् "प्रतिष्कशश्च कशेः" इत्यत्र वृत्तौ कश गति-	<√कव् (कव) शब्दे (प)। √कश् १/३७० दीप्तौ (प) काकृ। √कश् (कश) २/ गतिशासनयोः (आ)। √कंस् (कसि) २/ गतिशासनयोः (आ)।

शासनयोरित्यादादिक-स्योपादानादनार्षमिव प्रतीयते—सा ७१२।	√कस् (कस) १/ गति-शासनयोः (प) मै। √कस् (कस) २/१४ (आ)। इत्येके-क्षी।

क—केकु=नकुलः-वा. पॉकर्नीः।

ग—रथीव कशयाश्वाँ अभिक्षिपन्-ऋ. ५,८३,३। (कशति=शब्दायते ताडयति वा। ताडयत्यनया वा)=अश्वादेस्ताडनी-अ. को. २,१०,३१; मभार. १,१७७; १०। भानुजिदीक्षित आदादिकेन भौवादिकेन चोभयथा√कश् धातुना 'कशा'-शब्दं साधयति। वस्तुतो लक्ष्यं दृष्ट्वैव लक्षणे प्रवर्तन्ते लक्ष्यैकचक्षुष्काः। लक्ष्यस्थले यादृशमर्थादिकमनुभवन्ति तादृशं लक्षणस्थले निबध्नन्ति, वैयाकरणानां प्रयोगशरणत्वात्। ऋग्वेद-प्रयुक्त-कशाशब्द-निदिध्यासनेन केचन

प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन च॥ मनु. ८,२९९।

इति कशादण्डस्य शासने प्रयुज्यमानत्वात् √कश् धातोः शासनार्थकत्वं मन्वते। केचिच्च तस्यास्फालनेन शब्दत्वात्√कश् धातोः शब्दार्थकत्वमामनन्ति। एवं सत्यप्यस्य भ्वादिगणगतत्वमदादिगणगतत्वं वा तावत् सन्दिग्धं यावत् प्रयोगोपलब्धिर्न जायते, भवेन्नामायं क्वचित् प्रदेशविशेषे प्रयुक्तपूर्वोऽपि। केचन√कष् इत्यपि पठन्ति—जघ्नुर्दण्डकषांकुशैः-गोरामायणे-६,३७,४१। मैत्रेयस्तु√कस् १/७२२ इत्युल्लिलेख। इमे पाठभेदाः संस्कृतभाषाया लोकप्रियतामभिव्यञ्जन्ति।

+√कश् (कश) २/१४ क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो×	गतिशासनयोः (आ) सा। इत्येके-(छ. हृ. ले.।	<√कंस् (कसि) गतिशासनयोः (आ)। पूर्ववत्।

अन्ये तु व्याख्यान्तरेऽमुं (कसिम्) तालव्यान्तमनिदितं मन्यन्ते। तथा च "प्रतिष्कशश्च कशेः" (६/१/१५२) इत्यत्र वृत्तिः, 'कश गतिशासनयोः' इति सूत्रे सुधाकरश्च। पारायणिकैरयमिदिद् दन्त्यान्त्य उदाहारि। अन्यैस्तु "प्रतिष्कशश्च कशेः" (६/१/१५२) इति दर्शनात् तालव्यान्तः......। "घृतस्य धारा अभिचाकशीमि" इत्यत्र भट्टभास्करश्च कशेर्गतिकर्मणोर्यङ्लुकि रूपम्—सा २/१४। व्याख्याशेषः पूर्वधातौ द्रष्टव्यः।

√कष् (कष) १/६७६ श×	हिंसार्थः (प) क्षी-मै-सा-कात।	√कृ (कृञ्) ५/ हिंसायाम् (उ)।

हिंसायाम्— च-जै-काक्ठ-शा-हे । वधे-वो । कषणे, कोषणे—ह्वि. ।	√कृष् १/विलेखने (प)। √कष् १/ ६७६ आदानसंवरणयोः (उ) काक्ठ √कष्ट् १/५९७ प्रतिघाते (आ) काक्ठ । √खष् (खष) १/ हिंसार्थः (प)। √कह् १/३१६। हिंसागत्योः (प) काक्ठ । √कश् २/गतिशासनयोः (प)।

अयमुभयपदीति चतुर्भुज-जुमरौ—दुर्गादासः ।

क—कस् = कषणे, लुञ्चने-वा. पॉकर्नीः ।

ग—अपाकषन्-शौ. १०,७,२०; कषते-गोब्रा. १,३,२१; कषाम-मभार. १२, १८०, १३ = नाशयाम (नील.)। पामानं कषमाणम्-छान्दो. ४,१,८; छदहेम कषन्निवालसत्-नैषध. २,६९ ।

ङ—√कस (सक) = हिंसायाम्, (२) कोषणे, घर्षणे, (३) मालिन्ये । कसंति (पण्ण. १३)।

छ—√कसना
√किसना (बुं.ख.) } = कषणे ।

ज—√खिसाओ = क्रोधे ।

+√कस् (कस) १/७२२ क्षी-सा-श-च-जै-काक्ठ-कात-शा-हे-वो×	गतिशासनयोः (प) मै मै ।	√कसति (निघण्टौ-२/१४) गतिकर्मा । √कश् १/७१९ धातुर्द्रष्टव्यः ।

√कश् १/७१९ धातोर्व्याख्यानं पठनीयम्; √कस् (कस) २/१४ इत्यस्य च ।

√कस् (कस) १/८४५ श×	गतौ (प) क्षी-मै-सा-च-काक्ठ-कात-शा-हे-वो । गमने—जै ।	√कसति (निघण्टौ २/१४) गतिकर्मा । √कह् १/३१६। (हिंसागत्योः (प) काक्ठ ।

विकसने—ह्वि.। √कस्त् १०/४५ आमोदे (प)काकृ।

[विपूर्वोऽयं फुल्लीभावे। तथा च—फुल्लश्चैते विकसिते-अ. को. २,४,७-८।]

ग—उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु-अ. वे. ११,९,२१=विकसने। विकसन्—सुश्रु. १,२४७,१२। चकास-नलोदये २,२=शशुभे।

+√कस् (कस) २/१४	गतिशासनयोः (आ) इत्येके-क्षी।	<√कंस् (कसि) १/ गतिशासनयोः (आ)।
मै-श-च-जै-काकृ-कात-शा-हे×	क्षी-सा-वो। गतिशासनयोः-इत्यन्ये (छ. ह. ले.)। गतौ शाते च—वो।	द्र.√कश्। √कस् १/८४५ गतौ (प)।

ग—कसना-सुश्रु.२,२१६,१३; २,२९८,१०। शेषः √कश् धातौ प्रेक्ष्यः। विकस्तम् ऋ. १,१७७,२४=शाते।

छ—√कसना
छ—बुं. ख.√गँसना,√गंसाना } =दृढीकरणे, शासने।
ज—√कसाओ=दृढीकरणे।

अ+√कह् (कह) १/३१६	हिंसागत्योः (प) काकृ (छर्दने ?)	√कष् (कष) १/ हिंसार्थः (प)। √कस् (कस) १/ गतौ (प)। √कस् (कस) १/ गतिशासनयोः (आ)।

पा
णि
नी
यः

ग—कह-कह—वपं. ३१२ : ५ [लोटि मपु.]।

+√कांस् (कासि) १/६३७	दीप्तौ (आ) अन्ये-सा सा।	<√काश् (काशृ) दीप्तौ (आ)।
√कास् (कास)	अपरे—सा। इमौ धातू पल्सुले-मतेन। वस्तुत एनौ न स्तः।	

अत्र वा. ग. पल्सुले-महोदयो भ्रान्तः। तथा हि—धातुवृत्तौ १/६३७—"काशृ गतिशासनयोः-इत्यादादौ"-इति पाठे मुद्रणदोषः स्पष्टः। तत्र √कश् (कश) गतिशासनयोः इति भाव्यम्। इतोऽग्रे धातुवृत्तौ—"अन्ये दन्त्यान्त्यमिदितं पठन्ति"। वा. ग. पल्सुले-महाशयो मुद्रणदोषदुष्टं काश्टृ-धातुमभिलक्ष्य दन्त्यान्तेदितत्वेन

कासि √कांस् इति निर्णीतवान्। परन्त्वत्र भाष्यम्—कसि √कंस् इति। सोऽपि गतिशासनार्थको न तु दीप्त्यर्थकः। यतः "कस गतिशासनयोः" इत्येव पाठः शुद्धः। तस्य च दन्त्यान्तेदितकलेवरः कसि √कंस् इत्येव स्यान्न तु कासि √कांस् इति। अत्र काश्टृ दीप्तौ इति धातुव्याख्यानेऽस्य समुल्लेखस्तु ध्वनिसादृश्यदर्शनाय। ततोऽग्रे "अनिदितमित्यपरे"—इत्यनेन √कस् इति ग्राह्यम्, न तु √कास् इति। औपरिष्टौ धातू व्योथ-रॉथ-पत्सुले-मतेन। एवं ह्यनेकैः संस्कर्तृभिर्भ्रान्त्या धातूपन्यासेनोत्तरोत्तरं धातुपाठो वृद्धिं नीतः। अतो वयं निश्चेतुं न पारयामः—कियन्तो धातवः पाणिनेरिति।

√काङ्क्ष् (काक्षि) १/६५८ काङ्क्षायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। काङ्क्षणे—वो।
शा

√कन् (कनी) १/ दीप्तिकान्तिगतिषु (प)।
√कम् (कमु) १/ कान्तौ (आ)।
√जाङ्क्ष् १/८३० काङ्क्षायाम (प) काकृ।

क—कँक्=(दाहे, शुष्कतायाम्), बुभुक्षायाम्। लिथु. कंकिन्ति=यातनायाम्; कँक्ति=हानौ–जू. पॉकर्नीः।

ग—काङ्क्षति–नाद. ४२; [काङ्क्षते इति अड्या.] महा. २, ६०; गी. ५,३; १२,१७। काङ्क्षामः–वा. रा. ४,४७, १८; काङ्क्षते–मण्डलब्राह्मणोप. २,४,२; काङ्क्षे–गी. १,३२; आकाङ्क्षमाणा–वा. रा. २,६,१९; काङ्क्षन्ते–१ योत. ६१।

घ—कंखति–दीघ.१,१०६=संदेहे। कंखा (<काङ्क्षा) =सुत्तनिपात—५४१,११४९।

ज—कांकि = नयनमेकं निमील्य दर्शने।

+√काञ्च् (काचि) १/१६८ दीप्तिबन्धनयोः (आ) क्षी-मै-शा-च-जै-काकृ-सा। कात-शा-हे-वो×

√कञ्च् (कचि) १/ दीप्तिबन्धनयोः (आ)।
√कच् (कच)१/बन्धने(आ)।

ग—काञ्चनम् (काञ्चते=दीप्यते इति+ल्युः) मनु. २,२३९=स्वर्णम्।

छ—√काँछना=बन्धने।

√काश् (काशृ) १/६३९ दीप्तौ (आ) क्षी-मै-सा-च-जै-काकृ-शा-हे। द्युतौ—वो। प्रकाशने—ह्वि.।
शा-कात×

√कश् १/३७० दीप्तौ (प) काकृ—चाकश्यन्ते–शब्रा.२,३,२,१३।
√कास् (कासृ) १/ शब्दकुत्सायाम् (आ)।

√चकास् (चकासृ) २/दीप्तौ (प)।
√कास् (कासृ)१/ दीप्तौ (आ) सा।

क—क् उएकु -, क् उओकु -, उएकु स् = दर्शने, प्रकाशने।

ख—न. पर्सि. आगाह = ज्ञातम्, प्रसिद्धम्। निगाह-जू. पॉकर्नी:।

ग—आप इव काशिना संगृभीता-ऋ. ७, १०४,८; काशते-नृउ. ७,५; ससा. १,२८। वदनानि चकाशिरे-वा. रा. ३,५५,२५; प्रसुप्ता संप्रकाशते-वा. रा. ५,१०,३७।

ज—√काजि (बेड़ा) = प्रकाशने।

+√काश् (काशृ) ४/५१ दीप्तौ (आ) पूर्ववत्।
काकृ-कात ×, श क्षी-मै-सा-च-जै-शा-हे।
द्युतौ-वो।
√काश् (काश) दीप्तौ-इत्येके—क्षी।

ग—काशते-ससा. १,२८; (काश्यते इति निसा. सुपा. यनि. सुशोधः (तु. अड्या; वैतु. आन. 'प्रकाशते' इति।)

√कास् (कासृ) १/६१६ शब्दकुत्सायाम् (आ) √कश् (कश) १/ शब्दे (प)।
श क्षी-मै-सा-जै-काकृ-कात-शा-हे। √कस् (कस) १/ गति-शासनयोः (प) मै।
शब्दे—च। √कस् (कस) २/ गति-
कुशब्दे—वो। शासनयोः (आ) इत्येके-
कफे—ह्वि.। क्षी।
√कस् (कस) १/ गतौ (प)।

क—कुआस्- कुएस् = कासने-वा. पॉकर्नी:।

ग—कासते-सुश्रु. १,३८,१२; कासेत्-२,५०२,१९; श्वासकासविनाशन०-भा. पु. ३०,३०,१७। स्याच्छब्दानुकृतिः।

ङ—√कास (अक) = (१) कुशब्दने, (२) कासने, (३) कफनिष्कासने, (४) छिक्कायाम्। वकृ-कासंत, कासमाण-पण्ह. १,३-पत्र. ५४; आचा.।

ङ—√खास (अक) = कासने। खासइ (तंदु. १६)।

छ—√खाँसना = कासने।

+√कास् (कासृ) १/६३८ दीप्तौ (आ) √काशृ (काशृ) दीप्तौ
क्षी-मै-श-च-जै-काकृ- सा-कात। (आ)।
शा-हे-वो × √कास् ४/१०२ दीप्तौ (आ)
काकृ, १०५ कात।

		√चकास् (चकासृ) २/ दीप्तौ (प)।
√कि ३/१८ श-जै-काकृ-शा× चि ३/	ज्ञाने (प) क्षी-मै-सा-च-कात-हे-वो। ध्याने—ह्वि.।	√चित् (चिती) १/ संज्ञाने (प)।

ग—अचिकेत्—ऋ. १०,५१,३; काठ. ८,१०; क. ७, ६; चिकेतु—तै. ३,३,११,५।

+√किट् (किट) १/२९९ क्षी-मै-श-च-जै-काकृ-कात-शा×	त्रासे (प) मै मै-सा। उत्त्रासे—हे। कटवत् (=गत्याम्)-भयभीमयोः [च]—वो।	√किट्ट १/१२४ चूर्णे (प) काकृ। √खिट् (खिट) १/उत्त्रासे(प)

√खिट् धातोः प्रादेशिकः प्रयोगोऽयम्। चतुर्भिरेव वैयाकरणैः स्वीक्रियते।

+√किट् (किट) १/३१६ श×	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।	√कट् (कटी) १/गतौ (प) √केण् १/२१३f गतिप्रेषण-श्लेषणेषु (प) काकृ।

क—केइ (ए ?) =प्रेरणम्, उत्तेजनम्- वा. पॉकर्नीः।

ग—[किटिः- (√किट्+ इगुपधात् [उणा. ४/१०२]) =सूकरः-अ. को. २,५,२। किट्टम् (केटति(स्र)=लौहादिधात्ववयवत्वान्निर्गच्छतीति। गत्यर्था०-३,४,७२। इति क्तः। आगमशास्त्रस्यानित्यत्वान्नेट्)=मलम्-अ. को. ६,२,६५] तथा च भाव-प्रकाशे पूर्वखण्डे प्रथमे भागे-"शेषं किट्टश्च यत् तस्य" (श. क. द्रु.)।

√कित् (कित) १/९७८ श×	निवासे रोगापनयने च (प) क्षी-मै-सा-काकृ-कात। निवासे—च-जै-शा-हे। संशयेच्छावासारोग्ये—वो।	√कि ३/ज्ञाने (प)। √कित् (कित) ३/ ज्ञाने (प)। √केत् (केत) १०/ विश्रावणे (प)।
√चित् (सन्नन्तः)	ज्ञाने—ह्वि.। एवं सति कुत्वं न स्यात्।	√चित् संदेहे काकृ।

ग—अपचिकित्सति-शौ. १३,२,१५; चिकित्सतु-शौ. ६,१४१,१; पै. १६,४२,५; अचिकित्सन्—तैब्रा. ३,७,६,१२; चिकित्स्यते—अन्न. २,१; चिकित्स्यम्—योशि. ६,५९।

√कित् (कित) ३/२०	ज्ञाने (प)	√कि ३/ ज्ञाने (प)।
सा-श-जै-शा ×	क्षी-मै-च-काकृ-कात-हे।	√चित् (चिती) १/ संज्ञाने
	मतौ—वो।	(प)।
√चित्	ज्ञाने—ह्वि.।	√कित् (कित) १/ निवासे
		रोगापनयने च (प)।

ग—चिकेतति–ऋ. १,४३,३; कौ. १,४२४; जै. १,४१,६; ज्ञिकिद्धि–ऋ. ५,२२,४; तै. २,१४,४। अति····चेकिते–ऋ. १,५५,३; [कोऽत्र धातुः कतमं च तदीयं रूपमित्यत्र भवन्ति बहवो वादाः–√१ कितेर्यङि कर्मणीति सा.। २ चेर् वा चितेर् वा इत्यर्वाञ्चः प्रत्यञ्चः। यतु. २ √चि च √चित् च।] चिकितानः–ऐब्रा. ५,४; तैआ. ४,५,५ [चानशि न गुणः शित्त्वेन ङित्त्वात्; चेकितानम्—मभार. ७,२०१,६३=चेतयन्तम् (नील.)।

√चित् धातुस्वीकारे कुत्वं न स्यात्।

+√किल् (किल) ६/७४	श्वैत्यक्रीडनयोः (प)	√केल् (केल) १ / चलने
श	क्षी-मै-सा-शा-हे।	(प)।
	क्रीडने—च।	√कैल् १/२४७ गतौ (प)
	श्वैत्यक्रीडनयोः–जै-कात।	काकृ।
	शौक्ल्ये। क्रीडे—वो।	√खेल् (खेल) १/ चलने
(काकृ – √क्लिल्)	शैत्यक्रीडनयोः—काकृ।	(प)।
मुद्रणदोषः। √किल्		
इति भाव्यम्।		

ग—अनीनशत् किलासम् [केलनम्। बिदाद्यङ् ३/३/१०४। किलेन= श्वैत्येन, असति=दीप्यते।√अस्+अच् (३/१/१३४)]–अ. वे. १,२४,२; किलास-सिध्मे—अ. को. २,६,५३। किलासम् = सिध्म (>सेहुआँ–हि.) रोगः श्वेतो भवतीति धातोः श्वैत्यमर्थो घटते। किलासम्–वा. सं. ३०,२१। यद्युयुञ्जे किलास्यः–ऋ. ५,५३,१। न किल्विषादीषते वस्व आकरः–ऋ. ५,३४,४। (केलयति=क्रीडयति विषयेषु। √किल्+किलेवुक्च–उणा. १/५० इति टिषच्, वुगागमश्च)। [किल्विषं पापरोगयोः। अपराधेऽपि–मेदि. षे ३४। इत्थमेष क्रीडनेऽर्थेऽपि चरितार्थो भवति]

+√कील् (कील) १/५२४	बन्धे (प)	√कीट् (कीट) १०/वरणे (प);
श-जै ×	क्षी-च-काकृ-कात-हे-वो।	बन्धने-मै-कात।
णिचि–कीलयति–	बन्धने—मै-सा-शा।	√टीक् १०/ ८० बन्धने (प)
क्षी १/५२४		काकृ।

क—गेइ-ः गी=अङ्कुरणे, उद्भवे। पु. म. उ. ज. खिल्; म. उ. ज. किल्=पलाण्डुः। न. उ. ज. कील्-वा. पॉकर्नीः।

ग—कीलय-पी. ४२२:२; वं. ४३६:१४। कीलयेत्-शि. ६,१२९। कीलः-रापू. ४,४।

ङ—√खिल्ल (सक)=रोधे। खिल्लेमि-सुपा. १२७।

छ—√कील्ना=(१) कीलने, (२) वशीकरणे।

छ—√किल्ना=(कर्मवाच्ये प्रयोगः)।

छ—√खील्ना=(१) कीलने, (२) तृणशकलैः पुटकबन्धने।

यद्यपि भ्वादेः प्रयोगो न लभ्यते तथापि कीलशब्दसाधनाय प्रेरकक्रिया-साधुत्वाय च धातुरावश्यकः।

+√कु (कुङ्) १/९३७ शब्दे (आ) श×

क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
आर्तस्वरे—वो।

√कवते (निघण्टौ २/१४) गतिकर्मा।
√कु २/ शब्दे (प)।
√कु (कुङ्) ६/ शब्दे (आ)।
√कू (कूङ्) ६/ शब्दे (आ) इत्येके-क्षी।
√कूज् (कूज) १/ अव्यक्ते शब्दे (प)।
√कु (कुङ्) १/ गतिशोषणयोः (आ) देवराजयज्वा।

क—कॉइ-स्कॉइ=श्रवणे, प्रतीतौ। लेट्टि. कवेत्; सर्वि.-चुवति (c^u'vati)-वा. पॉकर्नीः।

ग—विश्वा रूपाणि प्रतिमुञ्चते कविः-ऋ. सं. ४,४,२४,२। अत्र निरुक्तम्-"मेधावी कविः क्रान्तदर्शनो भवति, कवतेर्वा" १२,१३-द्विधा व्युत्पत्तिं प्रस्तौति। तत्र 'कवते' इति शब्दार्थको नास्ति, पाणिनेर्धातुपाठे च 'कवते' इति गत्यर्थको नास्ति। श्रीमद्देवराजयज्वना (निघण्टौ २/१४) 'कवते=गतिकर्मा' इत्यत्र पाणिनेः √कु (कुङ्) १/गतिशोषणयोः (आ) इति धातुर्दर्शितः। एवमर्थको धातुः प्रस्तुतेषु सर्वेष्वपि धातुपाठेषु क्वापि नास्ति। देवराजेन कुतः प्रस्तुत इति रहस्यं प्रमादो वा। वेदे गत्यर्थकः=ज्ञानार्थकोऽयं कालक्रमेण लोके शब्दार्थको जातः स्यात्। ज्ञानानन्तरमुपदेशार्थं भाषणादिकं भवति। मुनयः (मननशीलाः) पश्चाद् वक्तारो जाताः। भवेन्नाम किमपि। शब्दार्थकोऽयं पाणिनेर्धातुः √कु (कुङ्) तु विकासपरम्परामच-

लम्बते—√कु २/३१ > √कु ६/१२० > √कू ६/१२० > √कूज् १/२१८ अव्यक्ते शब्दे। इमे सर्वे शब्दानुकृतिकल्पा धातवो निश्चप्रचं तदनुरूपमर्थं प्रस्तुवन्ति।

कवि-शब्दः षट्स्वर्थेषु भवति–कविर्वाल्मीकिशुक्रयोः। सूरौ काव्यकरे पुंसि स्यात् खलीने तु योषिति–मेदि., वे ४। तिङन्तरूपं नाधिगम्यते। ५/२६ निरुक्त-प्रयुक्तः शब्दकर्मा कोकूयते तौदादिकस्य √कू ६/१२० इत्यस्य यङन्तरूपम्। भौवादिकस्यादादिकस्य वा।

+√कु २/३१	शब्दे (प)	√कु (कुङ्) १/ शब्दे (आ)।
श	क्षी-मै-सा-च-जै-काकृ-	√कू (कूङ्) ६/शब्दे इत्येके-क्षी।
	कात-शा-हे।	√कव् (कव) १/ शब्दे (प)।
	आर्तस्वरे—वो।	√गु (गुङ्) १/ अव्यक्ते शब्दे (आ)।

क—कउ, काउ-केउ, केउ-, कू = शब्दे–वा. पॉकर्नीः।

ग—(कवीति–काशिका. ७,३,९५.)

न्यासे त्रयाणां √कु १/ √कु २/ √कू ६/ इत्येषां प्रयोगविषयः प्रस्तुतो लभ्यते "कवतिस्तावद् अव्यक्ते शब्दे वर्तते–'उष्ट्रः कोकूयते' इति। कुवतिरप्यार्तस्वरे–'चोकूयते वृषलः' इति=पीडित इत्यर्थः। कौतिस्तु शब्दमात्रे" (न्यासे ७/१४/६३)।

ज—कु-उ' = कासे।

√कु (कुङ्) ६/१२०	शब्दे (आ)	कोकूयते (निरुक्ते ५/२६)
श×	क्षी-मै-सा-च-जै-काकृ-	शब्दकर्मा।
	कात-शा-हे।	पूर्ववत्
	आर्तस्वरे—वो।	
√कु, √कू ६/····	रचनायाम्, चिन्तने-ह्वि.	

ग—आ वा अग्ने कुवते यजेयेति–शब्रा. ३,१,४,६।

+√कुक् (कुक)१/८८	आदाने (आ)	√कुर्क १/४१०c आदाने (आ) काकृ। (तु.—कुर्क-[तुर्की-भाषा] > कुर्की-हि.)
श×	क्षी-मै-सा-च-जै-काकृ-	√कुक्क् १/४१० b आदाने (आ) काकृ।
	कात-शा-हे-वो।	√कुङ्क् १/४१२f गतौ (आ) काकृ।
	गृहीतौ—जै।	

क—कुकु = शब्दानुकृतिरेषा। लिथु. कुकुओति; लेट्टि.-कूकुओत् = कोकिलशब्दे—वा. पॉकर्नीः।

क—म. इरि. = कूअख्-वा. पॉकर्नीः ।

ग—कोकिलः (√कुक्+उणा. १/५४ लच्) तात कूजति-वा. रा. २,५२,२ =सुकृष्णो विहगः काकः कोकिलपालकत्वात् कोकिलपदेनोक्तः (तिल.)। सर्वत आदानत्वात् स कोकिलः [कोकः (√कुक्+३/१/१३४ अच्)-अ. को. २,५७ =ईहामृगः। वृकः सर्वतो वत्सादीन् गृह्णात्येव। तथैव कुक्कुरः-(कोकते=आदत्ते, इति कुक्=यत् किमपि गृह्णन्तं जनं दृष्ट्वा, कुरति=शब्दायते-√कुर्+कः)= सारमेयः-इति राजनिर्घण्टः।]

ङ—√कुक्क-कुक्कइ (पि. १९७,४४८)।

ङ—√कोक्क-(सक)=आह्वाने। वक्त-कोक्कंत-कुमा.।

+√कुच् (कुच) १/१८१ श×	शब्दे तारे (प) क्षी-मै-सा-शा-हे। शब्दे—च। उच्चैः शब्दैः—जै। शब्दोत्तरे—काकृ-कात। तारशब्दे—वो।	√कु (कुङ्) १/ शब्दे (आ)। √खु (खुङ्) १/ शब्दे (आ)। √गु (गुङ्) १/ शब्दे (आ)। √कच् (कच) १/ शब्दे (प)।

+√कुच् (कुच) १/८४४ श×	सम्पर्चनकौटिल्यप्रतिष्टम्भ-विलेखनेषु (प)। क्षी-मै-सा-जै-काकृ-कात-शा-हे। कौटिल्ये—च। रोधपर्ककौटिल्यलेखने—वो।	√कुट् (कुट) ६/ कौटिल्ये (प)। √ककुप् च कुजतेः (=कौटिल्यार्थस्य-दुर्गा.)—निरु. ७/१२/७।

छ—√कोचना
छ—√कोंचना } =विलेखने (गोदना, गड़ाना-इति हिं.)।

छ—खोंचा (<कोचः)=पक्षिणां ग्रहणाय संसक्तप्रान्तनिर्यासको व्याधानां वेणुदण्डः।

छ—खोंच (<कोचः) त्वगुत्पाटनाघातः, (२) कीलकादिघट्टनेन वस्त्रादि-भेदः, विलेखनम्।

√कुच् (कुच) ६/८८ श — संकोचने (प) क्षी-मै-सा-च-जै काक्ृ-कात-शा-हे। संकोचे—वो। — √कुच् (कुच) १/ शब्दे तारे (प)। √कुच् (कुच) १/ सम्पर्चन-कौटिल्य... (प)।

क—कॉइ-कू—स्लॉ वे.-कुचति = कुचति।

ख—न. पर्सि. कोज़ु = कोचः-जू. पॉकर्नीः।

ग—संकुचत्यम्बुजं यथा-सुश्रु. १,३२१,८; उत्कुचतीषु रनावरज्जुपु-अ. कौशि. १५।

छ—कुचना* = संकोचने, प्रत्याहरणे।

+√कुज् (कुजु) १/१९६ शX — स्तेयकरणे (प) क्षी-मै-सा-जै-कात-शा। स्तेये-च-हे-वो। (काकृ-√कुच् [कुच]) लैपिकी स्खलतिः। √कुज् इति स्यात्। स्तेयकरणे-काकृ। — कुजय>√कुज्-वागीशः। ङ-कुजय = द्यूतकारः (सूअ. १,२,२)। √ककुप् च कुजतेः (= कौटिल्यार्थस्य-दुर्गा.) निरु. ७,१२,७ √खुच् १/५०f स्तेय-करणे (प) काकृ। √खुज् (खुजु) १/ स्तेयकरणे (प)। √गुज् १/५०c स्तेय-करणे (प) काकृ। √ग्रुच् (ग्रुच) १/ स्तेयकरणे (प)। √ग्लुच् (ग्लुच) १/ स्तेयकरणे (प)।

? ङ (कुजय = द्यूतकारः- सूअ. १,२,२) <कु+√जि।

√कुञ्च् (कुन्च) १/१८३ श-जै-काकृX सा-√कुञ्च् (कुचि) — गतिकौटिल्याल्पीभावयोः (प) क्षी (यु. मी. सं.)। कौटिल्याल्पीभावयोः-मै-सा-कात-शा-हे। कौटिल्ये—च। — √कुच् (कुच) १/ सम्पर्चन-कौटिल्य० (प)। √कुच् (कुच) ६/ संको-चने (प)।

वक्रणे तौच्छये—वो ।
अल्पीभावे—ह्वि. ।
कौटिल्याल्पीभावयोः—सा ।
गतेः कौटिल्ये द्रव्याल्पत्वे
च—क्षी. ।

क—द्रष्ट. √ कुच् ६/८८ ।

ग—कुञ्चनेन—शाण्डिल्यो. १,७,१२; योशि. १,१११; यो. १,५२; कुञ्चितम्-गरु. ५; कुञ्चमानम्-सुश्रु. २,३४,९ ।

ङ—√ कुंच (सक)=१-गमने, २-अल्पीभावे, ३-वक्रगतौ-कुमा., गउड. ।

+√ कुट् (कुट) ६/८६ श — कौटिल्ये (प) क्षी-मै-सा-च-जै-काक्ट-कास-शा-हे-वो । — √ कुच् (कुच) १/ सम्पर्चन-कौटिल्य० (प) । कुटतेर्वा स्याद् विपरीतस्य विकुटितो भवति (निरु. ६/३०) । विकुटितः=कुब्जीभूतः (कुत्सीभूतः)-दुर्गा. ।

क—द्रष्ट. √ कट् १/२९१; स्कॅल्—, कॅल्=न्युब्जीभावे, कौटिल्ये-वा. पॉकर्नीः ।

ग—पिता कुटस्य चर्षणिः-ऋ. १,४६,४=कौटिल्ये । कुटीं कृत्वा वने वसेत्-मनु. ११,७२ ।

+√ कुड् (कुड) ६/१०१ श× — बाल्ये (प) क्षी-मै-सा-काक्ट । बाहुल्ये—च । घसने बाल्ये च—जै-कात-शा-हे । बाल्येऽदने—वो । — √ कुट् (कुट) ६/ कौटिल्ये (प) । विकुटितः (=कुब्जीभूतः-दुर्गाचार्यः)-निरु. ६/३० ।

क—कॅर्त्, कॅरात्=वेष्टने । (*कृत्य)=कुड्यम्, पार्थक्यम्,-वा. पॉकर्नीः ।

ग—नियतमयं √ कुट् धातुतो विकासमाप्तः । कुड्य-(मभार. १,१४५,१०)—शब्दसाधनाय वैयाकरणाः (कुट्यां साधु । तत्र साधुः ४/४/९८ इति यत् । पृषोदरादि० ६,३,१०९.) मूले √ कुट् धातुं दर्शयन्ति । पुनररुचौ सत्यां "कुड्यते वा कुड्यम्"-इत्याह भानुजिदीक्षितः । तत्र स "कुडि (√ कुण्ड्) कार्कश्ये" इति धातु-

मुदाहरत्, तन्न समीचीनम्, कार्कश्यार्थक-कुडिधातोरभावात्। कुडति = अत्ति वज्रलेपमिष्टकादींश्चेति ण्यत्–३/१/१२ इति नो मतम्। एवमेव "कुड्मलाम्बुरुहाकारौ" मभार. ४,३९३। कुडव०–सुश्रुत. २,१७५,१५; मभार. १४,२७२२; कुडी (कुटयर्थे)– मभार. १३.६४७१; कुडिशः (=कुडयते=भक्ष्यतेऽसौ। √कुड्+बाहुलकात् शः, तत इट्)=मत्स्यविशेषः–इति राजवल्लभः। ६/३० निरुक्तेऽपि कुब्जीभूतार्थकस्य विकुटितशब्दस्य विद्यमानत्वादयं बाल्यबाहुल्यघसनार्थकः √कुट् धातुं कुतो नानुवदेत्!

+√कुण् (कुण) ६/५५ श	शब्दोपकरणयोः (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। शब्दे—च। उपकरणे शब्दे—वो। संकोचे—भानुजिदी० २,४, १२८।	√कण् (कण) १/ शब्दार्थः (प)। √क्वण् (क्वण) १/ शब्दार्थः (प)>√कुण्। √कल् (कल) १/ शब्द-संख्यानयोः (आ)। √गुण् १/२०७ III शब्दे (प) काकृ। √कुर् (कुर) ६/ शब्दे (प) काकृ। √घुर् (घुर) ६/ भीमार्थ-शब्दयोः (प)। कुणारुमिति—निरु २/२/५ √क्वण् शब्दार्थः–दुर्गाचार्यः।

क—द्रष्ट.-√कुट् ६/८६।

ग—सं पिणक् कुणारुम्–ऋ.३,३०,८; कुणीनामिव विल्वानि–मभार. ३,१२७०। कुणप०–अ. वे. ११,९,१०; कुणपे–तै. ७,२,१०,२; पुरुषकुणप०–शत्रा. ४,१,३,८; कुणपदुर्गन्ध०–मभार. १४,४८। [कुणपशब्दः√क्वण् धातुतो व्युत्पाद्यते–"क्वणेः सम्प्रसारणं च"–उणा. ३,१४३ इति कपन्। नूनमयं √क्वण् धातुना सम्बध्नाति —√क्वण् √कुण्। उपकरणार्थे तु–कोणः (वीणादि वाद्यते येन धनुराद्याकृतिना स कोणः। >√कुण्+हलश्च ३/३/१२१ इति घञ्)—अ. को. १,७,६। शब्दानुकृतिरेषः।] कोण-संघट्टितः पुनः–वा. रा. २,७१,२९—कोणः=भेर्यादिवादनदण्डः (तिल.)।

ङ—√कुणुकुण (अक.)=शीतकम्पे सति दन्तादिशब्दे। वक्रु–कुणुकुणंत–सुर. २,१०३।

छ—√कुनकुनाना (बुं. ख.)=शिशोर्निद्रात्यागलक्षणाव्यक्तध्वनौ, श्वशावकानां शीताद्यार्तारावे।

+√कुण्ट् (कुटि) १/३१९ वैकल्ये (प)
मै-श-कात×
क्षी-सा-च-जै-शा-हे-वो।
गतिवैकल्ये—काकृ।

<√कुण्ड् (कुडि) वैकल्ये।
√कुट् (कुट) ६/ कौटिल्ये (प)।
√कुट्ट् १/११७ वैकल्ये (प) काकृ।
√कुण्ठ् (कुठि) १/ ३२२ वैकल्ये (प) मै।
√क्लन्द् (क्लदि) १/ वैकल्ये (आ)।

ङ—कुंटार=म्लानम्, शुष्कम्, मलिनम्। कुंट=(१) कुब्जः, वामनः—आचार, (२)—करविकलः—(पव. ११०; निचू. ११; आचा.)।

छ—√कूँचना †=प्रमर्दने।
√कुट्>√कुण्>√कुण्ड्>√कुण्ट्>√कुण्ठ्>√कुट्ट् १/११७ काकृ।

√कुण्ठ् (कुठि) १/३२२ वैकल्ये (प) मै।
क्षी-सा-च-जै-काकृ-कात-
श-हे×
पूर्ववत्
खोटनवैकल्यालस्ये—वो।
मन्दे; मूर्खे, कुण्ठिते–ह्वि.।

इमं ह्विट्नीर्नामधातुरूपं स्वीकरोति तद्रूपानुपलब्धावपि कुन्नाम कुत आगतम्? एवमेव तेन √कुण्ट् १/३१९ प्रभृतयः सर्वे क्रियारूपविकला धातवः कुतो न स्वीकृताः यदा हि निरुक्तकारो बोधयति—अथापि प्रकृतय एवैकेषु भाष्यन्ते विकृतय एकेषु-२,२,८।

ङ—कुंठ=मन्दः, अलसः—श्रा. १६;=मूर्खः—आचा.।
छ—कुंद=कुण्ठितः।

√कुण्ठ् (कुठि) १/३३९ च=गतिप्रतिघाते (प)
श-जै×.
क्षी-मै-सा-शा।
आलस्ये, च=गतिप्रतिघाते- पूर्ववत्।
काकृ-कात-हे।
शेषणे—च।
खोटनवैकल्यालस्ये—वो।
मन्दे, मूर्खे, कुण्ठिते–ह्वि.।

क—(स्) केल्ट्=छेदने-वा. पॉकर्नीः।

ग—कुण्ठ०-सुश्रु. १,२७,१५=शस्त्र०। शराः कुण्ठधाराः-वा. रा. ३,३२,१६; [कुठारः "कुण्ठेर्नलोपश्च"-सर. कण्ठा.-२,३,४३।] अत्र√कुठ् धातुनापि भाव्यम। कालक्रमेणायमस्मिन्नेव संक्रान्तः। "आम्रं छित्त्वा कुठारेण"-वा. रा. २,३५,१४; कुठारिका-सुश्रु. १,२६,१३।

+√कुण्ड् (कुडि) १/२६७ दाहे (आ) पूर्ववत्।
शX क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो।

क—कर्=दाहे। नासिक्यम्। कुर्नो=कुण्डः, जारजातः। पु. आइस्. हानुंग्र्; पु. गॉथि. हॉर्नुग्-वा. पॉकर्नीः।

ग—कुण्डः—(>गुंडा-हि.)=जारजातः-(कुण्ड्यते=दह्यते कुलमनेन। √कुण्ड्+करणे घञ्)=पत्यौ जीवति कुण्डः स्यात्-मनु. ३,१७४; मभार. १,१२३, ६८; प्राक्षिपत् काञ्चने कुण्डे-मभार. २,१४३११।

छ—√कौरना † (<कुण्डनम्) मन्दभर्जने, मन्दपाके।

छ—कुड़मूता=कुण्डः-बुं. ख.।

छ—कोड़ा (<कुण्डम्)=अग्निसेवनस्थलम् (अलाव-हि.)। "कुण्डमग्न्यालये मानभेदे (<कुड़ौ) देवजलाशये"-मेदि. डे ४।

+√कुण्ड् (कुडि) १/३१९ वैकल्ये (प) >√कुण्ट् (कुटि) वैकल्ये (प) इति।
श-च-जै-शाX क्षी-मै-सा-काक्र-कात-हे-वो। कौशिकदुर्गौ-क्षी। पूर्ववत्।

ङ—कुंड=इक्षुनिष्पीडनार्थं वंशनिर्मितं जीर्णकाण्डम्-दे. २,३३;४,४५।

छ—√कोड़ना, √कोरना } (<कुण्डनम्=वैकल्ये=खण्डने)=भूमिखोडने (गोड़ना-हि.), अवदारणे।

√कुथ् (कुथ) ४/१० पूतिभावे (प) √क्वथ् (क्वथे) १/ निष्पाके (प)।
जै X, श क्षी-च-कान्-शा-हे। पूतीभावे—मै-सा-काक्र। पूतित्वे—वो। दौर्गन्ध्ये—ह्वि.। न शुद्धो धातुः—ह्वि.।

क—क् उअत् (हृ)=फेनेन पूरणे, फेनः-वा. पॉकर्नीः।
ग—कोथयति-सुश्रु. १,३४४,४।

कोथः (कुथ्यति=गुदं क्षिणोति। √कुथ्+कर्तरि-अच्)=गुह्यक्षयकारक-भगन्दररोगविशेषः-सुश्रु.-"तत्र क्षतनिमित्तः कोथ उपजाते"। मूत्रपुरीषकोथ०-सुश्रु. १,४१,९। स्नायुमांससिराकोथ०-सुश्रु. १,९२,४; कुथित०-सुश्रु. २,११५,३।

ङ—√कुह् (अक)=दौर्गन्ध्ये। कुहइ-भवि.।
,,√कुत्थ (सक)=दौर्गन्ध्यापादने-पव. १५८ टी.।

+√कुथ् (कुथ) ९/४२	संश्लेषणे (प) इति	<√कुन्थ् संश्लेषणे (प) सा।
क्षी-मै-श-च-जै-	दुर्गः-सा।	√कुत् आस्तृतौ—सौ. धा.
शा-हे-वो×	काकृ-कात।	—वो।
	संक्लेशे इत्येके—सा।	√कुथ् (कुथ) ४/पूतीभावे (प)।

ग—शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्-मभार. २,१८९४; कुथानां कम्बलानां च-वा. रा. ४,५०,×३४।

+√कुन्थ् (कुथि) १/४१	हिंसासंक्लेशयोः (प)	√कन्थ् १/७ d संक्लेशे (प)
श×	क्षी-जै-काकृ-कात-शा-हे।	काकृ।
	हिंसासंक्लेशनयोः-मै-सा।	√कुथ् (कुथ) ९/संक्लेशे-(प) इत्येके—सा।
	हिंसायाम्—च।	√किन्थ् १/७ f संक्लेशे (प) काकृ।
	वधे क्लेशे च—वो।	√क्रुन्थ् ९/ श्लिषि क्लिशि (प) वो।

हिंसा= प्राण्युपघातः-क्षी
संक्लेशः= बाधा-क्षी।

ग—√कुथ् ९/४२, √कुन्थ् चाभिन्नौ धातू। √कुथ्>√कुन्थ् (द्रष्ट. √अङ्क)। अतो वैयाकरणा अनेनैव कुथ-शब्दं साधयन्ति नुममकृत्वा। यथा-कुथः (कुन्थति-अशोभां क्लेशं वा। √कुन्थ्+अच् आगमशास्त्रस्यानित्यत्वान्न नुम्।) [=गजपृष्ठस्थितचित्रकम्बलम्]-मभार. २, ५१, ३६। कुथोदरी (कुथम्=हिंसात्मकमुदरं यस्याः सा)=निकुम्भदुहिता, कुम्भकर्णपौत्री-कालिकपुराणे, षोडशः अध्यायः।

ङ—कुंथु= दुःखसहनक्षमः। जिनदेवविशेषः-सम. ४३; पडि.। (२) क्षुद्रजन्तुविशेषः-उत्त. ३६; जी. १७।

छ—√कूँथना[†] * (<कुन्थनम् = संक्लेशे)
छ—√कूँखना (<कुन्थनम् = संक्लेशे)
छ—√कोंथना (<कुन्थनम् = संक्लेशे)
छ—√कूल्हना (<कुन्थनम् = संक्लेशे)
} = (१) आर्तरवे, दुःखस्वने, (२) कपोतशब्दे ।

+√कुन्थ् (कुन्थ) ९/४२ श्लेषणे (प) ।
काक्र-कात ×, श

क्षी-हे ।
संश्लेषणे—मै-सा-च ।
संक्लेशे—जै-शा ।
श्लिषि क्लिशि—वो ।

> √कुन्थ् (कुथि) श्लेषणे (प) इति दुर्गः—क्षी ।
> √कुथ् (कुथ) संश्लेषणे (प) सा ।
√क्रुन्थ् ९/ श्लिषि, क्लिशि (प)—वो ।

√कुन्थ् (कुथि) १/४१, √कुन्थ् (कुन्थ) ९/४२, √कुथ् (कुथ) ९/४२ एते धातव एकमूलका गणभेदार्थम्, अनुनासिकविकलतार्थम्, कित्ति ङित्ति नुम्भेदार्थं तत्र तत्र तथा पठिताः । उदाहरणानि पूर्ववज्ज्ञेयानि ।

√कुप् (कुप) ४/१२०	क्रोधे (प) ।
श	क्षी-मै-सा-च-जै-शा-हे ।
रोषे—काक्र-कात ।
कोपे—वो ।

कु+√पा-घञर्थे कः—(वा. ३, ३, ५८); कुपानेन क्रोधो भवति—वागीशः ।

कोपः = नेत्रलौहित्यादिहेतुश्चित्तविकारः—दुर्गादा. ।

क—कॉइ (ए) प्—,कु ऐप्,—कूप्, कुप् = धूमः, क्रोधावेगः, उत्तेजने । लैति. कुपिओ = कुप्यति (लिथु. कूपुओति) पु. च. स्लॉ. क्यपेति = उत्तेजने–जू. पॉकर्नीः ।

ग—प्रकुप्यन्ति विपर्यये–वा. रा. २, २६, ३४; दोषाः कुप्यन्ति–सुश्रु. १, २३, ८; कुप्यते–सुबा. ९ ।

घ—कुप्पति–अंगुत्तर. ३, १०१ (<कुप्यते ?)
ङ—√कुप्प (सक) = कोपे । कुप्पइ–उव. महा. ।
ङ—√कोव (सक) = दूषणे, (२) कोपने । कोवेइ–सूअनि. १२५ ।
छ—√कुपना *
छ—√कोपना *
} = कोपे ।

+√कुम्ब (कुबि) १/४२६ क्षी-श-जै-काकृ-शा ×	आच्छादने (प)। मै-कात-हे। छादने—सा-च। स्तृत्याम्—वो।	√गुप् (गुपू) १/ रक्षणे (प)। √कुम्प् (कुपि)१०/ छादने (प)। √कुम्ब् (कुबि) १०/... इति कौशिकः—क्षी। √कुम्भ् (कुभि) १०/ छादने (प) अपरे—सा। √कुभ् १/३६२g धारणे (प) काकृ। √कुम्भ् १/३६१c गर्वे (प) काकृ। √कूम्ब् १/२०६bb मर्दने (प) काकृ।

ग—तैत्तिरीयसंहितायाम्-"उदीचीनकुम्बां शम्याम्"। कुम्बं चाधिनिध्मसि-अ. वे. ६, १३८, ३।

+√कुर् (कुर) ६/६१ श×	शब्दे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√कु (कुङ्) १/ शब्दे (आ)। √कुण् (कुण) ६/ शब्दोपकरणयोः (प)। √कण् (कण) १/ शब्दार्थः (प)। √क्वण् (क्वण) १/ शब्दार्थः (प)। √कल् (कल) १/ शब्द-संख्यानयोः (आ)। √खु (खुङ्) १/ शब्दे (आ)। √खुण् १/२०७J शब्दे (प) काकृ। √गुण् १/२०७m शब्दे (प) काकृ। √घुर् (घुर) ६/ भीमार्थ-शब्दयोः (प)।

क—कॉइ=विश्लेषणे, शकले–वा. पॉकर्नीः ।

ग—(कुर्यते । √कुर्+उणा.५/३५ वुन) कुररः–मभार. ३, ११५७९ । (कुरति–क्षी । उणादौ तु √कु (ङ्) शब्दे–कुवः क्ररन् ३, १३३)। एतेनापि सिध्यति √कु धातुतोऽस्य विकासः । कुररीमिवार्त्ताम्–वा. रा. ४, १८, ३२ । कुरीरमस्य शीर्षणि–अ. वे. ६, १३८, ३; शब्दानुकृतिरेष धातुः ।

ङ—कुरर=पक्षी, उत्क्रोशः–पण्ह. १, १; उप. १०२६ ।

ङ—√कुरकुर
ङ—√कुरुकुरु } =कुरकुरशब्दे, प्रलापे । कुरुकुराअर्सि–पि. ५५८ ।

ङ—कुरुल=शब्दे, काकरवे । कुरुलहि–भवि. ।

छ—√कुरलना*=खगकलरवे ।

इत्थमेष धातुः √कु इत्यतो रलयोर्विहितयोः सतोर्विकासमाप्तः शब्दाधिक्यदर्शनाय क्वचिद् द्वित्वमप्यनुवदति–√कुरकुर, √कुरुकुरुप्रभृति । ककारं प्रत्याघाते सत्येष हिन्द्यां जायते—

छ—√खुरखुराना=(१) खुरखुरशब्दे, (२)—गलनलिकायां कफसत्त्वाद् घर्घरशब्दे ।

√कुर्द् (कुर्द) १/२१ शX

क्रीडायामेव (आ) । क्षी-मै-सा-काकृ-कात । उपाध्यायास्तु गुदक्रीडायाम्—क्षी । गुदक्रीडा=गुदविहार इति चरके—सा । क्रीडायाम्—च-जै-शा-हे । गुदक्रीडे क्रीडे—वो ।

√उर्द् (उर्द) १/ माने क्रीडायां च (आ) ।
√खुर्द् (खुर्द) १/ क्रीडायामेव (आ) ।
√गुद् (गुद) १/ क्रीडायामेव (आ) ।
√गुध् (गुध) १/ क्रीडायामेव (आ) ।
√गुर्द् (गुर्द) १/ क्रीडायामेव (आ) ।
√घुर्द् (घुर्द) १/३९०d क्रीडायामेव (आ) काकृ ।
√स्कुन्द् (स्कुदि) १/ आप्रवणे (आ) ।

क्रीडानियमोऽत्र धातूनामनेकार्थत्वे लिङ्गम्—क्षी ।

क—(स्) क्रे-द् तथा (स्) केर्द्—ःलैति. कर्दो=परिवर्तने, भ्रमणे । पु. उ. ज. स्केर्दो=उपर्यधो भ्रमणे । म. इरिश्–केइर्द्=लङ्घने—जू. पॉकर्नीः ।

ग—कूर्दः—आब्रा. १,४४८; बलः पृथुश्रीः स चुकूर्द रामः—हरिवंश. ८३९८; कूर्दमान०—८३९९। कूर्दन्ति—मभार. ६,३,३४=क्रीडन्ति (नील.)। चुकूर्द-मभार. १,८९,१६=जगौ। √कुर्द् धातुरत्र गानार्थः (नील.)। क्रीडानियमोऽत्र धातूनामनेकार्थत्वे लिङ्गम्"—क्षी।

छ—√कूदना (<कूर्दनम्)=उत्प्लवने। √'कूँदना' इति तु (<स्कुन्दनम्=उत्प्लवने √स्कुन्द् धातुतः।

+√कुड् (कुड) १/८२६ श×	संस्त्याने बन्धुषु च (प) क्षी-मै-सा-कात। संस्त्याने—च। संस्त्यानसन्तानयोः—जै। बन्धुसंस्त्यानयोः—शा-हे। संख्याने—काकृ। (लैपिकी त्रुटिः) 'संस्त्याने' इति स्यात्। बन्धुसंहत्योः—वो।	√कल् (कल) १/४९३ शब्दसंख्यानयोः (आ)। √कुल् (कुल) १/२३७a आवरणे (प) काकृ। कुलं कुष्णातेर्विकुपितं भवति-निरु. ६,२२,४। √कूल् (कूल) १/ आवरणे (प)। √कोल् १/२३७b आवरणे (प) काकृ। √कोल् १/२५२a गति-प्रतीघाते (प) काकृ। √कौल् १/२४७h गतौ (प) काकृ।

संस्त्यानम्= सङ्घातः—क्षी।

क—कु उएल्=कुलम्, गणः—वा. पॉकर्नी।

ग—कुले वसन्ति—शब्रा. २,१,४,४; न कुलम्—वा. रा. २,३९,२३=प्रशस्तम् (तिल.) कुलस्थ०—मभार. १३, ५४६८; कुलिन्द० मभार. ०,५९०; आकुलेन—पै. ११,७,३। कुले कुले—वा. रा. २,८२,३२=गृहे गृहे (तिल.); कुलायेऽधिकुलायं कोशे कोशः समुब्जितः—अ. वे. ९,३,२०; कुलिश इति वज्रनाम कु (कु) लशातनो भवति–निरु. ६,१७,११; कुल्माषाः कुलेषु सीदन्ति—निरु. १,४,१४; कुल्या (निघ. १/१३) कुले=पर्वते भवा—४,४,११० यद् इति देवराजयज्वा।

ङ—कुल=कुटुम्बः—उप. ६,७७।

+√कुश् (कुश) ४/१०५ मै-श-च-जै×	श्लेषणे (प) इति दुर्गः- क्षी। क्षी-सा-काकृ-कात-शा-हे।	<√कुस् (कुस) श्लेषणे (प)। √कुशूल (कुशूल) १०/

श्लिषि—वो । क्रीडायाम् (प) इत्येके-मै ।

√कुन्थ् (कुन्थ) ९/ श्लेषणे (प)।

कुशिकः—क्रोशतेः शब्द-कर्मणः । क्रंशतेर्वा स्यात् प्रकाशयतिकर्मणः साधु-विक्रोशयितार्थानामिति वा—निरु. २,२५,१ ।

क—(स्) कॉइ=आच्छादने, आश्रये । कण्ठ्यविस्तारः—(स्) कॉइ—कु-: वा. पॉकर्नीः ।

ग—कुशः (कु=पापं श्यति नाशयति । कु+√शो+डः। यद्वा—कौ=भूमौ शेते=राजते, शोभते । यद्वा-कुश्यति । √कुश्+३/१/१३५ कः)—शब्रा. ३,१,२,१६; कोशः (कुश्यते=संश्लिष्यते । अकर्तरि च कारके ३/३/१९ इत्यधिकरणादौ घञ्)= आवरणविशेषः—इति भा. पु. २,१,२४ ।

छ—√खोंसना (<कोशनम्=श्लेषे)=कस्यचन वस्तुनः क्वचित् स्थिरी-करणाय कस्मिंश्चिदन्यस्मिन् वस्तुनि तदीपदंशप्रवेशने, श्लेषणे ।

√कुष् (कुष) ९/४६ श | निष्कर्षे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । | √कृष् (कृष) १/ विलेखने (प)। √कुच् (कुच) १/ सम्पर्चन... विलेखनेषु (प)।

निष्कर्षः= इयत्तापरिच्छेदः—दुर्गादासः ।
निष्कर्षः= बहिर्निस्सारणम्—सा ।
निष्कर्षः= बहिष्करणम्—क्षी ।

क—कउस्—कर्षणे । च. स्ला. कुसु=अंशे, भागे (शैथिल्ये); कुतिति सें= शैथिल्ये—वा. पॉकर्नीः ।

ग—ममच्चन त्वा कुषवा जगार—ऋ. ४,१८,८; जीवन्तमेव कुष्णाति वृकीव कुकुटुम्बिनी—कथासरि. २३,२७; अभिकुष्णीयात्—सुश्रु. १,१४५,२; गृध्रा रुषा मम कुषन्ति-भा, पु, ३,१६,१० इति तौदादिकोऽपि प्रयोगः । निष्कुषितं विहङ्गैः-रघु. ७,५०=खण्डितम् (सं.)।

+√कुस् (कुस) ४/१०५ श-काकृ-कात-शा× | श्लेषणे (प) क्षी-मै-सा-च-जै-हे । श्लिषि-वो । | >√कुश् (कुश) श्लेषणे (प) इति दुर्गः-क्षी ।

ग—कुसुमम्-(कुस्यति ।√कुस्+उगा. ४/१०६ इत्युमः । संज्ञापूर्वकत्वान्न गुणः) सुश्रु. १,१५९,१८ ।

छ—द्रष्ट. √कुश् ।

छ—√घुसना=प्रवेशे, श्लेषणे ।

√कू (कुङ्) ६/१२० च-काक्ष-कात×;•श	शब्दे (आ) इत्येके—क्षी । क्षी-मै-सा-जै-शा-हे । आर्तस्वरे—वो ।	<√कु (कुङ्) शब्दे (आ) ।

क—कुआँ—, कुए--, कूउआ, कुइ--, कुंउ ।

ख--अवे.--कू=?--वा. पॉकर्नीः ।

ग—आकुवते—काठ.—२३,२; क. ३५,८; आकूतम्—खि. ३,१५,६; तै. ३,४,४,१; मै. १,२,३; आकूतात्—मा. १८,५८; का. २०,४,१ । आकूतिम्—खिसा. ३६,४; शौ. ५,७,८ ।

√कूज् (कूज) १/२१८ श	अव्यक्ते शब्दे (प) क्षी-मै-सा-च-जै-काक्ष-कात-शा-हे । हिक्कने—वो ।	√कु (कुङ्)६/ शब्दे (आ)। √कुञ् १/३१३f हिंसागत्योः (प) काक्ष। √कुञ् १/७४c अव्यक्तेशब्दे (प) काक्ष। √गुज् (गुज) १/ अव्यक्ते शब्दे (प)। √गुञ् (गुजि) १/ अव्यक्ते शब्दे (प)। √कीज् (कीज) १/७४a अव्यक्ते शब्दे (प) काक्ष। √क्षीज् (क्षीज) १/ अव्यक्ते शब्दे (प)। √कू (कूङ्) ६/ शब्दे (आ)इत्येके-क्षी।

क—काउ-, केउ-, कू=शब्दे । कु-(अथवा),गु-योजनेन-कूज्-वा. पॉकर्नीः ।

ग—कूजति-षत्रा. ५,७; कूजते-मा. २२,७; का. २४,३,३; मै. १२,३; कुक्कुराविव कूजन्तौ—अ. वे. ७,९५,२; कोकिलस्तात कूजति-वा. रा. २,५२,२; भृङ्गराजस्तु

कूजति–सुश्रु. २,२४६,६। अत्र √कूज् धातुः कोकिलकुक्कुरभृङ्गराजादिशब्दे प्रयुक्त इति मधुरामधुरसर्वाव्यक्तशब्दविषयः।

घ—√कूज् (कूज) अव्यक्ते सद्दे–धा. पा. ७८—कूजति–जातक २,४३९।

ङ—√कूज (अक) = अव्यक्ते शब्दे। कूजाहि–चारु. २१।
√कूय (अक) = अव्यक्ते शब्दे। वक्ट–कूयंत, कूयमाण–ओघ २१ भा; विपा. १,७।

छ—√कूजना } = शब्दे, मधुरशब्दे
छ—√कूकना }

+√कूल्(कूल) १/५२५ आवरणे (प)
श× क्षी-मै-सा-जै-कात-शा-हे
आवृतौ—वो।
वरणे—च।
(काकृ √कुळ् आवरणे—काकृ।
[कुल])
लैपिकी त्रुटिः।
√कूल् इति भाव्यम्

√कट्(कटे) १/ वर्षावरणयोः (प)।
√कुल्(कुळ) १/ संस्त्याने बन्धुषु च (प)।
√कोल् (कोल) १/२३७b आवरणे (प) काकृ।
√कोल् (कोल) १/२५२a गतिप्रतीघाते (प) काकृ।
√कोल् (कोल) १/२४७b गतौ (प) काकृ।
√गुण्ड्(गुडि) १०/ वेष्टने (प) मै।
√घृ १०/ आवरणे (प)।

क—केर् = दाहे, औष्ण्ये। लिथु. कुरिउ, कुर्ति = औष्ण्ये; कूरेन्ति = अनवरतमौष्ण्ये; कुर्स्टयति = उत्तेजने; लेट्टिश्—कुरु (कुर्स्तु), कुर्त् = धूमे, वाष्पे। केउ-(ःकूेउ-, कू-) = दीप्तौ, दाहे–वा. पॉकर्नीः।

ग—कूलम्—तांब्रा. १४,३,१३। (कूलति = जलप्रवाहमावृणोतीति। √कूल्+अच्) = नद्या जलसमीपस्थानम्। ह्विट्नीः √कूड्, √कूल् इति (प्रयो.) दाहे दीप्तौ पठति। तथा हि–

नेदीयसः कूळयातः पणींरुत–ऋ. ८,२६,१०; (अग्निः) तासां प्राजमानो योनिमकूलयत्; अङ्गारैः खादिरैरवकूलयेत्–सुश्रु. २,३५०,१८।
ङ—कूल = तटम्—णाया. १,१९।

√ कृ (कृञ्) १/८८५ मै-श-च-काकृ-कात×	करणे (उ) क्षी-सा-जै-शा-हे । कृतौ—वो ? रचनायाम्—ह्वि. ।	√करन्ती—निघ. २/१ । √कृ (डुकृञ्) ८/ करणे (उ) । √कृ (कृञ्) ५/ हिंसायाम् (उ) ।

क—कुऐर्=करणे, निर्माणे । लिथु. कुर्ति, केरेति=करणे, —जू. पॉकर्नीः ।

ख—अवे. कूरूनओइति(<कृणोति)=करणे-जू. पॉकर्नीः ।

ग—करामहे-मा. ९,५; का. १०,२,१; तै. १,७,७,१ । करे—मभार. १४,९,२९ । =कुर्वे (नील.) कृञ्छान्दसं भौवादिकत्वम्-नील. । नीलकण्ठेन च्छान्दसत्वमुक्तं तन्न विचारसहम्, प्राकृतहिन्दिभाषयोः √कर् धातोरुपलम्भात् ।

ङ—√कर (सक)=करणे, निर्माणे (करइ) । वकृ-करंत, करेमाण-पि. ५०९; रयण. ७२; से. २,१५; सुर. २,२४; उवा. ।

छ—√करना ।

धातोरस्य करति-रूपं क्वचिल्लेट्-लकारेऽपि सिद्ध्यति । यथा—करति-शौ. १९,१५,५ =कुर्यात्-सायणभाष्यम् । क्वचिन्न-ऋ. १,४३,६-व्यत्ययेन शप्-सा.भा. ।

√कृ (कृञ्) ५/७ श	हिंसायाम् (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । वधे—वो । निर्माणे—ह्वि. ।	√कृ (डुकृञ्) ८/ करणे (उ) । √कॄ ९/ हिंसायाम् (उ) । √कृण्व् (कृवि) १/ हिंसा-करणयोश्च (प) । √कृत् (कृती) ६/ छेदने (प) ।

क—(स्) केर्-, (स्) केर्-, (स्) क्रे=छेदने—जू. पॉकर्नीः ।

ग—आकृणोति—ऋ. १,१७३,११ । कृधि-ऋ. १,१०,११ । कृणोति-मा. २९, ३९; का. ३१,२,३; काठ. २१,१३; पै. २,३२,४ ।

+√कृ (कृञ्) ९/१३ मै-सा-श-च-काकृ-कात-शा-वो×	हिंसायाम् (उ) इत्येके—क्षी । क्षी-जै-हे ।	<√कॄ (कॄञ्) हिंसायाम् (उ) । द्रष्ट.√कॄ ९/१३ ।
√कृ (डुकृञ्) ८/९···· जै-शा-हे×,श	करणे (उ) क्षी-मै-सा-च-काकृ-कात । कृतौ—वो ? हिंसायाम्—मभार. ५, ७८, ५ ।	पूर्ववत् ।

क—, ख—द्रष्ट. √कृ १/८८५ ।

ग—'करोति' इति रूपम् ऋग्वेदे मया नाधिगतम् । करोति—खिसा. २९, ४३; खि. २, ६, १९; शब्रा. १, १, १, १० । कुरुते—शब्रा. १, १, २, ४ ।

घ—करोमि-सुत्तनिपात ७८ ।

ङ—√कुव्व (सक)=करणे । कुव्वइ-भग. ।

ङ—√कि (सक)=करणे । डुक्कियं करणे—विसे. ३३०० ।

+√कृड् (कृड) ६/१०२	घनत्वे (प) क्षी-सा-हे ।	√कड् (कड) ६/ घसने (प) ।
मै-श ×	'घसने' इत्येके—सा । सा-च-कात-शा-हे । धान्ये भक्षे—वो ।	√कुड् (कुड) ६/ घसने बाल्ये च (प) जै-कात-शा-हे ।
(काकृ-√क्रुड् [क्रुड] जै-√तड् [तड] संभवतो मुद्रणदोषः √कृड् इति स्यात्	घसने—काकृ ।	√कूड् (कूड) ६/ धान्ये भक्षे च (प) वो । √क्रुड् (क्रुड) ६/९७ चलने (प) काकृ । √क्रूड् (क्रूड) १/२१४b चलने (प) काकृ । √घनत्वे ? ह्वि-क्रूडयति-काठ.६,३ ।

क—द्रष्ट.√क्रूड् धातुः । इँग्लि. कर्ड=दधि । म. इँग्लि. क्रुड् (डे), क्रुड-केल्टिकमूलम् । तु. गऐल. —ग्रुथ । इरि. ग्रुथ्, क्रुथ्, क्रुथैम् ।

महाराष्ट्रिया ऋकारमुकारवदुच्चारयन्ति हिन्द्यामपि क्वचित् तथा । यथा—अमृत-(फलम्) >अमरुत >अमरूद । एवमत्र काशकृत्स्न इमं धातुं √क्रुड् पठति । घसनार्थकः √कुड् जै-कात-शा-हेमैः पठितः । इत्थमेनस्य विकाससरणिर्भविष्यति-√कड् ६/१०० घसने (प) >√कृड् घनत्वे घसने>√कुड् ६/ घसने (प) >√कूड् ६/धान्ये भक्षे (प) वो; इति । क्रुडति-(महीध.) वा. सं. २५, ८ ।

√कृण्व् (कृवि) १/५९४	हिंसाकरणयोश्च (प)	√कृण्व् ५/१७e जिघांसायाम् (प) कात ।
श-काकृ-कात-हे-वो×	क्षी-मै-सा-शा । हिंसायाम्—च । हिंसाविकरणयोः—जै ।	√कृण्व् ५/२३ हिंसाकरणयोश्च (प) शा । √कृण्व् ५/२५ हिंसाकरणयोश्च (प) हे ।

√कृण्व् ५/ हिंसे कृतौ च (प) वो।
√कृ (कृञ्) ५/ हिंसायाम् (उ)।
√कृण् १/२०८a अपनयने (प) काकृ।
√कृण्व् ८/१३ —श।

धातुरयं नूनं सौवादिकेन √कृ (कृञ्) धातुना सम्बद्धो वर्तते। यथा–√कृ+णु+अ=√कृण्व्। अत एव वैयाकरणा नैकमत्यं भजन्ते (ध्वनिमेलके द्रष्ट.)। देशभेदेनैनस्य प्रयोगभेदः स्यात्। कृण्वति–ऋ. सं. ३, ३, २१, ४ वेदे करणार्थकस्यापि √कृ धातोः कृणोतीति रूपं भवति। फलत इह √कृ (डुकृञ्), √कृ (कृञ्) च धातू संक्रान्तौ।

√कृत् (कृती) ६/१५२ श	छेदने (प) क्षी-मै-सा-च-जै, काकृ (उप), कात-शा-हे।	√कृ (डुकृञ्)८/करणे (उ)। √कृ (कृञ्) ५/ हिंसायाम् (उ)।
		√कुट् (कुट) १०/ छेदने (आ) इत्येके स्वामी
	छिदि—वो।	—सा।
		√कुट्ट् (कुट्ट) १०/ छेदनकुत्सनयोः (प)।
		√कुठ् छिदि सौ.धा.—वो। -कुठारः।

क—(स्) केर्त—, क्रेत—ः
ख—अवे. कृरून्तइति=कृन्तति–जू. पॉकर्नीः।
ग—चकर्तिथ–ऋ. १,५७,६। कृन्तति–तै. ६,१,८,४।
घ—कन्तति–जातक २,५३; करति–दीघ. १,५२=मिलिन्दपञ्ह १,५१६।
ङ—√कंत (सक)=छेदने। तर्कुत्या। सूत्ररचनायाम्। कंतामि–पिंडभा. ३५।
ङ—√कत्त (सक)=छेदने। कत्ताहि–पण्ह. १,१। सूत्ररचनायाम्–पिंड. ५७४।
ङ—√कट्ट (सक)=छेदने। कट्टइ–भवि.।
छ—√कतरना = छेदने।
छ—√कुतरना = „ ।
छ—√काटना = „ ।

ज—√केचा = खण्डशः करणे ।

√कृत्(कृती) ७/१० श	वेष्टने (प) क्षी-मै-सा-च-जै,काकृ-(उप), कात-शा ।	√कृत्(कृती) ६/ छेदने (प)। √कुण्ठ् (कुठि) १०/ वेष्टने (प) एके-सा।
		√गुण्ड् (गुडि)१०/ वेष्टने (प)।
	संवेष्टने—हे।	√गुध् (गुध) ४/परिवेष्टने (प)।

क—कॆर्त्, कॆर्तृत्-, क्रात्=वेष्टने-वा, पॉकर्नीः ।
ग—कृणत्ति-तै. २,५,१,७; शब्रा. ३,१,२,१९ ।
ङ—√कंत (सक) = तर्कुरुया सूत्ररचनायाम्, वेष्टने। कंतामि-पिंडभा. ३५।
ङ—√कत्त (सक) = तर्कुरुया सूत्ररचनायाम्, वेष्टने-पिंड. ५७४।
छ—√कातना = तर्कुरुया सूत्ररचनायाम्, वेष्टने।

√कृप्(कृपू) १/५७४ श	सामर्थ्ये (आ) क्षी-मै-सा-च-काकृ-काल-शा-हे।	√कृ(डुकृञ्) ८/ करणे (उ)। √कृ+√पा २/ रक्षणे (प)।
(जै√त्रप् [त्रपूङ्]) मुद्रणदोषः। कृपूङ् इति स्यात्।	सामर्थ्ये—जै।	

क—स्कॆल् (ऐ) प्—ः लैति. स्कल्पो = लालसायाम्, गात्रविघर्षणे। लिथु. स्कॆम्प्ति=दीप्तौ, घर्षणेनोज्ज्वलने।

ख—हु-कुऌप्त = सुक्लृप्तम्—जू. पॉकर्नीः।

ग—अनुकृपते-ऋ. १, ११३,१०। नास्मै समितिः कल्पते-अ. वे. ५, १९, १५। कल्पते न मुह्यति-शब्रा. १,५,२,१५।

घ—कप्पति-दीघ. २,१६२।

ङ—√कप्प (अक) = सामर्थ्ये, (२) कल्पनायाम्, (३) छेदने। कप्पइ, कप्पए (कप्प., महा., पिंग.)।

ङ—√खिप्प (अक) = सामर्थ्ये, (२) दौर्बल्ये। खिप्पइ-संक्षि. ३५।

√कृप् (कृप) १/७७४ क्षी-सा-श-च-काकृ-कात-शा-हे-वो×	कृपायां गतौ (आ) इत्येके-मै मै। भावकरणे—जै। विलापे, शोके—ह्वि.।	<√क्रप् (क्रप) कृपायां गतौ (आ)। √कृप् (कृपू) १/ सामर्थ्ये (आ)। √कल् (कल) शब्दसंख्यानयोः (आ)।

ग—कृपते-ऋ. १,११३,१०। अकृपन्त-ऋ. ९,८५,११। कृपन्त-कौ. २,९८३।

√कृश् (कृश) ४/११४ श	तनूकरणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा। तनुत्वे—हे। कार्श्ये—वो।	√कृ (डुकृञ्) ८/ करणे (उ)।

क—(केकु्-:) काकु्—: कृकु् = कार्श्ये। लिथु.-कर्तुं, करिर्त-, कर्सिन्ति = भे ;, स्थगने।

ख—अवे. कूरूस = कार्श्यम्-वा. पॉकर्नीः।

ग—कृश्यति-तांब्रा. ५,१,७। मांसानि कृश्यतः कृश्यन्ति-शब्रा. ११,१,६,३४। अवकर्शयन्ति (प्रेर.) ऋ. ६,२४,७। अवकृश्नीयात् (क्रैयादिकोऽपि)-मै. ३,६,९।

ङ—√किस (सक) = ह्रासे, अपचये। किसए-सूअ. १,२,१,१४।

√कृष् (कृष) १/९७५ श	विलेखने (प) क्षी-मै-सा-च-काकृ-कात-शा-हे। विलिखितौ—जै। विलेखे—वो।	√कृ (डुकृञ्)८/करणे (उ)। √कच् (कच) १/ बन्धने (आ)। √कञ्च् (कचि) १/ दीप्तिबन्धनयोः (आ)। √खच् (खच) १०/ बन्धने (प)।

क—कुएल्स्-,कुएलूस्—

ख—अवे. कर्ष् इति = कर्षति-जू. पॉकर्नीः।

ग—कर्ष—ऋ. ५,८३,७। कर्षति-ध्या. ६०; योचू. २९; योशि. ६,५३। कर्षन्ति-ऐब्रा. ८,११।

घ—अवकस्सति तथा ओकस्सति–विनय. २,२०४।

घ—कड्ढति–जातक १,१९३।

घ—कसति–संयुत्त. १,१७२,१७३; सुत्तनिपात ८०।

ङ—√ खंच (सक) = (१) कर्षणे, (२) वशीकरणे। खंचइ–भवि.।

छ—√ करषना* } = कर्षणे, (२) शोषणे, (३) आह्वाने, निमन्त्रणे।
छ—√ करसना*

छ—√ कसना–(<कर्षणम्) = बन्धनादिदार्ढ्याय तद्रज्जुकर्षणे।

छ—√ काढ़ना = उल्लेखने (हि. उरेहना), विलेखने, (२) निष्कासने, (३) ऋणादाने।

छ—√ खचाना = (<कर्षणम्) = अङ्कने।

छ—√ खँचाना† = (<कर्षणम्) = अङ्कने।

छ—√ खाँचना†* = (<कर्षणम्) = अङ्कने, कर्षणे।

√ कृष् (कृष) ६/६	विलेखने (उ)	
जै×, श	क्षी-मै-सा-च-काकृ-कात-शा-हे।	पूर्ववत्।
	आकृपि—वो।	

क—पूर्ववत्।

ग—कृषति–मै. ३,२,४; क. ३१,५। अचीकृषम्–ऋ. १०,११९,११। कृषति–शब्रा. ७,२,४,२। कृषन्ते–तैब्रा. १,८;४,२। कृष्णन्ति—(क्रैयादिकोऽपि) आर्षे. ७ : ७।

छ—√ खींचना } = कर्षणे।
√ खैंचना

ज—√ केति (<कृष्टिः) = विलेखने।

√ कॄ ६/१२८	विक्षेपे (प)	√ कृ (डुकृञ्) ८/करणे (उ)।
श×	क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।	√ गॄ ६/ निगरणे (प)।
	विक्षेपणे—जै।	

क—(स्) केर्–, (स्) केर्–ः स्के = उच्छलने, परित उत्प्लवने। ओस्सेतन्–क्लन् = राशौ–जू. पॉकर्नीः।

ख – स्कारथत्–रथ (स्. स्केर् = वेष्टने)–वा. पॉकर्नीः।

ग—अकिरत्–ऋ. १,३२,१३। अनुकिरामि–अ. वे. १८,३,६९। आ...किरासि–ऋ. ८,४९,४।

घ—अभिकिरति-संयुक्त. १,४५।

ङ—√किर (सक)=(१) क्षेपणे, (२) प्रसारणे, (३) विकिरणे। वक्त-किरंत-से. ४,५८;१४,५७।

छ—केराना† =(<किरणम्) =शूर्पोत्पवने (पछोड़ना-हि.), शूर्पं प्रचाल्य महल्लघुकणविभागे।

+√कॄ (कॄञ्) ९/१३ जै×, श	हिंसायाम् (उ) क्षी-मै-सा-च-काकृ-कात-शा-हे। हिंसे—वो।	>√कृ (कृञ्) हिंसायाम् (उ)। √कृ (कृञ्) ५/ हिंसायाम् (उ)।

अयं√कृ ५/७ हिंसायाम् इति धातोरभिन्नो गणभेदात् पृथक् संख्यातो वैयाकरणैः। श्नाविकरणकमस्य रूपं यावद्गवेष्ये साहित्ये नोपलब्धम्। कृणीमसि–तांब्रा. १२,६,३ इति केवलेन प्रयोगेण द्विष्ठः सम्बन्धः श्नाविकरणात्मको विचिकित्सितः प्रस्तूयते।

+√कॄ ९/२५ श-च-काकृ-कात-वो×	हिंसायाम् (प) क्षी-मै-सा-जै-शा-हे।	पूर्ववत्।

सर्वैर्नानुमोदितः। कृतः–मभार. १२,१२८,४=हतः (नील.)√कॄ हिंसायाम् इत्यस्य रूपम् (नील.), नैतत् साधिकारं वक्तुं शक्यते;√कृ ५/७ इत्येतस्मादपि क्त-प्रत्यये सति प्रकृतरूपसिद्धेः सत्त्वात्। तस्मादयं परस्मैपदाय निमित्तायैव पार्थक्यं नीतः। नेदमपि मनोरमम्,√कृ ९/१३ इत्यस्योभयपदित्वादिष्टसिद्धेः।

+√केप् (केपृ) १/३६४ श×	च=कम्पने, गतौ च (आ) क्षी-सा। कम्पने—मै-च। चलने—जै-कात-शा-हे। चलने गतौ च—काकृ। चाले—वो।	√कम्प् (कपि) १/ चलने (आ)। √वेप् (टुवेपृ) १/ कम्पने (आ)। √गेप् (गेपृ) १/च=कम्पने गतौ च (आ)। √खेप् १/१४३ चलने (आ) जै, ९३० शा। √ग्लेप् (ग्लेपृ) १/च= कम्पने गतौ च (आ)।

क—केइभ्= प्रबलम्, तीव्रम्–वा. पॉकर्नीः।

ग—ते न्यविशन्त केपयः–ऋ. १०,४४,६। केपयः कपूया भवन्ति, कपूयमिति पुनाति कर्म कुत्सितं दुष्पूयं भवति–निरु. ५/२४। अस्माकं मतेन तु 'केपि'-शब्दे सुस्पष्टं√केप् धातुः प्रतीयते, सर्वधातुभ्यश्च इन् प्रत्यये सति रूपनिष्पत्तिर्ज्ञेया। चलनमनस्का दुर्मनस्का भवन्ति। चलनाः कम्पना वाऽस्थिरत्वादनर्हाः। तदुक्तम्-न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः–निरु. ५,२५,१।

+√केल् (केल) १/५३७ चलने (प)
शX क्षी-मै-सा-च-जै-शा-हे।
गतौ—काकृ-कात।
चालगत्योः—वो।

√क्रीड् (क्रीडृ) विहारे (प)।
√किल् (किल) ६/ श्वैत्य-क्रीडनयोः (प)।
√क्ष्वेल् (क्ष्वेल)१/चलने(प)।
√क्वेल् १/७२१ चलने (प) जै, ४४६ हे।
√कैल् १/२४७ गतौ (प) काकृ।
√खेल् (खेल)१/चलने (प)।

ग—उपचारक्रिया केलिः–मनु. ८,३५७। स तु केलिकिलो विप्रो भेदशीलश्च नारद–हरिवंश. (श. क. द्रु.)=नायकवयस्यः। यद्यप्ययं शब्दः श्वैत्यक्रीडनार्थकेन √किल् ६/७४ धातुनापि साधयितुमर्हति तथापीह 'केल्'-ध्वनिदर्शनात् केल् धातुरेव ज्यायान्। व्युत्पत्तिस्तु√क्रीड् > √किल् > √क्ष्वेल् > √क्वेल् > √केल् > √कैल् > √खेल् इति मनोरमा।

ङ—केली(=चलने), असती, कुलटा–दे. २,४४।

+√केव् (केवृ) १/५०१ सेवने (आ)
मै-सा-शX क्षी-च-जै-शा-हे।
सेचने—काकृ-कात।
सेवे—वो।

√केव् १/३९९ a गतौ (प) च।
√खेव् (खेवृ) १/ सेवने (आ)।
√गेव् १/४३९ d सेवने (आ) च, जै-शा-हे।
√ग्लेव् (ग्लेवृ) १/ सेवने (आ)।
√के+√वा २/ गतिगन्धनयोः (प)= √केव इति वागीशः⊥

क—कै=एकाकिन् (कैउऍरॉ)-वा. पॉकर्नीः ।

ग—अस्माकमस्तु केवलः-ऋ. १,७,१० । केवले-ऋ. १०,५१,९। केवली यत्सोमाहुतिः-शब्रा. १,७,२,१० । केवला-वा. रा. २,३४,५५=कृत्स्ना (तिल.)। केवलमुत्पद्यते ज्ञानम्—सां. का. ६४=ज्ञानभेदः । केवलः(=कुम्भकविशेषः)-हठयोगदी. २,७१ । न केवलानां पयसां प्रसूतिम्-रघु. २,६३=शुद्धानाम्। केवलं स्मरणेनैव-रघु. १०,२९=कृत्स्नम् (सं.)। माकीं सं शारि केवटे-ऋ. ६,५४,७; ऋ. सं. ४,८,२०,२=सेव्यते जलार्थिभिः√केव्+अटन्-केवटः=कूपः-निघ. ३/२३ ।

ङ—केवल=एकाकी-ठा. २,१; औप. ।

छ—केवड़ा (<केविका—राजनिर्घण्टः)=पुष्पविशेषः ।

अत्र ज्ञान-कृत्स्न-पुष्पादिषु सेवनार्थकत्वं लभ्यते । अस्मन्मतेन-के=शिरसि+√वा (गतिगन्धनयोः)=√केव् इति निष्पद्यमानो धातुः सेवनार्थकः । शिरसि गतिर्गन्धनं वा सेवनमेव । सेचनार्थकोऽप्ययं (काक्कात०) पठ्यते । एवं सति के=जले+√वा (गतिगन्धनयोः)=√केव् इति क्रमः । जले गन्धनम्=सेचनमेव । पुष्पार्थे केविकाशब्दे तु √वा धातुः सुस्पष्ट एव । गन्धनम्=मर्दनादिकम् ।

√कै १/९०१ √का ४/···	शब्दे (प) क्षी-मै-सा-च-जै-काक्क- कात-शा-हे-वो । प्रसादे, आनन्दे—ह्वि. ।	√कम् (कमु) १/ कान्तौ (आ) ।

क—का=इच्छायाम्—जू. पॉकर्नीः ।

ग—कायमानः-ऋ. ३,९,२ । आचके-ऋ. १,२५,१९; तै. २,१,११,६ । कायमानश्चायमानः (=पश्यन्) कामयमान इति वा-निरु. ४/१४ इति दृशाऽयं कान्तौ दर्शने च भवति । दर्शनानन्तरं वाग्व्यवहार इति लोके धातुरेष शब्दार्थको जातः । प्राकृते 'काय'-शब्दः काकवाचकः ।

ङ—काय=काकः-उप. पृ. २३; हेका. १४८; वा. २६ ।

ज—√कै-कै=पीडाशब्दे ।

ह्विट्नीदैवादिकमिमं स्वीकरोति । तेनायं पक्षो गृहीतः स्याद् दुर्गादासस्यैकदेशीयप्रश्नात् । तद्यथा—"एषामादन्तत्वेन दिवादौ पाठेऽपीष्टसिद्धौ भ्वादावैकारान्तत्वेन पाठो गणकृतमनित्यत्वमिति ज्ञापयति । तेन √अय् धातोरात्मनेपदानित्यत्वे शपो लुकि च "य्वोर्लोप" इति यलोपे, √अय् धातौ परे उपसर्गरेफो ल् इति वक्तव्यात् पराशब्दस्य रेफस्य लकारे "एककालः समुत्पन्नो यः पलाति स जीवति" इति सिद्धम् । वेदेषूच्चारणभेदार्थो भ्वादौ पाठ इति केचित् ।

ग—ते न्यविशन्त केपयः-ऋ. १०,४४,६। केपयः कपूया भवन्ति, कपूयमिति पुनाति कर्म कुत्सितं दुष्पूयं भवति-निरु. ५/२४। अस्माकं मतेन तु 'केपि'-शब्दे सुस्पष्टं√केप् धातुः प्रतीयते, सर्वधातुभ्यश्च इन् प्रत्यये सति रूपनिष्पत्तिर्ज्ञेया। चलनमनस्का दुर्मनस्का भवन्ति। चलनाः कम्पना वाऽस्थिरत्वादनर्हाः। तदुक्तम्-न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः-निरु. ५,२५,१।

+√केल् (केल) १/५३७ चलने (प) शX
क्षी-मै-सा-च-जै-शा-हे।
गतौ—काकृ-कात।
चालगत्योः—वो।

√क्रीड् (क्रीडृ) विहारे (प)।
√किल् (किल) ६/ श्वैत्य-क्रीडनयोः (प)।
√क्ष्वेल् (क्ष्वेलृ) १/चलने (प)।
√क्वेलृ १/७२१ चलने (प) जै, ४४६ हे।
√कैल् १/२४७ गतौ (प) काकृ।
√खेल् (खेलृ) १/चलने (प)।

ग—उपचारक्रिया केलिः-मनु. ८,३५७। स तु केलिकिलो विप्रो भेदशीलश्च नारद-हरिवंश. (श. क. द्रु.) = नायकवयस्यः। यद्यप्ययं शब्दः श्वैत्यक्रीडनार्थकेन √किल् ६/७४ धातुनापि साधयितुमर्हति तथापीह 'केल्'-ध्वनिदर्शनात् केल् धातुरेव ज्यायान्। व्युत्पत्तिस्तु √क्रीड् > √किल् > √क्ष्वेल् > √क्वेल् > √केल् > √कैल् > √खेल् इति मनोरमा।

ङ—केली(=चलने), असती, कुलटा-दे. २,४४।

+√केव् (केवृ) १/५०१ सेवने (आ) मै-सा-शX
क्षी-च-जै-शा-हे।
सेचने—काकृ-कात।
सेवे—वो।

√केव् १/३९९ a गतौ (प) च।
√खेव् (खेवृ) १/ सेवने (आ)।
√गेव् १/४३९ d सेवने (आ) च, जै-शा-हे।
√ग्लेव् (ग्लेवृ) १/ सेवने (आ)।
√के+√वा २/ गतिगन्धनयोः (प)= √केव इति वागीशः ⊥

क—कै = एकाकिन् (कैउएरॉ)-वा. पॉकर्नीः ।

ग—अस्माकमस्तु केवलः-ऋ. १,७,१० । केवले-ऋ. १०,५१,९। केवली यत्सोमाहुतिः-शब्रा. १,७,२,१० । केवला-वा. रा. २,३४,५५ = कृत्स्ना (तिल.) । केवलमुत्पद्यते ज्ञानम्—सां. का. ६४ = ज्ञानभेदः । केवलः(= कुम्भकविशेषः)-हठयोगदी. २,७१ । न केवलानां पयसां प्रसूतिम्-रघु. २,६३ = शुद्धानाम् । केवलं स्मरणेनैव-रघु. १०,२९ = कृत्स्नम् (सं.) । माकीं सं शारि केवटे-ऋ. ६,५४,७; ऋ. सं. ४,८,२०,२ = सेव्यते जलार्थिभिः √केव्+अटन्-केवटः = कूपः-निघ. ३/२३ ।

ङ—केवल = एकाकी-ठा. २,१; औप. ।

छ—केवड़ा (<केविका—राजनिर्घण्टः) = पुष्पविशेषः ।

अत्र ज्ञान-कृत्स्न-पुष्पादिषु सेवनार्थकत्वं लभ्यते । अस्मन्मतेन-के = शिरसि + √वा (गतिगन्धनयोः) = √केव् इति निष्पद्यमानो धातुः सेवनार्थकः । शिरसि गतिर्गन्धनं वा सेवनमेव । सेचनार्थकोऽप्ययं (काकृकात०) पठ्यते । एवं सति के = जले + √वा (गतिगन्धनयोः) = √केव् इति क्रमः । जले गन्धनम् = सेचनमेव । पुष्पार्थे केविकाशब्दे तु √वा धातुः सुस्पष्ट एव । गन्धनम् = मर्दनादिकम् ।

√कै १/९०१ √का ४/···	शब्दे (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो । प्रसादे, आनन्दे—ह्वि. ।	√कम् (कमु) १/ कान्तौ (आ) ।

क—का = इच्छायाम्—जू. पॉकर्नीः ।

ग—कायमानः-ऋ. ३,९,२ । आचके-ऋ. १,२५,१९; तै. २,१,११,६ । कायमानश्चायमानः (= पश्यन्) कामयमान इति वा-निरु. ४/१४ इति दृशाऽयं कान्तौ दर्शने च भवति । दर्शनानन्तरं वाग्व्यवहार इति लोके धातुरेष शब्दार्थको जातः । प्राकृते 'काय'-शब्दः काकवाचकः ।

ङ—काय = काकः-उप. प्र. २३; हेका. १४८; वा. २६ ।

ज—√कै-कै = पीडाशब्दे ।

ह्विट्नीर्दैवादिकमिमं स्वीकरोति । तेनायं पक्षो गृहीतः स्याद् दुर्गादासस्यैकदेशीयप्रश्नात् । तद्यथा—"एषामादन्तत्वेन दिवादौ पाठेऽपीष्टसिद्धौ भ्वादावैकारान्तत्वेन पाठो गणकृतमनित्यत्वमिति ज्ञापयति । तेन √अय् धातोरात्मनेपदानित्यत्वे शपो लुकि च "य्वोर्लोप" इति यलोपे, √अय् धातौ परे उपसर्गरेफो ल् इति वक्तव्यात् पराशब्दस्य रेफस्य लकारे "एककालः समुत्पन्नो यः पलाति स जीवति" इति सिद्धम् । वेदेषूच्चारणभेदार्थो भ्वादौ पाठ इति केचित् ।

√क्नस् (क्नसु) ४/५ जै×, श	ह्वरणदीप्त्योः (प) क्षी-मै-सा-कात-शा। ह्वरणे—च। ह्वतिदीप्त्योः—हे। ह्वतौ भासने च—वो।	√नस् (णस्) १/ कौटिल्ये (आ)। क्रंशतिः प्रकाशयति कर्मा- निरु. २,२५; १२/८। √क्नंस् १०/११९ भासार्थः
काक्-√क्नस् [क्नुस्]।	ह्वरणदीप्त्योः—काक्। ह्वरणम्=कौटिल्यम्-क्षी।	क्नंसु ११/ भासने (प) वो। पक्षे भ्वा. दुर्गादा.।

जनीजॄषक्नसुरञ्जोऽमन्ताश्च १/८०३०-मित्
श-जै-शा-हे× (काक्-क्रसु)
स्याल्लैपिकी त्रुटिः।

यद्यपि नास्य प्रयोगोपलब्धिर्यथागवेष्ये साहित्ये तथाप्येष क्रमपि सुश्रृङ्खलं विकाससम्बन्धमुपन्यस्यत्येव। यथा—√नस् (णस्) १/६२० कौटिल्ये (आ) >आदौ ककारसंयोगे—√क्नस् ह्वरणदीप्त्योः (प) >उपोत्तमे नुगमागमे सति—√क्नंस् १/११९ भासार्थः (प) शा, वो>उपोत्तमे रेफे सति>क्रंश् प्रकाशयतिकर्मा (भासार्थः)—निरु. २,२५। अनुनासिकरेफयोर्माधुर्यात् सन्निवेशः स्वाभाविकः। पूर्वमनुनासिको रेफो वेति विचिकित्सितमिति निरुक्तोक्तः √क्रंश् धातुरपि क्नंसतेः प्राग् भवितुम् अर्हति।

+√क्नू (क्नूञ्)९/८ च×, श	शब्दे (उ) क्षी-मै-सा-जै-काक्- कात-शा-हे-वो।	√कु (कुङ्) १/शब्दे (आ)। √कू (कूङ्) ६/ शब्दे (आ)। √नू (णू) ६/ स्तवे (प)। √नु १/५५१q शब्दे (आ) काक्। √कु+√नू=√क्नू शब्दे—इति वागीशः। √क्वण् १/ शब्दे>(व-ण-विपर्यये)—√क्नव् (संप्रसारणे) >√क्नू। √क्नूय् (क्नूयी) १/ शब्दे उन्दने च (आ)।

छ—√गुन्नाना (<क्नूना०)—[बुं. ख.]=अतोपे बालकादीनामस्फुटो ध्वनिः। अयमुत्तरधातोः क्र्यादिभेदः क्वचिद् देशे व्यवहृतिपद्यां प्रपन्नः, सम्प्रति नोपलभ्यमानः।

√क्नूय् (क्नूयी १/४८२ शब्दे उन्दने च (आ)
शX क्षी ।
शब्दे उन्दे च—मै-सा ।
(काक्र-√क्रूय् [क्रूयी]) शब्दे—च-काक्र-कात-शा ।
लैपिकी त्रुटिः । क्नूयी इति जै—भ्रष्टोऽर्थः । पूर्ववत् ।
स्यात् । शब्दोन्दनयोः—हे ।
दुर्गन्ध आर्द्रत्वे शब्दे—वो ।
√क्नू ४/ (कर्मणि वा) उन्दने—ह्वि. ।

क—कॅन्=कान्तौ । कॅने-, कॅनाइ-, कॅनॉइ-: ग्रीक्-क्स्नो (फ्) ऑस्= घर्षणादिशब्दे । पु. गॉथि. क्नेअव्=निर्धनम् (:); गर्द्धनः । न. उ. ज. गेनौ; लेट्टिश—क्नूदु तथा क्नूस्तु, क्नूत्, क्नूस्त्=लालसायाम्, कण्डूतौ । द्-: क्नूदेत्; पॉलिश्-क्नोवक्=खण्डने, शकले-वा. पॉकर्नीः ।

ग—अभिक्नूयमिवादन्ति-शब्रा. १४,१,१,१४ । क्नोपयति (=स्नेहयति)- निरु. ७,१४,५ । वस्त्रक्नोपम्-शिशु. १०,४९ ।

+√क्मर् (क्मर) १/५५६ ह्वर्च्छने (प) मै । √[ह्वर्] ह्वृ१/ कौटिल्ये (प) ।
क्षी-शX मै-सा-च-जै-काक्र-कात- मकरशब्दस्य विपर्ययेण क्मर
शा-हे । >√क्मर् इति स्यात्-
कौटिल्ये—वो । इति वागीशः ।

क—कम्-ऍर्=कौटिल्ये । लैति. (तत्र कुतश्चन गृहीतः शब्दः,) कॅमॅरा= सारसनम्; कॅमॅर, कमर=तोरणः, वृत्तखण्डम् ।

ख—अवे. कमरा=मेखला, कटिसूत्रम्-जू. पॉकर्नीः ।

छ—मक्कार=कुटिलः, जिह्मः ।

+√क्रथ् (क्रथ) १/७९३ हिंसार्थः (प) मित् । √कृत् (कृती)६/ छेदने (प)
शX क्षी-मै-सा-कात-शा-हे । √क्रथ् (क्रथ) १०/ हिंसा-
हिंसायाम्—च-जै-काक्र । याम् (प) ।
वधे—वो । √क्नथ् १/३४७ हिंसायाम्
अयं १०/१३ धातुना (प) जै, ६०७b काक्र ।
सम्बध्यते । √क्लथ् (क्लथ) १/ हिंसार्थः
(प) ।

√क्नस् (क्नसु) ४/५ जै×, श — ह्वरणदीप्त्योः (प) क्षी-मै-सा-कात-शा। ह्वरणे—च। ह्वृतिदीप्त्योः—हे। ह्वृतौ भासने च—वो। काक्र-√क्नस् ह्वरणदीप्त्योः—काक्र। [क्नुस्]। ह्वरणम् = कौटिल्यम्—क्षी।

√नस् (णस्) १/ कौटिल्ये (आ)। क्रंशतिः प्रकाशयति कर्मा— निरु. २,२५; १२/८। √क्नंस् १०/११९ भासार्थः क्नंसू ११/ भासने (प) वो। पक्षे भ्वा. दुर्गादा.।

जनीजृषक्नसुरञ्जोऽमन्ताश्च १/८०३०–मित्
श-जै-शा-हे× (काक्र–क्रसु)
स्याल्लैपिकी त्रुटिः।

यद्यपि नास्य प्रयोगोपलब्धिर्यथागवेष्ये साहित्ये तथाप्येष कमपि सुश्रृङ्खलं विकाससम्बन्धमुपन्यस्यत्येव। यथा—√नस् (णस्) १/६२० कौटिल्ये (आ) >आदौ ककारसंयोगे—√क्नस् ह्वरणदीप्त्योः (प) >उपोत्तमे नुगमागमे सति—√क्नंस् १/११९ भासार्थः (प) शा, वो>उपोत्तमे रेफे सति>क्रंश् प्रकाशयतिकर्मा (भासार्थः)—निरु. २,२५। अनुनासिकरेफयोर्माधुर्यात् सन्निवेशः स्वाभाविकः। पूर्वमनुनासिको रेफो वेति विचिकित्सितमिति निरुक्तोक्तः √क्रंश् धातुरपि क्नंसतेः प्राग् भवितुम् अर्हति।

+√क्नू (क्नूञ्)९/८ च×, श — शब्दे (उ) क्षी-मै-सा-जै-काक्र-कात-शा-हे-वो।

√कु (कुङ्) १/ शब्दे (आ)। √कू (कूङ्) ६/ शब्दे (आ)। √नू (णू) ६/ स्तवे (प)। √नु १/५५१q शब्दे (आ) काक्र। √कु+√नू = √क्नू शब्दे— इति वागीशः। √क्वण् १/ शब्दे>(व-ण-विपर्यये)— √क्नव् (संप्रसारणे) >√क्नू। √क्नूय् (क्नूयी) १/ शब्दे उन्दने च (आ)।

छ—√गुन्नाना (<क्नूना॰)—[बुं. ख.]=अतोषे बालकादीनामस्फुटो ध्वनिः। अयमुत्तरधातोः क्र्यादिभेदः क्वचिद् देशे व्यवहृतिपद्यां प्रपन्नः, सम्प्रति नोपलभ्यमानः।

√क्नूय् (क्नूयी १/४८२ श×	शब्दे उन्दने च (आ) क्षी ।	
	शब्दे उन्दे च—मै-सा ।	
(काक्र-√क्रूय् [क्रूयी]) लैपिकी त्रुटिः । क्नूयी इति स्यात् ।	शब्दे—च-काक्र-कात-शा । जै—भ्रष्टोऽर्थः ।	पूर्ववत् ।
	शब्दोन्दनयोः—हे ।	
	दुर्गन्ध आर्द्रत्वे शब्दे—वो ।	
√क्नू ४/ (कर्मणि वा)	उन्दने—ह्वि. ।	

क—केन् = कान्तौ । केने-, केनाइ-, केनॉइ-ः ग्रीक्-क्स्नो (फ्) ऑस् = घर्षणादिशब्दे । पु. गॉथि. क्नेअव् = निर्धनम् (:); गर्द्धनः । न. उ. ज. गेनौ; लेट्टिश—क्नूद्रु तथा क्नूस्तु, क्नूत्, क्नूस्त् = लालसायाम्, कण्डूतौ । द्र-ः क्नूदेत्; पॉलिश्-क्नोवक् = खण्डने, शकले-वा. पॉकर्नीः ।

ग—अभिक्नूयमिवादन्ति-शत्रा. १४,१,१,१४ । क्नोपयति (= स्नेहयति)-निरु. ७,१४,५ । वस्त्रक्नोपम्-शिशु. १०,४९ ।

+√क्मर् (क्मर) १/५५६ क्षी-श×	हूर्च्छने (प) मै । मै-सा-च-जै-काक्र-कात-शा-हे । कौटिल्ये—वो ।	√[ह्वर्] ह्वृ१/ कौटिल्ये (प) । मकरशब्दस्य विपर्ययेण कमर > √क्मर् इति स्यात्-इति वागीशः ।

क—कम्-एर् = कौटिल्ये । लैति. (तत्र कुतश्चन गृहीतः शब्दः,) कमेरा = सारसनम्; कमेर, कमर = तोरणः, वृत्तखण्डम् ।

ख—अवे. कमरा = मेखला, कटिसूत्रम्-जू. पॉकर्नीः ।

छ—मक्कार = कुटिलः, जिह्मः ।

+√क्रथ् (क्रथ) १/७९३ श×	हिंसार्थः (प) मित् । क्षी-मै-सा-कात-शा-हे । हिंसायाम्—च-जै-काक्र । वधे—वो । अयं १०/१३ धातुना सम्बध्यते ।	√कृत् (कृती)६/ छेदने (प) √क्रथ् (क्रथ) १०/ हिंसायाम् (प) । √क्नथ् १/३४७ हिंसायाम् (प) जै, ६०७b काक्र । √क्लथ् (क्लथ) १/ हिंसार्थः (प) ।

ग—क्रथनाय—मभार. ८,३३,५८=हिंसाय (नील.); क्रथनः=दानवविशेषः-१,६७,५८। क्रथनगात्र०-सुश्रु. १,५२,१५। क्रथकैशिकानाम्-रघु. ५,३९ =विदर्भदेशानाम् (सं.)।

+√क्रद् (क्रद) १/७६६ श-च-शा×	वैक्लव्ये (आ) इति नन्दी-क्षी। क्षी-मै-सा-जै-कात-हे। क्षीरस्वामिमतमुद्धृतं पुरुषकारे (८१ पृ.)। वैकल्ये—काक्र। वैक्लव्यविक्लत्वयोः—वो। रोदने—ह्वि.।	<√कन्द (कदि) वैक्लव्ये (आ)। √कल् (कल) १/ शब्दसंख्यानयोः (आ)। √कद् (कद) १/ वैक्लव्ये (आ) इति नन्दी—क्षी। √क्रन्द् (क्रदि) १/ वैक्लव्ये (आ)।
√क्रन्द्······	विक्लवः=कातरः—क्षी।	√क्लद् (क्लद)१/ वैक्लव्ये (आ) इति नन्दी—क्षी। √क्लन्द् (क्लदि) १/ वैक्लव्ये (आ)।

अस्य विकासक्रमः √कद् >√कन्द्>√क्रद् >√क्रन्द; कद् >√क्रद् >√क्लद् >√क्लन्द् इति।

ग—(अनु) चक्रदे- ऋ. ८,३,१०; शौ. २०,९,४। अभि···अचिक्रदत्—कौ. १,५६२; जै. १,५७,७।

√क्रन्द् (क्रदि) १/६८ श×	आह्वाने रोदने च (प)। क्षी-मै-सा-कात। आह्वानरोदनयोः—जै-शा। आह्वाने—च। आह्लादने रोदने च—काक्र। रोदनाह्वानयोः—हे। रोदने आह्वाने—वो।	√कद् (कद) १/७६५ वैक्लव्ये (आ)। √क्रद् (क्रद) १/७६६ वैक्लव्ये (आ)। √कन्द् (कदि) १/ आह्वाने रोदने च (आ)। √कल् (कल) शब्दसंख्यानयोः (आ)। √क्लन्द् (क्लदि) १/ आह्वाने रोदने च (आ)।

क—केल्=आह्वाने, क्रन्दने-वा. पॉकर्नीः । विस्तारः* क्(ऐ) लेम्(लैति. क्ला—आरे)-जू. पॉकर्नीः ।

ग—तस्य वज्रः क्रन्दति-ऋ. १,१००,१३ । क्रन्ददश्वो रुवद्गौः-ऋ. १,१७३,३ । क्रन्ददाध्ये शिवायै-ऋ. १०,९५,१३ । क्रन्देत्-शब्रा. ११,८,१,१ । क्रौञ्चीं क्रन्दन्तीम्-वा. रा. १,२,१७ । त्राहीति चार्ताः क्रन्दन्ति-मा. पु. १५,६८=आह्वयन्ति ।

घ—कन्दति-मिलिन्दपञ्ह २,१४८ ।

ङ—कंदइ-पिः २३१ ।

छ—√काँदना (<क्रन्दनम् । वंग.)=रोदने, चीत्कारे ।

√क्रन्द् (क्रदि) १/७६६ श ×	वैक्लव्ये (आ) घटादिः क्षी-मै-सा-च-कात-शा-हे-वो । 'वैकल्ये' इति चन्द्रः-क्षी । आह्वानरोदनयोः—जै ? आह्लादने रोदने च-काक ? वैकल्यविकलत्वयोः—वो ।	√कद् (कद) १/ वैक्लव्ये (आ) । √कन्द् (कदि) १/ वैक्लव्ये (आ) । √क्रद् (क्रद) १/ वैक्लव्ये (आ) । √क्लद् (क्लद) १/ वैक्लव्ये (आ) । √क्लन्द् (क्लदि १/ वैक्लव्ये (आ) ।

विक्लवः = कातरः-क्षी. ।

ग—क्रन्दयते-(प्रेर.) क. २७,२; क्रन्दमानमत्यर्थम्-मभार. ३,२३८१; वा. रा. २,२४,४१; दह्यमानं क्रन्दमानं हतस्त्रीसुतगोधनम्-स्क. पु. ३,१३,२० ।

√क्रप् (क्रप) १/७६४ श ×	कृपायाम् (आ) घटादिः । क्षी-मै-काक-कात-शा-हे-वो । कृपायां गतौ—मै-सा ।	√कृप् १/७७४ वत् ।
(जै-√कृप् [कृपै])	कृपायाम्—जै ।	
√कृप्······	विलापे, शोके—ह्वि. ।	

क—क्रेप्-, कृप्=शरीरम्, आकृतिः ।

ख—अवे. कुर्फ्स्, केहर्पो (षष्ठी)=आकृतिः, घटनम्, म. पर्सि. कर्प = कलेवरम्, सामग्री । वा. पॉकर्नीः ।

ग—अक्रपिष्ट-ऋ. ७,२०,९ । अस्माद् धातोः √कृप् १/७७४ धातोर्भेदः सम्प्रसारणमात्रकः । वस्तुतो द्वावेव धातू अभिन्नौ ज्ञानीयौ ।

√क्रम् (क्रमु) १/४६९ श	पादविक्षेपे (प)। क्षी-मै-सा-जै-काकृ-कात-शा-हे। पादविहरणे—च। गतौ—वो।	√कम्ब् १/ गतौ (प) वो। √कर्ब् (कर्ब) १/ गतौ (प)। √गम् (गम्लृ) १/ गतौ (प)। √घम्ब् १/ गतौ (प) वो। √क्रिम् १/२२२b पादविक्षेपे (प) काकृ।

ग—आ····अक्रमीत्—ऋ. ९, ६४, २९; मा. ३, ६; का. ३, १, ६; तै. १, ५, ३, १। क्रामति-षब्रा. १, ७; क्रमते-शब्रा. १, ६, ३, ३३; तैब्रा. १, ३, ५, ४; क्रमयति-शब्रा. ११, ७, २, १।

घ—कमति-सुत्तनिपात १७६।

ङ—√कम (सक)=(१) चलने, (२) उल्लङ्घने, (३) प्रसरणे, (४) सत्तायाम्-विसे. २४६।

ङ—√कम (सक) = (१)साङ्गत्ये, (२) आधिक्ये। कमइ-पिंड. २३१; पच. ६१।

√क्री (डुक्रीञ्) ९/१ श	द्रव्यविनिमये (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। द्रव्यपर्यये—वो।	√कृ (डुकृञ्) ८/ करणे (उ)।

क—कुरेइ=क्रये। पु. रसन्-क्रिनुति, क्रेनुति=क्रये; पु. इरि. कुरिम्-जू. पॉकर्नीः।

ग—क्रीणाति-ऋ. ४, २४, १०; तै. १, ८, १८, १; मै. २, ४, २; काठ. १२, ११।

घ—केतुम् (<क्रेतुम्)-जातक ३, २८२।

ङ—√कीण (सक) = द्रव्यविनिमये। भवि-कीणिस्सं-पि. ५११।

ङ—√किण (सक)=द्रव्यविनिमये। वकृ-किणंत-सुपा. ३६६।

छ—√कीनना ‡ (सक) = द्रव्यविनिमये।

√क्रीड् (क्रीडृ) १/३४६ श	विहारे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। खेले—वो।	√किल (किल) ६/ श्वैत्य-क्रीडनयोः (प)। √क्री (डुक्रीञ्) ९/ द्रव्य-विनिमये (उ)।

		√केल्ट (केल्ल) १/ चलने (प)।
		√क्वेल्ट १/७२१ चलने (प) जै, ४४६ हे।
		√क्ष्वेल्ट (क्ष्वेल्ल) १/ चलने (प)
		√कैल्ट १/२४७ f गतौ (प) काक्ट।
		√खेल्ट (खेल्ल) १/ चलने (प)।

क—के्र्=शिखरम्। लैति. क्रीनिस्=केशः, तन्तुः, सूत्रम्; क्रिस्त्=कङ्कतिका, पर्वतपृष्ठम्। संस्कृ. (*क्रिज्-द्)-वा. पॉकर्नीः।

ग—क्रीडति-ऋ. ९, ६६, २९; क्रीळन्ति क्रीळा विदथेषु घृष्वयः-ऋ. १, १६६, २। क्रीडते-योशि. १, ४३; कू. १८; सार. २४६: ९; शि. ४, २७।

घ—कीळति-विनय ४, ११२।

ङ—√कील (अक)=क्रीडायाम्। कीलइ-प्राप्र.।

ङ—√किड्ड (अक)=क्रीडायाम्। वक्त-किड्डंत-पि. ३९७।

√कु (कुङ्) १/९३८ क्षी-मै-श-च-जै-काक्ट-कात-शा-हे-वो ×	गतौ (आ) कचित्-सा। सा। रूक्षतायाम्—ह्वि.।	<√क्लु (क्लुङ्) गतौ (आ)। √कु (कुङ्) १/ गति-शोषणयोः (आ)। द्रष्ट. √कु (कुङ्) १/९३७।

ग—कवणस्य-ऋ. ५, ४४, ९; कविष्णुः-ऋ. १०, ८७, ५; कव्यम्-मै. ३, १०, १; क्षीरस्वाम्यपि √कु (कुङ्) गतौ (आ)-धातोः कव्यं साधयति-अ. को. २, ६, ६३ परन्तु स क्षीरतरङ्गिण्यां धातुमेनं न सस्मार। स्यात् पाठभ्रंशः

+√कुञ्च् (कुन्च) १/१८२ श-शा ×	गतौ (प)। क्षी-च-हे। कौटिल्याल्पीभावयोः—मै-सा-जै-काक्ट-कात। गत्यां वक्रणे तौच्छये—वो।	√कु (कुङ्) १/ गतौ (आ)। √कुञ्च् (कुन्च) १/ गति-कौटिल्याल्पीभावयोः (प)।

क—(स्) क्रॉइ-क्-ः लैति. क्रुक्स्=ईशोर्वधस्य काष्ठफलकविशेषः (क्रॉस)-जू. पॉकर्नीः।

ग—क्रुञ्च्०-वा. सं. २५, ६; क्रुङ् (ञ्च्) [क्रुञ्चति=वक्रं यथा स्यात् तथा गच्छति। ऋत्विक्० ३/२/५९ इति साधुः]-यजुर्वे. १६ (१९), ७३ (वा. सं.)।

छ—खोंच (<क्रुञ्चिः) = प्रसृति-(= अर्धाञ्जलि)-मितः पदार्थः, प्रसृतिर्वा। इयं प्रसृतिर्निकुञ्जेन पाणिना सम्पद्यत इति धातोः कौटिल्याल्पीभावौ चरितार्थौ।

√क्रुध् (क्रुध) ४/७६ जै ×, श	कोपे (प)। क्षी-मै-सा-च-शा-हे-वो। रोषे—काकृ-कात।	√क्रु (क्रुङ्) १/ गतौ (आ) सा।

ग—अचुक्रुधत्-ऋ. ५, ३४, ७; क्रुध्यति-शौ. ४, ३६, १०; शब्रा. ३, २, २, २४। क्रुध्यस्व—खिसा. २९, २७।

घ—कुज्झति-अंगुत्तर. १, २८३।

छ—√कुढ़ना = ईषत्कोपे, ईर्ष्यायाम्।

√क्रुश् (क्रुश) १/८४१ श	आह्वाने रोदने च (प)। क्षी-मै-सा। आह्वाने—च-काकृ-कात। रोदनाह्वानयोः—जै। आह्वानरोदनयोः—शा-हे। रोदे हूतौ—वो।	√कु (कुङ्) ६/१२० शब्दे (आ)। √क्रु (क्रुङ्) १/ गतौ (आ)। √क्रुञ्च् (क्रुन्च) १/ गतौ (प)। √क्रुध् (क्रुध) ४/ कोपे (प)। क्रोशतिः शब्दकर्मा-निरु. २,२५।

क—(स) क्(ऑ) रौकु्ः

ख—क्स्रओसइति=आह्वाने, क्रन्दने-जू. पॉकर्नीः।

ग—इन्द्रं क्रोशन्तः-ऋ. १०,९५,४। क्रोशति-जै. १६५। क्रोशतु-शौ. ११, ११,७। क्रोशन्ती-वा. रा. १, ५४, ७।

छ—√कोसना (<क्रोशनम्)=शापे, दुर्वचने।

छ—√खुंसना-बुं. ख.-=क्रोधे।

√क्रूड् (क्रूड) १०/ अपाणिनीयः	घनत्वे ? (प)। न्योथ-रॉथ-ह्वि.।	√कृड् (कृड) ६/ घनत्वे (प)। √क्रुड् (क्रुड) ६/ घसने (प) काक्ट। √कूड् (कूड) ६/ धान्ये भक्षे च (प) वो।

क—क्रॉइ=क्रॉइए=घनम्, स्थूलम्।

ख—अवे. क्सरूज्द्र, क्सरूज्द्र=क्रूरम्, कठोरम्, घनम्-वा. पॉकर्नीः।

ग—क्रूडयति, अक्रूडयत्—काठ. ६, ३; क. ४, २। क्रूडयेत्—काठ. ६, ७; क. ४, ६।

√क्लथ् (क्लथ) १/७९४ शX	हिंसार्थः (प) मित् क्षी-मै-सा-कात-शा-हे। हिंसायाम्—च-जै-काक्ट। वधे—वो। परिवर्तने ?—ह्वि.।	√क्रथ् (क्रथ) १/ हिंसार्थः (प)। √श्रथ् (श्रथ) १/ हिंसार्थः (प) मित्।

ग—क्लथन्—मा. ३९, ५ [सपा. क्लथत्<>क्वथत् इति पाभे.]। क्लथन्—वा. सं. ३९, ५ (क्लथनं मध्ये घृतस्यावर्तनम्)।

+√क्लद् (क्लद) १/७६७	वैक्लव्ये (आ) इति नन्दी—क्षी क्षी-मै-सा-जै-कात-हे। वैकल्ये—इति चन्द्रः—क्षी। क्षी-सा-काक्ट। च ? शा ? वैक्लव्यविकलत्वयोः—वो।	<√क्लन्द् (क्लदि) वैक्लव्ये (आ)। √क्रद् १/७६६ धातुर्वीक्षणीयः; तेनैव च सम्बन्धो योजनीयः।

ग—अवस्थस्य क्लदीवतः—अ. वे. ७, ९०, ३।

√क्लन्द् (क्लदि) १/६९ आह्वाने रोदने च (प) √क्रन्द् १/७६६ वत् ।
श × क्षी-मै-सा-कात । √क्रन्द् १/६८ वत् ।
आह्वानरोदनयोः—
जै-शा ।
रोदनाह्वानयोः—हे ।
रोदने आह्वाने—वो ।

क—√क्रन्द् १/६८ प्रेक्षणीयः ।
ग—(अप्सरसः) याः क्लन्दास्तमिषीचयोऽक्षकामाः—अ. वे. २, २, ५ ।

√क्लन्द् (क्लदि) १/७६७ वैक्लव्ये (आ)
मै-श-जै-कात × क्षी-सा-च-शा हे ।
वैकल्ये इति चन्द्रः— √क्रन्द् १/७६६ वत् ।
क्षी । क्षी-सा-काकृ ।
वैकल्यविकलत्वयोः—
वो ।
विक्लवः=कातरः—क्षी ।

ग—क्लन्दते—अशि. ४, १०; वट्ठ. ३१६ : ४ ।

√क्लम् (क्लमु) ४/९४ ग्लानौ (प) √क्रम् (क्रमु) १/ पादविक्षेपे (प) ।
श क्षी-मै-सा-च-काकृ-कात-हे-वो । √ग्लै १/ हर्षक्षये (प) ।
ग्लाने—जै-शा । √श्रम् (श्रमु) ४/ तपसि खेदे च (प) ।

क—क्लॆम्—, क्लेम्=शिथिलम्, ग्लानम्—जू. पॉकर्नीः । पु. ब्रेटॉ. क्लॅन्व्=व्याकुलम्, अस्वस्थम्; लैति. क्लेमेन्स्=मृदु । पु. इरि. क्लम्—कुष्ठिन्—वा. पॉकर्नीः ।

ग—आक्लान्तम्—पै. ११, २, ७ । क्लामयति—अशि. ४, १०; वट्ठ. ३१६ : ४ । क्लान्ता-वा. रा. २, ४२, १९=पीडिता (तिल.) ।

घ—किलमति—विनय. २, १५; किलमेति (ना. धा. किलम् इत्यस्य)—जातक १, ११५ ।

ङ—√किलम्म (अक)=ग्लानौ । किलम्मइ—कप्पू. ।

√क्लिद् (क्लिदू) ४/१२९ काक्र-कात ×,श	आर्द्रभावे (प) क्षी-च-जै-शा-हे । आर्द्रीभावे—मै-सा । क्लेदे—वो ।	√क्लिन्द् ४/७३ आर्द्रभावे (प) काक्र । √क्लिल् ६/ शैत्यक्रीडनयोः (प) काक्र । √स्विद (ष्विदा) ४/ गात्रप्रक्षरणे (प) √स्विद् (ञिष्विदा) १/ स्नेहमोहनयोः (प) ।

क—क्लॉन् =आर्द्रत्वे । लिथु. क्लुनेस्=पल्वलम्, पङ्कः, पु. आइस्.पु. गाथि.

ह्लन्द्=मूत्रम् । लिथु.—स्क्लिस्तु, स्किल्न्दौ, स्क्लिस्ति=आपूरे—वा. पॉकर्नीः ।

ग—क्लिद्यते-१ आ. १। तेन क्लिद्यति हि व्रगः-सुश्रु.२,२३,१२ । क्लिन्नः,-न्नम्-पै. १६,१२४,४ ।

+√क्लिन्द्(क्लिदि)१/१५ श×	परिदेवने (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे । रुदि—वो	√क्रन्द् (क्रदि) १/ आह्वाने रोदने च (प) । √क्लन्द् (क्लदि)१/ आह्वाने रोदने च (प) । √क्लन्द् (क्लदि) १/ वैक्लव्ये (आ) । √क्लिन्द् ४/७३ आर्द्रभावे (प) काक्र ।

√क्रन्द् १/७६६; √क्लन्द् १/६९ इत्याभ्यां जातो विकासः स्यादस्य ।

+√क्लिन्द्(क्लिन्दि)१/७० श×	परिदेवने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे । रुदि—वो ।	पूर्ववत् ।

परस्मैपदार्थं पृथक् संख्यातः स्यात् । तत्रोभयपदित्वादेव सिद्धम् ।

√क्लिश् (क्लिश) ४/५० उपतापे (आ)

श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । उपतपे—वो ।

√कल् (कल) १/ शब्दसंख्यानयोः (आ) । √क्लिद् (क्लिदू) ४/आर्द्रभावे (प) । √क्लिन्द् (क्लिदि) १/ परिदेवने (आ) । √क्लिश् (क्लिशू) ९/ विबाधने (प) ।

क—क्लाङ्कु्=पीडने, निष्पीडने । लिथु.क्लिसे = क्लेशः । च. स्लॉ. क्लेस्त् =संदंशिका, उपरितनदंष्ट्रास्थि, क्लेरितुति । cech. (बोहें.)–स्–क्लेस्नॉउति = दार्ढ्येन ग्रहणे, पीडने, निष्पीडने–वा. पॉकर्नीः ।

ग—क्लिश्यते–यो. २,२५; तव हेतोर्वयं बाले परिक्लिश्यामहे–वा. रा. ५,२५,३२ । क्लिश्यसे प्राकृतो यथा– वा. रा. ४,१६,२७ । त्रयः परार्थे क्लिश्यन्ति–मनु. ८,१६९ ।

घ—किलिस्सति–थेरगाथा १,९५४ ।
ङ—√किलिस (अक)=खेदे, श्रान्तौ । वक्र–किलिसंत–पउम. २१,३८ ।
ङ—√कीस (अक)=खेदे, श्रान्तौ । कीसंति–उत्त. १९,१५; वै. ३३ ।
ज—√केसेद्' =अवरोधे, विघ्ने ।

√क्लिश् (क्लिशू) ९/५० विबाधने (प)

श क्षी-मै-सा-जै-काकृ-कात-शा-हे । बाधने—च । विबाधे—वो ।

√क्लिश् (क्लिश) ४/उपतापे (आ) । पूर्ववत् ।

क—पूर्ववत् ।

ग—सुदृढं क्लिश्नाति–मभार. २,२३,५१ । क्लिश्नाति–सुश्रु. १,१८१,२०; कुमारसं. २,४० । क्लिश्नाति लब्धपरिपालनवृत्तिरेव–शाकु. १०३ ।

ज—√केसेद्' =अवरोधे, विघ्ने ।

+√क्लीव् (क्लीबृ) १/३७८ अधाष्टर्ये (आ) क्षी-मै-सा-काकृ। आधाष्टर्ये—च-कात-शा-हे। बान्तवत् (=अधाष्टर्ये) —वो।

√क्लीव् १/ अधाष्टर्ये (आ) वो।

जै—√क्लीव् (क्लीवृङ्).... अधाष्टर्ये [च]—जै।

क—केल्-, केला=खण्डने, घटने, भङ्गे। ओष्ठ्यविस्तारः-लिथु. क्लुग्वस्=पङ्गु, निर्बलम्-वा. पॉकर्नीः।

ग—क्लीवक्लीबं त्वाकरं वध्रे-अ. वे. ६,१३८,३; वा. सं. ३०,५। क्लीबः-मा. ३०,२२; का. ३४,४,४; तै. २,३,३,४; मै. २,४,२; काठ. १२,११। विक्लीवते-मभाष्य. ३,१,११. २१[१०]; महाभाष्यप्रयोगेणायं वकारान्तोऽपीति वोपजैनेन्द्रमतं पुष्णाति।

(छ-√किलपना-(<क्लीवनम्)>√कलपना=दुःखे, विलापे।

+√क्लु (क्लुङ्) १/९६६ गतौ (आ) इत्येके-मै

<√प्लु (प्लुङ्) गतौ (आ)। √क्रु (क्रुङ्) १/९३९ गतौ (आ) इति। क्वचित् पठ्यते-सा।

क्लवः, क्लब इति बवयोरभेदाद् द्रष्टव्यम्-सा ९३९।

क—क्लोइ तथा क्लाउ=ग्रहणम्, कौटिल्यम्-वा. पॉकर्नीः।
क—प्ल्(ए)उ, प्लेउ-टिओ=क्लोमन्। लैति. पुल्मो=क्लोमन्-वा. पॉकर्नीः।

ग—क्लवितमिऽव—संब्रा. १। क्लोशम् अनुष्वणि-ऋ. ६,४६,१४. [क्लु (=क्रु) श् (आह्वाने)] विक्लवः=कातरः। विक्लवन्ते दिवि ग्रहाः-श्रीभोजः......। विक्लवं दूतमासाद्य-वा. रा. ५,२,३९। वैक्लव्यम्-वा. रा. ५,२,४१। क्लोमहृदयम्-शब्रा. ४,५,४,६; कात्या.श्रौ. ६,७,११।

+√क्लेव् (क्लेवृ १/५०१ सेचने (आ) इत्यपि—सा। क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×

<√ग्लेव् (ग्लेवृ) सेचने (आ) सा। √केव् (केवृ) १/ सेवने (आ)-क्षी।

√खेव् (खेवृ) १/ सेवने (आ)-क्षी।

√क्लिद् (क्लिदू) ४/ आर्द्रीभावे (प)।

नेहैकमताः सर्वे वैयाकरणाः। सायणोऽपि पाठान्तरमेवोद्धरति न तु स्वकीयं मतम्। एवं सत्यप्ययं धातुः कमपि सम्बन्धं दर्शयति-√केव् >(ककारोत्तरलकार-प्रवेशे)>√क्लेव्>√ग्लेव्। अत्र दण्डक-गत-धातून् केचन क्षीरादयः सेवनार्थकान् वदन्ति केचिच्च मैत्रेयादयः सेवनार्थकान्। √क्लेव् धातुः √क्लिद् ४/ आर्द्रीभावे (प) इति धातुना महत् सादृश्यं धत्ते। एतन्निष्पन्नक्लेदशब्दस्य दकारावकाशे रुद्धे सति 'क्लेव' इति जायते। अस्तीहैव किमपि साङ्कर्यम्।

+√क्लेश् (क्लेश) १/६०२ श× — च व्यक्तायां वाचि (आ) क्षी-मै-जै-शा। सभ्याः पृथक् पेठुः-क्षी। भाषणे—क्षी। अव्यक्तायां वाचि-सा। 'बाधने' इति दौर्ग-सूत्रम्—क्षी। क्षी-सा-च-काकृ-कात। विबाधने व्यक्तायां वाचि च—हे। वदे उपतपे—वो।

√भिक्ष् (भिक्ष) १/ क्लेशे च व्यक्तायां वाचि (आ)।

√क्लिश् (क्लिश) ४/ उपतापे (आ)।

√क्लिश् (क्लिशू) ९/ विबाधने (प)।

तत्तद्देशप्रसिद्धार्थानां पृथङ् निर्देशः-क्षी।

ग—[क्लेशते न वृथा वाक्यम्-हला. ९३] व्यक्तवचने निर्देशः। वस्तुतोऽत्र निर्णयः दुष्करः। "तद्देशप्रसिद्धार्थानां पृथङ् निर्देशः" इति क्षीरस्वाम्युक्ति-र्निकामं भाति।

√क्वण् (क्वण) १/४४२ श× — शब्दार्थः (प) क्षी-मै सा-च। शब्दे—जै-काकृ-कात-शा-हे-वो।

√कण् (कण) १/ शब्दार्थः (प)।

√कुण् (कुण) ६/ शब्दोपकरणयोः (प)।

. शब्दे—ह्वि। √खुण् १/२०७J शब्दे (प) काकृ।
√गुण् १/२०७iii शब्दे (प) काकृ।

ग—क्वणति–सौ. २,१०। क्वाणनम्–छाग. २५:१२; कुणारुमिति–निरु. २,२.५ (√क्वण् शब्दार्थः–कुणारुः—दुर्गाचार्यः)।

ङ—√कण (सक)=शब्दे। वकृ–वज्जा. ६६।

√क्वथ् (क्वथे) १/८३० निष्पाके (प)
श× क्षी-मै-सा-च-कात-शा-हे।
निष्पचने—जै-वो।
पाके—काकृ।

क—कु अत् (ह्)=फेनोत्पादने, क्वथने। पु. बुल्गा. (स्)क्युस्नोति–, क्युसे्ति=अम्लीभावे। लैति. कुअतियो=उत्तेजने, चालने–जू. पॉकर्नीः।

ग—क्वथन्—तैआ. ५, ११, ४। यवागूं क्वथिताम्—मनु. ६, २०; सुश्रु. २, ४१८, ५।

घ—कठति=क्वथने—विनय. १, २०५।
घ—√कुथ् (कुथ)=क्वथने—जातक ६, १०५ (कुथन्तो)।
ङ—कढ (सक)=क्वथने। वकृ—कढमाण—पि. २२१।
छ—√काढ़ना—पाके।

+√क्षज् (क्षज) १/७६२ गतिदानयोः (आ) इति कौशिकः—क्षी क्षी-सा। दागत्योः—वो। <√क्षञ्ज् (क्षजि) गतिदानयोः (आ)।
मै-श-च-जै-काकृ-कात-शा-हे।
√क्षज् १०/२८ क्षान्तौ (प) कात।

वैदिकेन हिंसाविभाजनदानार्थकेन√क्षद् (आ)-धातुनाऽस्य सम्बन्धः साध्यताम्।

+√क्षञ्ज् (क्षजि) १/७६२ गतिदानयोः (आ) मित् >√क्षज् (क्षज) गतिदानयोः (आ) इति कौशिकः—क्षी।
श × क्षी-मै-सा-जै-शा-हे।
गतौ—च। √जङ्क्ष् १/१००१ गतिदानयोः (आ) हे;

	दाने गतौ च—काकृ-कात। दागत्योः—वो।	गत्यां दाने च (आ) वो। √खङ्ग् १/३८ ॥ गतौ (प) काकृ। (√स्वङ्ग इत्युचितम्। भातीयं लैपिकी त्रुटिः। कातन्त्रेऽपि √स्वङ्ग् पठ्यते)। √क्षञ्ज् (क्षजि) १०/८४ कृच्छ्रजीवने (प)।

√क्षज् >√क्षञ्ज् (वर्णविपर्ययः)>√जञ्ज्—हे १/१००१; वो; इत्यस्य लभ्यते विकासो न तु प्रयोगः। पुनरयं चुरादौ कृच्छ्रजीवनार्थको जातः।

√क्षण् (क्षणु) ८/३ श	हिंसायाम् (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। वधे—वो।	>√क्षिण् (क्षिणु) हिंसायाम् (उ) इति च दुर्गः—क्षी। √क्षण् १/२०७gg शब्दे (प) काकृ।
√क्षण् (क्षनु....... क्षी-मै-च-जै-काकृ-श कात-शा ×	हिंसायाम् (उ) इति धातुपारायणे—मै। मै-सा-हे। वधे—वो।	√क्षि ५/ हिंसायाम् (प)। √क्षि (क्षिष्)९/ हिंसायाम् (प)।

क—क्षॆन्=क्षतौ, हिंसायाम्।

ख—अक्स्सुत=अक्षतम्—वा. पॉकर्नीः।

ग—क्षणुते-शब्रा. ४, ४, ३, १३। क्षण्वीत—तैब्रा. ३, २, १०, १।

ङ—√छण (सक)=हिंसायाम्। छणे—आचा।

ङ—√छण (सक)=छेदने। छणह—सूअ. २, १, १७।

अ पा णि नी यः	√क्षद् (क्षद)	संवृतौ (आ) सौ. धा.—वो। हिंसायां विभाजने दाने च—वै. प. को। विभाजने—ह्वि.।	√खद् (खद) १/ स्थैर्ये हिंसायां च (प)। √क्षज् (क्षज) १/ गतिदानयोः (आ)।

ग—होतेव क्षदसे प्रियम्—ऋ. १, २५, १७; क्षदामहे—शौ. (अ. वे.) १०, ६, ५; पै. १६, ४२, ५।

√क्षम् (क्षमूष्) १/४३५	सहने (आ)	√शम् (शमु) ४/उपशमे (प)।
श ×	क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।	√क्षम् (क्षमूष्) ४/ सहने (प)।
	मर्षे—वो।	क्+√शम् ४=√क्षम्- इति वागीशः।

क—घुएम्-, घुओम्-, घम्=क्षमा (पृथिवी)—वा. पॉकर्नीः।

ग—अभिक्षमध्वम्—ऋ. २, २८, ३। क्षमन्ते—गोब्रा. २, ५, ९। क्षमते—मनु. ८, ३१३। क्षमस्व—वा. रा. ४, २६, २५। क्षमते—मभार. ३, १०३५। क्षमेत्—शि. ५, ३९।

ङ—√खम (सक)=क्षमायाम्, (२) सहने। खमइ—उवर. ८३, महा.।

ङ—√खाम (सक)=क्षमायाचने। खामेइ—भग.।

ज—खमा=क्षमायाम्।

√क्षम् (क्षमूष्) ४/९३	सहने (प)	
मै-श-जै-शा-हे-वो ×	क्षी-सा-च-काकृ-कात।	पूर्ववत्।
√क्षम् (क्षमू)......	सहने (प) इति	
श-च-काकृ-कात×	सभ्याः—क्षी।	
	क्षी-मै-सा-जै-शा-हे।	
	मर्षे—वो।	

ग—क्षम्यताम् (कर्मणि ?)-सार. २९२ : २१।

छ—√क्षमना * } =क्षमायाम्।
छ—√क्षमना † }

√क्षर् (क्षर) १/८३५	सञ्चलने (प)	क्+√शल् (शल) १/ चलनसंवरणयोः (आ)=√क्षल्।
श×	क्षी-मै-सा-च-जै-काकृ-शा-हे-वो।	√क्षल् (क्षल) १/ सञ्चये,
	चलने सञ्चलने च—कात।	च=सञ्चलने (प)।

√शल् (शल) १/ आशु-गमने (प)।
√शल् (शल) १/गतौ (प)।

क—गुहएर्=प्रवाहे, सञ्चलने।

ख—च्जुरइति=क्षरति।

ग—क्षरन्ति–ऋ. १,७२,१०; क्षरति–ऐआ. २,२,२; तैब्रा. २,४,६,१२; क्षरते–अना २५। क्षरते–मभार. ३,२७,२५=प्रकाशयति (नील.)।

ङ—√खर (अक)=श्च्योतने, (२) नाशे। खरइ–विसे. ४५५।

ङ—√खिर (अक)=श्च्योतने। वकृ–खिरंत–पउम. १०।

ङ—√झर (अक)=श्च्योतने। वकृ–झरंत–कुमा., सुर. ३,१०।

छ—√छरना (<क्षरणम्)=श्च्योतने।

छ—√झरना * † (<क्षरणम्)=श्च्योतने, जलधारादिपाते।

छ—√झड़ना (<क्षरणम्)=श्च्योतने, बिन्द्वादिरूपेण पाते।

+√क्षल् (क्षल) १/८३६	सञ्चये, च=संचलने (प)	√क्षर् (क्षर) सञ्चलने (प)।
मै-श-च-जै-काकृ-	क्षी।	पूर्ववत्।
कात-शा-हे×	सञ्चलने—सा।	√खल् (खल) १/ सञ्चये, च=चलने (प)।
	√क्षर् इत्यत्र सायण आह–अत्र√क्षल् सञ्चलने इति कचित् पठ्यते चाले चये—वो।	√स्खल् (स्खल) १/ चलने (प)। √खल्ल् १/२४८ b चलने (प) काकृ।

छ—√छलकना (<क्षलनम्)=सञ्चलने, पात्रात् सोच्छालं (जलादेः) वहिष्पतने।

छ—√झलना (<क्षलनम्)=सञ्चलने, व्यजनादिचालने।

√क्षि १/२३३	क्षये ऐश्वर्ये च (प)	√क्षि ५/ हिंसायाम् (प)।
श-जै-शा×	(यु. मी. सं. 'क्षये' इत्येव)।	√क्षि (क्षिष्) ९/ हिंसायाम् (प)।
	क्षी-हे।	
	क्षयैश्वर्ययोः—वो।	√क्षि १/ ऐश्वर्ये (प)
	क्षये—मै-सा-च-कात-शा-हे।	इत्येके–क्षी।
(काकृ-√क्षी)	(मै-सा)-काकृ।	√क्षै १/ क्षये (प)।
		√सै १/ क्षये (प)।
		√जै १/ क्षये (प)।

क—क्षे (इ)–, क्षु (इ) = प्राप्तौ, अर्जने, जये ।

ख—अवे. क्सस्युयति = क्षयति–जू. पॉकर्नीः । क्सस्यु येइति = क्षयति (शक्तौ)–वा. पॉकर्नीः ।

ग—त्वमस्य क्षयसि यद्ध विश्वम्–ऋ. ४,५,११; यो विश्वस्य क्षयति–ऋ. ५,४२,११ । तेजश्च शोकः क्षयति–वा. रा. ४,६,१४ ।

ङ—√ खि (अक) = क्षये । कर्म–खिज्जइ–स. ६८४ ।

ङ—√ झिज्झ (अक) = क्षये । कवक्त–झिज्झंत, झिज्जमाण (<क्षीयमाण)–से. ५, ५८; उप. ७२८ टी. ।

छ—√ छीजना (<क्षीय [माणः]) = क्षये, नैयून्ये ।

√ क्षि १/९३३ ऐश्वर्ये (प) इत्येके–क्षी । पूर्ववत् ।
मै-सा-श-च-जै-काकृ- क्षी-हे-वो ।
कात-शा ×

क—,ख—पूर्ववत् ।

ग—क्षयति–ऋ. १,३२,१५; मै. ४,१४,१३; शौ. ५,२,८ । ०क्षयात्–मभार. १२, ३, ३०३, २ = ०सामर्थ्यात् (नील.) ।

'क्षयैश्वर्ययोः' इति पूर्वधातुनैव 'ऐश्वर्यार्थस्य' गतार्थत्वात् पृथक् संख्यातिर्न समीचीना ।

√ क्षि ५/२९ हिंसायाम् (प)
श-जै-काकृ-कात-शा × क्षी-मै-सा-हे-वो ।
च ?

√ क्षिण् (क्षिणु) ८/ हिंसायाम् (उ) इति दुर्गः—क्षी ।
√ क्षि (क्षिष्) ९/ हिंसायाम् (प) ।

क—कुहुसेइ = दौर्बल्ये, नाशे–वा. पॉकर्नीः ।

ग—सिंही हैनं भूत्वा क्षिणोति—शब्रा. ३,५,१,२५ । क्षिणोमि–तैआ. २,५३ । अक्षिण्वन् योगतस्तनुम्–मनु. २,१०० ।

√ क्षि ६/१२६ निवासगत्योः (प)
श क्षी-मै-सा-जै-काकृ-कात-शा-हे । पूर्ववत् ।
निवासे—च । क्षियति–निघण्टौ
वासगत्योः—वो । २/१४ गतिकर्मा ।

क—कु सेइ् = निवासने, स्थापने ।
ख—अवे. सुएइति = क्षितिः, सोइथ्र = क्षेत्रम् ।

ग—क्षियन्ति सुक्षितिम्—ऋ. ७,७४,६। क्षेति–ऋ. १, ८३, ३; कौ. २, ५४८। क्षियते–काठ. १९,३। क्षयम्–मभार. ८१,१,२,२ = गृहम्–(नील.)।

√क्षि (क्षिष्) ९/३५ हिंसायाम् (प)
मै-सा-जै-काकृ × क्षी-कात-शा-हे-वो । पूर्ववत् ।
च ?

क—√क्षि ५/२९ वत् ।

ग—क्षिणाति–ऋ. १०,२७,१३। क्षिणन्ति शत्रून्–ऋ. ६,७५,७। क्षिणामि–अ. वे. ३,१९,३।

+√क्षिण् (क्षिणु) ८/३ हिंसायाम् (उ) इति
श-च-शा × दुर्गः—क्षी ।
क्षी-मै-सा-जै-काकृ-कात-हे ।
वधे—वो । पूर्ववत् ।
√क्षिण् (क्षिनु) ८/४ हिंसायाम्—मै ।
क्षी-श-च-जै-काकृ-कात-
शा ×

क—पूर्ववत् ।
ग—क्षिणुयात्–काम्रा. २, २, ४, ५; आक्षिणकेभ्यः–मै. २, ९, ९।

'आक्षिणकेभ्यः' इत्यत्र नूनं √क्षिण् धातुरवधेयः। तिङन्तरूपाणि त्वस्य √क्षि ५/२९ वदेव भवन्ति–इति केचनेमं तानादिकं नाङ्गीकुर्वन्ति। यदाह नागेशभट्टो बृहच्छब्देन्दुशेखरे—"क्षिणु इत्यादि प्रयोगास्तु "बहुलमेतन्निदर्शनम्" इति √क्षि धातुं स्वादावप्यङ्गीकृत्य समाधेयाः–इत्यन्ये"–पृ. सं. १७९२। एवं सत्यप्येष 'आक्षिणकेभ्यः' इत्यादिसिद्धयर्थं तनादौ स्वीकरणीयो भवत्येव।

+√क्षिप् (क्षिप) ४/१३ प्रेरणे (प)। √क्षि ६/ निवासगत्योः (प)।
श क्षी-मै-सा-च-जै-काकृ- √क्षिप् (क्षिप) ६/ प्रेरणे (उ)।
कात-शा-हे ।
नुदि—वो ।

√क्षिब् (क्षिबु) ४/ निर-
सने (प)।
√क्षिप् १०/२६० प्रेरणे (प)
काक्ट । २४१···कात ।

ग—क्षिप्येत्–छान्दो. ८, ६, ५ [इति निसा.]; वासुकेरथ नागस्य सहसा क्षिप्यतः सुरैः–मभार. १, ११२६ ।

क्षीरस्वामी √क्षिप् धातोर्दैवादिकं पाठं नवीनं मन्यते । तेन प्रमाणं नोक्तम् । सुधाकरस्तु धातोरेतस्य दैवादिकं पाठमयुक्तं घोषयति पारायणिकानां मतेन– "पारायणिकैः क्षिपेरिह पाठोऽयुक्त इति सुधाकरेण भूसूत्रे प्रतिपादितम्"–धा. वृ. पृ. २८४। (४/१४) तेनाप्यस्यासाङ्गत्यहेतुकं प्रमाणं नोद्धृतम् । मन्ये साहित्ये द्वित्रा एवोपलभ्यन्ते प्रयोगाः, इति तेषामनुपलम्भादुपन्यस्तमिदं स्यात् ।

छ—√छीपना=कण्टकनद्धस्य मत्स्यस्य वडिशेन बहिः क्षेपणे ।

√क्षिप् (क्षिप) ६/५ श — प्रेरणे (उ) । क्षी-मै-सा-च-जै, काकृ (प), कात-शा-हे । नुदि—वो । — पूर्ववत् ।

√क्षिप् ९/२९८ प्रेरणे (उ)
काकृ ।

क—क्सेइप्–, क्सेइब्=प्रक्षेपणे । रसन्–सिृबति = क्षिपति–जू. पॉकर्नीः ।

ग—अव क्षिपन्–ऋ. १०, ६८, ४; शौ. २०, १६, ४ । अभिक्षिपन्–ऋ. ५, ८३, ३ । क्षिपसि–शौ. ९, १, १० ।

ङ—√खिव (सक)=१–क्षेपणे, २–प्रेरणे, ३–पातने, वेशने । खिवइ, खिवेइ–महा. । कवक्त–खिप्पंत–काल. ।

छ—√खेवना }
छ—√खेना } (<क्षेपणम्)=नौचालने, (२) यापने ।

छ—√खेपना (<क्षेपणम्) }
छ—√छिपना (<क्षेपणम्) } =निलयने ।

छ—√झेपना, √झेंपना (<क्षेपणम्)=व्रीडायाम् ।

+√क्षिब्(क्षिबु)४(१/३७९) निरसने (प) । मै-सा-श-च-जै-काकृ-शा- क्षी-कात । हे-वो ×

√क्षिव् (क्षिवु) १/ निर-
सने (प) ।
√क्षिव् (क्षिवु) ४/ निरासे
(प) वो ।

√क्षिप् (क्षिवु) ४/४b
निरसने (प) च-काक्ष।
२४ हे।
शेषः पूर्ववत्।

ङ—√छिम्भ=असने। क्षिम्भंति–सूअ. १, ५, २, १२।

+√क्षिरि ५/२९	हिंसायाम् (प) इति दुर्गः—क्षी (यु. मी. सं.)।	√क्षि ५/ हिंसायाम् (प)। √चिरि ५/ हिंसायाम् (प)। √जिरि ५/ हिंसायाम् (प)।

√क्षि+√चिरि=√क्षिरि, इति धातुद्वयसंयोगभ्रमे, 'चि'-वर्णे त्यक्ते चायं धातुः स्याज्जातः कैश्चिदप्यस्मृतः।

+√क्षिव् (क्षिवु)१/५६६ श-काक्ष×	निरसने (प)इति चन्द्रः—क्षी क्षी-मै-सा-च-जै-कात-शा-हे। निरासे—वो।	√क्षेव् (क्षेवु) १/ निरसने (प) इति चन्द्रः—सा। √क्षिप् ४/ प्रेरणे (प)। √क्षिप् ६/ प्रेरणे (प)। √ष्ठिव् (ष्ठिवु) ४/ निरसने।
+√क्षी (क्षीष्) ९/३६ क्षी-श-च-काक्ष-कात-शा-वो ×	हिंसायाम् (प) मै मै-सा-हे।	√क्षि ५/२९ वत्।
+√क्षीज् (क्षीज)१/२३३ श×	अव्यक्ते शब्दे (प) क्षी-मै-सा-च-कात-हे। शब्दे—जै-शा। हिक्कने—वो।	√सिञ्ज् २/४९ अव्यक्ते शब्दे (आ) काक्ष। √शिञ्ज् २/४७ शब्दे (आ) च।
(काक्ष√कीज् [कीज])··· स्यात् स्खलतिः।	सखेदस्वनने—मै। अव्यक्ते शब्दे—काक्ष।	√कूज् (कूज) १/२१८ अव्यक्ते शब्दे (प)। शेषः १/२१८ धातौ द्रष्टव्यः।

क्+√शिञ्ज् २/१७>√क्षिञ्ज्>√क्षीज् इति स्यादस्य व्युत्पत्तिः।

+√क्षीब् (क्षीबृ) १/३७९ शX	मदे (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे । दर्पे—वो ।	√क्षीब् (क्षीबु) ४/४ निरसने (प) च ।

(जै-√क्षीव् [क्षीवृ]... मदे—जै ।

ग—क्षीवं राक्षसशार्दूलम्–वा. रा. ५,१०,१३ । उत्तरधातोरभिन्नोऽयं बवयोरात्मनेपद–परस्मैपदयोश्च भेदार्थं पृथङ् निर्दिष्टः ।

+√क्षीव (क्षीवृ) १/५६६ मै-श-च-जै-कात्-शाX	निरसने (प) क्षी-सा-काकृ । निरासे—वो । हे ? निरासः = फुत्कारः— इति भट्टमल्लः ।	<√क्षीव् (क्षीवु) निरसने (प) इति चन्द्रः—क्षी । √ष्ठिव् (ष्ठिवु) १/ निरसने (प) । √क्षेव् (क्षेवु) १/५६० निरसने (प) इति चन्द्रः—सा । पूर्ववत् ।

क—स्प् (ह्) इएउ–ः स्पिउऊ–, स्पिउ=ष्ठीवने—वा. पॉकर्नीः ।

ग—क्षीवाः कुर्वन्ति हास्यं च कलहांश्च तथापरे–वा. रा. ५,६०,१२; क्षीवन्–भा. पु. ५,१७,२०; क्षीवता–कथासरि. ८,२,५५ (१३,१०) । क्षीवस्यान्तःकरणकरिणः –भर्तृ. ३,८२ ।

√क्षु (टुक्षु) २/२५ श	शब्दे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । क्षुतौ—वो । छिक्काशब्दे—ह्वि. ।	√कु (कुङ्) ६/ शब्दे (आ) √कु २/शब्दे (प) । √कु+√शु १/ गतौ (प) =√क्षु । कु+√सु (षु) २/ प्रसवैश्वर्ययोः (प)=√क्षु √क्षु १/५५२f गतौ (आ) काकृ । √खु (खुङ्) १/ शब्दे (आ)।

क—स्कॉइ–, स्कोउ–, क्सॉइ–, क्सोइ=छिक्काशब्दे । पु. लिथु. स्किऔदेति=छिक्काशब्दे–जू. पॉकर्नीः ।

ग—क्षुमन्तः-ऋ. १,३०,१३; तै. १,७,१३,५; मै. ४,१२,४; काठ. ८,१७; कौ. १,१५३। क्षवम् (=छिक्का)-शौ. १९,८,५; क्षुवीत-मनु. ४,४३; क्षविता-आश्व. गृह्य. ३,६; सुश्रु. १,३८,१३; क्षुवतस्तु मनोर्जज्ञे-भा. पु. १,६,४।

√क्षुद् (क्षुदिर्) ७/६ श	संपेषे (उ) क्षी-शा-हे। सम्पेषणे—मै-सा-च-काकृ-कात। सम्प्रेक्षणे—जै। क्षुदि—वो।	क्षोदति-निघण्टौ २/१४—गतिकर्मा।

(क—क्सॉइद=तौच्छ्ये, सञ्चूर्णने, पीडने-जू. पॉकर्नीः)

ग—अक्षोदयत्-ऋ. ४,१९,४; क्षोदन्ते-५,५८,६। क्षोदन्ति-ऋ. ७,५८,४। तैब्रा. २,४,५,२। वातरुग्ण इव क्षुण्णः-मभार. ३,६७८। क्षुण्णाद् आमनोर्वर्त्मनः परम्-रघु. १,१७।

छ—√खोदना=खनने।

√क्षुध् (क्षुध) ४/७७ श	बुभुक्षायाम् (प) क्षी-मै-सा-च-काकृ-कात-शा-हे। बुभुक्षणे—जै। क्षुधि—वो।	क्+√शुध् (शुध) ४/ शौचे (प)=√क्षुध्। शौचम्=नैर्मल्यम्-क्षी। विकाररराहित्येन बुभुक्षा जायते।

ग—क्षुध्यति-काठ. २४,७; क. ३७,८। अक्षुध्यत्-तै. ७,४,३। क्षुधत्-शौ. २,२९,४।

ङ—खुधा=बुभुक्षा-धर्मसं. १०६२।

√क्षुभ् (क्षुभ) १/७४२ श	सञ्चलने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। सञ्चले—वो।	क्+√शुभ् (शुभ) १/ दीप्तौ (आ)।
सञ्चलनम्=	रूपान्यथात्वम्—क्षी।	√क्षुप् ९/३० गर्वे (उ) काकृ, सौ धा.—वां। क्षुम्पति-निघण्टौ २/१४-गतिकर्मा। क्षुम्पम्-निरु. ५,१७,१ =स्पृष्टमात्रं

क्षुभ्यते=चलति तस्मा-
त् क्षुम्पम्=क्षोभणम् इति
न्याय्यम्-दुर्गाचार्यः।

क—क्सॉइभ्=कम्पने, सञ्चलने-जू. पॉकर्नीः।

ग—क्षोभणः-ऋ. १०,१०३,१। क्षोभते-छान्दो. ३,५,३; चुक्षुभे द्विषतां मनः-रघु. ४,२१। =कालुष्यं प्राप (सं.)।

ङ—√ खुभ (अक) =भये, सम्भ्रमे। खुभइ-रयण. १८।

छ—√ खुभना=प्रवेशे।

छ—√ खुभराना=उपद्रवार्थं चङ्क्रमणे।

√ क्षुभ् (क्षुभ) ४/१२६ सञ्चलने (प)
श क्षी-मै-सा-च-जै-काकृ-काত-शा-हे। पूर्ववत्।
सञ्चले—वो।

क—पूर्ववत्।

ग—क्षुभ्यसि-वा. रा. २,३४,४६=मर्यादां त्यजति (तिल.)। सुश्रु. १,२७७,२। क्षुभ्यसि भिक्षुकि-मभार. १,३२८९।

ङ—√ खुब्भ (अक)=क्षोभे, निमज्जने। वक्र-खुब्भंत-ठा. ७-पत्र. ३८३।

ङ—√ छुब्भ (अक)=विचलने। क्षुब्भंति-पि. ६६।

√ क्षुभ् (क्षुभ) ९/४७ सञ्चलने (प)
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। पूर्ववत्।
सञ्चले—वो।

क—पूर्ववत्।

ङ—√ खोभ (सक)=विचालने। (प्रेर.)-खोभेइ-महा.।

ङ—√ खोह (सक)=विचालने (प्रेर.)-खोहइ-भवि.।

छ—√ छोभना *
छ—√ छोहना * } =विचलने, चित्तचाञ्चल्ये।

+√ क्षुर् (क्षुर) ६/६२ विलेखने (प) √ कृष् (कृष) ६/ विलेखने (प)
श× क्षी-मै-सा-च-जै-काकृ-कात-शा। >√ क्षुर्।
√ खुर् (खुर) ६/ विलेखने (प)

विखनने—हे। √छुर् (छुर) ६/ छेदने (प)।
विलेखे खनने—वो।
विलेखनम् = छेदः—क्षी।

क—कॆस् = विलेखने। क्स्-ऑइ—वा. पॉकर्नीः।

ग—शशः क्षुरं प्रत्यञ्चं जगार-ऋ. १०,२८,९। क्षुरा अधि-ऋ. १,१६६,१०। क्षुरः-अ.वे. २०,१२७,४। वज्रो वै क्षुरः-शब्रा. ३,१,२,७। क्षुरेण निशितेन च। शिर उत्कृत्य-मभार. १,१३४,९०। क्षुरः = शरः।

ङ—छुर = छेदने-वा. १२; पउम. २८,२८; खुर (<क्षुरः) = क्षुरिका-णाया. १,८; प्रयौ. १०७।

छ—√करोना (<क्षुरणम्) = विलेखने (खरोचना-हिं.)।
छ—√खौरना (<क्षुरणम्) = तिलकरचनायाम् (विलेखने)।
छ—(सपरना)√खोरना—बुं. ख. (<क्षुरणम्) = तिलकरचनायाम्। तिलकस्य स्नानोत्तरक्रियात्वात् स्नानतिलकयोश्चातिसम्बन्धादयं स्नानार्थेऽपि संक्रान्तः क्वचित्(व्रजप्रदे. बुं. ख.)-'यमुना चल खोरें'-सूरदासः।

√क्षै १/८९८ क्षये (प) √क्षि १/ क्षये ऐश्वर्ये च (प)।
श× क्षी-मै-सा-च-जै-काकृ- √सै १/ क्षये (प)।
कात-शा-हे-वो। √जै १/ क्षये (प)।
√क्षा ४/ दीप्तौ, दाहे—ह्वि.

क—कुसा=दीप्तौ, दाहे-जू. पॉकर्नीः। कुसे (इ) अथवा कुस् (इ)=दाहे, दीप्तौ-जू. पॉकर्नीः।

ख—क्स्सुयेइति = (क्षायति) शक्तौ, अधिकारे-वा. पॉकर्नीः

ग—(अप) क्षायति-मै. १,८,९; काठ. ३५,१७; क. ४८,१५; क्षायतः-मै. १,४,१३।

घ—ओक्खायति (<सं. अव+क्षायति ?; अव+खायति = खदने)-संयुत्त. ४,१४४ sq।

√क्ष्णु २/२६ तेजने (प) √क्षु २/ शब्दे (प)।
श क्षी-मै-सा-च-जै-काकृ- √शान् (शान) १/ तेजने (उ)।
कात-शा-हे-वो। √कु २/ शब्दे (प)।
√स्वन् (स्वन) १/ शब्दे (प)
√कु+√स्वन् = √क्ष्णु।

क—√द्रष्ट. क्षुर् ६/६२ ।

ख—अवे. हु-क्सुर्√नुत=क्ष्णुतम्-वा. पॉकर्नीः ।

ग—अव क्ष्णौमि दासस्य नाम चित्-ऋ. १०,२३,२ । वाचं क्ष्णुवानः-अ. वे. ५,२०,१ । आ क्ष्णौति—काल्या. श्रौ. २१,४,६ । संक्ष्णुत्येव गायेत्-षन्ना. २,२ ।

√क्ष्माय् (क्ष्मायी) १/४८३ श×	विधूनने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√क्षम् (क्षमूष्) १/ सहने (आ) । √क्षम् (क्षमूष्) ४/ सहने (प) । √क्ष्मै १/४८३ धारणे (आ) काकृ ।

ग—क्ष्मया चरति-ऋ. ४,४६,३; विक्ष्मापयन्ती-निरु. १०/७ । (=हिंसन्ती-दुर्गाचार्यः) । क्ष्मा (निघ. १/१) पृथिव्या नाम । अस्यैव शब्दस्य नामधातुरयं भवति ।

+ √क्ष्मील् (क्ष्मील) १/५१९	निमेषणे (प) इति चन्द्रः-क्षी । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । निमेषे—वो ।	< √श्मील् (श्मील) निमेषणे (प) । √स्मील् (स्मील) १/ निमेषणे (प) । √मील् (मील) १/निमेषणे (प) ।

√मील्>√स्मील्>√श्मील्>, क्+√श्मील=√क्ष्मील इति स्पष्टो विकासः ।

+√क्ष्विड् (ञिक्ष्विडा)१/७३५ मै-सा-श-च-जै-काकृ-कात-शा-हे×	स्नेहनमोहनयोः (आ) इत्यार्हतः-क्षी । स्नेहे मोक्षे—वो ।	>√क्ष्विद् (ञिक्ष्विदा) स्नेहमोहनयोः (आ) । √स्विद् (ञिष्विदा) १/ स्नेहमोहनयोः (आ) । √क्ष्विद् (ञिक्ष्विदा) ४/ स्नेहमोहनयोः (प) । √स्विद् (ष्विदा) ४/ गात्रप्रक्षरणे (प) ।

ग—निश्वासक्ष्वेडनादेव भर्त्सयन्तमिव स्थितम्—मभार. ३,१७८,२६= मोचनात्।

ङ—√छोड (<क्ष्वेड-)=मोचने- भवि. महा। } द्रष्ट.√क्षोट् (क्षोट)
छ—√छोड़ना (<क्ष्वेड-)= मोचने। } १०/३१९ क्षेपे (प)।

(मोहने—क्ष्वेडः=विषम्—आनन्दलह. २९।) (मोचने—प्रक्ष्वेडनास्तु नाराचाः -अ.को. २,८,८७)।

√क्ष्विड् (ञिक्ष्विडा) [१/९६३] अव्यक्ते शब्दे (प) >√क्ष्विद् (ञिक्ष्विदा)
१/३०० हे (क्षी) हे। अव्यक्ते शब्दे (प)।
√ज्विद् १/३५६ अव्यक्ते शब्दे (प) काकृ।

क्षीरस्वामी तु √क्ष्विद् (ञिक्ष्विदा) १/७३५ स्नेहनमोहनयोः (आ) इत्यत्र √क्ष्विड् धातोः पाठभेदं दर्शयति, इति स √क्ष्विड् स्नेहनमोहनार्थक एव सम्पत्स्यते न त्वव्यक्तशब्दार्थकः, मूलधात्वर्थमाधृत्यैव पाठभेदधातोरर्थनिश्चेयत्वात्। अत्र श्रीयुधिष्ठिरो मीमांसको भ्रान्तः। स स्नेहनमोहनार्थकस्य √क्ष्विड् १/७३५ धातोः प्रयोगोदाहरणम्— "न च क्ष्वेडेत्"—इति मनुवचनं प्रस्तौति, तन्न समीचीनम्, तस्य धातोरात्मनेपदित्वादव्यक्तशब्दार्थकत्वाभावान्मनुवचनस्याव्यक्तशब्दार्थकत्वाच्च। क्षीरस्वामिनाऽव्यक्तशब्दार्थकः √क्ष्विड् धातुर्न जातु क्वचित् पठितस्तरङ्गिण्याम्। तेन √क्ष्विद् (ञिक्ष्विदा) १/९६३ अव्यक्ते शब्दे (प) इत्यत्र √क्ष्विड् इति पाठभेदो दर्शनीय आसीत् तथैव मैत्रेयसायणाभ्यामपि। हेमचन्द्रस्तु करोति तथा। अतो मया √क्ष्विद् १/९६३ अव्यक्ते शब्दे (प) इति धातोः पाठभेदः √क्ष्विड् दर्शितः।

क—सुएइ—, सुइ,—क्सॉइद्—, क्सु—एइ—(द्)—ः=अव्यक्ते शब्दे। *सुएइज्—दो, (*स्वैज्दति, *स्वैस्दति) किम्रिक्—छव्यथु=शब्दे; छव्यथ्, छव्यथद्—वा. पॉकर्नीः।

ग—क्ष्वेडन्तो धावमानाश्च—वा. रा. ४,४५,८; नास्फोटयेन्न च क्ष्वेडेत्—मनु. ४,६४= अव्यक्तदन्तशब्दात्मकं क्ष्वेडनं न कुर्यात् (मन्वर्थ.)। आस्फोटयन् क्ष्वेडयंश्च—मभार. ३,१२३७९। हंसः क्ष्वेडति—सुश्रु. २,२४६,६। क्ष्वेडन्ति घुर्घुरायन्ते—सुश्रु. २,१०४,१। क्ष्वेडितास्फोटितस्वनैः—मभार. १,६९,६ – क्ष्वेडितम्=सिंहनादः। क्ष्वेडयन्तौ—मभार. २,१४,३ =आस्फोटयन्तौ (नील.)।

+√क्ष्विद्(ञिक्ष्विदा)१/७३५ स्नेहनमोहनयोः (आ) >√क्ष्विड् (ञिक्ष्विडा)
मै-श-जै-काकृ-कात-शा× क्षी। स्नेहन-मोहनयोः (आ)।
गात्रप्रस्रवणे—सा। >√स्विद् (ञिष्विदा) १/

	स्नेहने—च।	स्नेहनमोहनयोः इति
	स्नेहने मोहने च—हे।	नन्दी—क्षी।
	मोक्षे स्नेहे—वो।	√क्ष्वेल् (क्ष्वेल) १/चलने (प)। शेपः पूर्ववत्।

क—द्रष्ट.√क्ष्विद् ४/१३३।

√स्विद् (ञिष्विदा) >क्+√स्विद् >√क्ष्विद्>√क्ष्विड् इति व्युत्पत्तिः।

√क्ष्विड् मोचनार्थकस्य (वोपमते) धातोः प्रयोग उपलभ्यते तज्जातीयकस्यास्य तु न तथा।

√क्ष्विद् (ञिक्ष्विदा) १/९६३ अव्यक्ते शब्दे (प) श-काक्रु-कात×	क्षी-मै-सा-च-जै-शा-हे-। कूजने—वो।	पूर्वधातुद्वयवत्।

क—पूर्ववत्।

ग—क्ष्वेदेत्–काठ. १९,१२; क. ३१,२।

+√क्ष्विद् (ञिक्ष्विदा) ४/१३३ श	स्नेहनमोहनयोः (प) क्षी। स्नेहनमोचनयोः—मै-सा। स्नेहने—च। स्नेहने मोक्षे च—जै। मोचने—च-काक्रु। स्नेहने मोचने च—कात-शा-हे। मोक्षे स्नेहे—वो।	√स्विद्(ष्विदा) ४/ गात्रप्रक्षरणे (प)। पूर्ववत्

क—सुएइद् = स्वेदे।

ख—अवे. क्स्विद्, क्स्वीद् = दुग्धम्, रसः, तैलयुतं श्वेतमिश्रणम्–वा. पॉकर्नीः।

ग—निश्वासक्ष्वेडनादेव भर्त्सयन्तमिव स्थितम्—मभार. ३,१७८,२६= मोचनात्।

{ङ—√छोड (<क्ष्वेड-)=मोचने - भवि. महा।
छ—√छोड़ना (<क्ष्वेड-)= मोचने।} द्रष्ट.√क्षोट् (क्षोट) १०/३१९ क्षेपे (प)।

(मोहने—क्ष्वेडः=विषम्—आनन्दलह. २९ ।) (मोचने—प्रक्ष्वेडनास्तु नाराचाः -अ.को. २,८,८७)।

√क्ष्विड् (ञिक्ष्विडा) [१/९६३] अव्यक्ते शब्दे (प) >√क्ष्विद् (ञिक्ष्विदा) अव्यक्ते शब्दे (प)।
१/३०० हे (क्षी) हे।

√ज्विद् १/३५६ अव्यक्ते शब्दे (प) काक्र।

क्षीरस्वामी तु √क्ष्विद् (ञिक्ष्विदा) १/७३५ स्नेहनमोहनयोः (आ) इत्यत्र √क्ष्विड् धातोः पाठभेदं दर्शयति, इति स √क्ष्विड् स्नेहनमोहनार्थक एव सम्पत्स्यते न त्वव्यक्तशब्दार्थकः, मूलधात्वर्थमाधृत्यैव पाठभेदधातोरर्थनिश्चेयत्वात्। अत्र श्रीयुधिष्ठिरो मीमांसको भ्रान्तः। स स्नेहनमोहनार्थकस्य √क्ष्विड् १/७३५ धातोः प्रयोगोदाहरणम्— "न च क्ष्वेडेत्"—इति मनुवचनं प्रस्तौति, तन्न समीचीनम्, तस्य धातोरात्मनेपदित्वादव्यक्तशब्दार्थकत्वाभावान्मनुवचनस्याव्यक्तशब्दार्थकत्वाच्च। क्षीरस्वामिनाऽव्यक्तशब्दार्थकः √क्ष्विड् धातुर्न जातु क्वचित् पठितस्तरङ्गिण्याम्। तेन √क्ष्विद् (ञिक्ष्विदा) १/९६३ अव्यक्ते शब्दे (प) इत्यत्र√क्ष्विड् इति पाठभेदो दर्शनीय आसीत् तथैव मैत्रेयसायणाभ्यामपि। हेमचन्द्रस्तु करोति तथा। अतो मया √क्ष्विद् १/९६३ अव्यक्ते शब्दे (प) इति धातोः पाठभेदः √क्ष्विड् दर्शितः।

क—सुऐइ—, सुइ,-क्सॉइद्-, क्सु-एइ-(द्)-ः=अव्यक्ते शब्दे। *सुएइज्-दो, (*स्वैज्दति, *स्वैस्दति) किम्रिक्-छव्यथु=शब्दे; छव्यथ्, छव्यथद्-वा. पॉकर्नीः।

ग—क्ष्वेडन्तो धावमानाश्च—वा. रा. ४,४५,८; नास्फोटयेन्न च क्ष्वेडेत्-मनु. ४,६४ = अव्यक्तदन्तशब्दात्मकं क्ष्वेडनं न कुर्यात् (मन्वर्थ.)। आस्फोटयन् क्ष्वेडयंश्च—मभार. ३,१२३७९। हंसः क्ष्वेडति—सुश्रु. २,२४६,६। क्ष्वेडन्ति घुर्घुरायन्ते—सुश्रु. २,१०४,१। क्ष्वेडितास्फोटितस्वनैः—मभार. १,६९,६ – क्ष्वेडितम्=सिंहनादः। क्ष्वेडयन्तौ—मभार. २,१४,३ =आस्फोटयन्तौ (नील.)।

+√क्ष्विद्(ञिक्ष्विदा)१/७३५ स्नेहनमोहनयोः (आ)
मै-श-जै-काक्र-कात-शा × क्षी।
गात्रप्रस्रवणे—सा। { >√क्ष्विड् (ञिक्ष्विडा) स्नेहन-मोहनयोः (आ)।
>√स्विद् (ञिष्विदा) १/

	स्नेहने—च।	स्नेहनमोहनयोः इति
	स्नेहने मोहने च—हे।	नन्दी—क्षी।
	मोक्षे स्नेहे—वो।	√क्ष्वेल् (क्ष्वेल) १/चलने (प)। शेषः पूर्ववत्।

क—द्रष्ट. √क्ष्विद् ४/१३३।

√स्विद् (ञिष्विदा) >क्+√स्विद् >√क्ष्विद्>√क्ष्विड् इति व्युत्पत्तिः।

√क्ष्विड् मोचनार्थकस्य (वोपमते) धातोः प्रयोग उपलभ्यते तज्जातीयकस्यास्य तु न तथा।

√क्ष्विद् (ञिक्ष्विदा) १/९६३ अव्यक्ते शब्दे (प)		
श-काकृ-कात×	क्षी-मै-सा-च-जै-शा-हे-। कूजने—वो।	पूर्वधातुद्वयवत्।

क—पूर्ववत्।

ग—क्ष्वेदेत्-काठ. १९,१२; क. ३१,२।

+√क्ष्विद् (ञिक्ष्विदा) ४/१३३ श	स्नेहनमोहनयोः (प)	√स्विद्(ञिष्विदा) ४/ गात्रप्रक्षरणे (प)। पूर्ववत्
	क्षी। स्नेहनमोचनयोः—मै-सा। स्नेहने—च। स्नेहने मोक्षे च—जै। मोचने—च-काकृ। स्नेहने मोचने च—कात-शा-हे। मोक्षे स्नेहे—वो।	

क—सुएइद् = स्वेदे।

ख—अवे. क्स्विद्, क्स्स्वीद् = दुग्धम्, रसः, तैलयुतं श्वेतमिश्रणम्—वा. पॉकर्नीः।

√ स्विद् > ,क्+√ स्विद् =√ क्ष्विद् इति व्युत्पत्तिः। प्रयोगो नोपलभ्यते संस्कृतसाहित्ये, √ स्विद् धातोः प्रयोगबाहुल्यादस्य च क्वाचित्कत्वात्। रस-दुग्धार्थक आवेस्तः 'क्स्स्वीद्'-शब्दस्त्वस्य धातोः सत्तां साधयति। अत्र महाभाष्यकारस्य वचनं सार्थकं भवति-"उपलब्धौ यत्नः क्रियताम्। महान् शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः, साङ्गाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः, एकविंशतिधा बाह्वृच्यं नवधाथर्वणो वेदः, वाकोवाक्यमितिहासः पुराणं वैद्यकमित्येतावाञ्छब्दस्य प्रयोगविषयः। एतावन्तं शब्दस्य प्रयोगविषयमननुनिशम्य "सन्त्यप्रयुक्ताः" इति वचनं केवलं साहसमात्रमेव। (महाभाष्ये पस्पशाह्निकम्)।

√ क्ष्वेल (क्ष्वेऌ) १/५३९ चलने (प) श-च-काक्र-कात-हे-वो× क्षी-मै-सा-जै-शा। क्रीडायाम्—ह्वि.।

√ क्वेल (क्वेऌ) १/७२१ चलने (प) जै; ४४६ हे; गतौ—काक्र-कात।
√ केल (केऌ) १/ चलने (प)।
√ खेल (खेऌ) १/ चलने (प)।
√ ख्वेल (ख्वेऌ) १/२४७k गतौ (प) काक्र।
√ वेल (वेऌ) १/ चलने (प)।

क—केउ-(कूउ-, कू-)=प्रकाशने, ज्वलने दाहे। *कु-लोस्=दाहे। लेट्टिश. क्वेलेत्=लौहादि-सुदाहे—वा. पॉकर्नीः।

ग—क्ष्वेलन्ति च हसन्ति च-वा.रा.६,२,२१;क्ष्वेलन्त्यपि-६,२३,४६। क्ष्वेलिका-भा. पु. ५,८,१८=क्रीडा (श्रीधरस्वामी); क्ष्वेली-भा. पु. १०,२९,४६=क्रीडा। क्ष्वेडित०-मभार. १४,६०,१०=कूर्दनम् (नील.)। लडयोश्चैकत्वात् √ क्ष्वेड् अपि तथा।

छ—√ खौलना (<क्ष्वेलनम्)=उत्क्वथने, अत्यौष्ण्ये, उत्तेजने।

छ—√ झेरना *†=हस्तपादेन जलचालने, (२) जलान्तर्हिल्लोलने, (३) प्रेरणे, (४) सहने।

+√ खक्ख् (खक्ख) १/१२० हसने (प) इति दुर्गः-क्षी> मै-सा-श-च-जै-काक्र-कात-श× क्षी-हे। हासे—वो।

√ खर्ख् (खर्ख) हसने (प)।
√ कक् (कक)१/ लौल्ये (आ)।
√ कख् (कखे)१/हसने (प)।
√ कक् १/४०९० लौल्ये (आ) काक्र।

√कक् हासे-सौ.धा.-वो.।
√कक्क् १/४०९b लौल्ये
(आ) काक्क।

क—द्रष्ट.√कक्ख् १/११९।

ङ—√खोक्ख् (अक)=वानरशब्दे। खोक्खइ–गा. १७१ अ.।

छ—खक्खा=(१) अट्टहासः। पाञ्चालाः क्षत्रियाः प्रायश आत्मानं 'खक्खा' इति निगदन्ति। अतोऽयं शब्दो विविधार्थवाचको जातः—(२) अनुभव-सम्पन्नः पुरुषः, (३) विशाल उच्चश्च करी।

धातुरेष शब्दानुकृतिः। हासे सत्ययं स्वतो जायते। प्रादेशिकीषु भाषासु अट्टहासः 'कक्खा'-शब्देन भाष्यते। 'क ख ग घ' इत्येतेषां चतुर्णां वर्णानां विपर्या-सेनायं धातुर्विकसितः। ध्वनिमेळके ध्वनयस्तुलनीयाः। √कक्ख् धातुः पालिभाषायां लभ्यते–धम्मसंगणि ८५९।

+√खच् (खच) १/१६६ बन्धने (प) इति लौकिकः–क्षी।

<√कच् (कच) बन्धने (प)।
√कच् (कच) १/ दीप्ति-बन्धनयोः (आ)।

क—कुाग्, कुाइग् = उत्प्लवने। पु. उ. ज. स्काछ्=दस्युता–वा. पॉकर्नीः।

ग—द्वित्राणि यानि खचद्दशनाङ्कुराणि–कथासरि. २३,८८। रत्नच्छाया-खचित०–मेघ. ३६।

ङ—√खअइ (<खचित०)=जटितम्, (२) व्याप्तम्–औप.; स. ११४; खचिअ–कुमा.; (३) पिञ्जरितम्–कप्प.।

छ—√खचना *=बन्धने, जटिते,–"मरकत खची"—तुलसी.।

+√खच् (खच) ९/५९ भूतप्रादुर्भावे (प) इति दुर्गः—क्षी।
श-च-काक्र-कात-शा ×
क्षी-मै-सा-जै।
हेठश्चवत् (=भूतप्रादुर्भावे)–हे।
भूतिपूत्योरुत्पत्तौ—वो।
भूतिः = सम्पत्तिः, पूतिः = पवित्रता। तयोरुत्पत्तिः = प्रादुर्भावः। भूत्युत्पत्तौ पूत्युत्पत्तौ चेत्यर्थः—दुर्गादा.।

<√खव् (खव) भूतप्रादु-र्भावे (प)।
√खु ९/ भूतप्रादुर्भावे (प) मै।

+√खज् (खज) १/२२८ मन्थे (प) श× क्षी-मै-सा-च-काकृ-कात-शा-हे-वो। मन्थने—जै।

√कज् (कज) १/मदे (प)। √गज् (गज) १/मदने (प)। √खजे (निघण्टौ २/१७) = सङ्ग्रामनाम।

क—(स्) केक् = उत्प्लवने, स्केज् = त्वरायाम्, प्लवने। कॉइउकु = परिभ्रमणे। आइस्. स्कक = मन्थनदण्डः-वा. पॉकर्नीः।

ग—खज-कृत्-ऋ. ६,१८,२; ७,२०,३; काठ. ८,१७। खजङ्कर-ऋ. १,१०२,६; तैब्रा. २,७,१५,६। यद्वन्निर्मथ्यते खजैः-मभार. १२,२१४,२१। खजां दर्वीं च करेण धारयन्-मभार. ४,७,१। खजङ्करः-ऋ. सं. १,७,५,१।

√खञ्ज् (खजि) १/२२९ गतिवैकल्ये (प) श× क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। पाङ्गुल्ये—वो।

√कंस् (कसि) २/ गति-शासनयोः (आ); गतिशातनयोः—शा-हे। √खज् (खज) १/ मन्थे (प)। √खण्ड् (खडि) १/ मन्थे (आ)।

क—घेंघ् = लङ्घने। लिथु. केमेंजोति = मन्दगतौ—वा. पॉकर्नीः।

क—स्केंज् = गतिवैकल्ये। स्वीडिश् (प्रादे.) स्किंक = गतिवैकल्ये, पु. आइस्. हिंक = गतिवैकल्ये-वा. पॉकर्नीः।

ग—खञ्जः-ध्या. ९३,१। खञ्जाः-गर्भ. ३। निखञ्जति-मभाष्ये १,२,४५. २२० [२६]। खञ्जः-मनु. ३,२४२।

घ—खञ्जति-पेतवत्थु ३,२ [२८]।

ङ—√खंज (अक) = गतिवैकल्ये-कप्पू.।

छ—खाँजा (बु. ख.) = गतिविकलम् (विशेषतः-क्षेत्रकर्मणि हलस्य व्यवस्थितरेखां विहाय चलने)।

+√खट् (खट) १/३०५ काङ्क्षे (प) श क्षी-कात-हे। काङ्क्षायाम्—मै-सा-जै-काकृ। काङ्क्ष्ये—च-शा। काङ्क्षि—वो।

√घट् (घट) १/ चेष्टायाम् (आ)। खटकः = घटकः—त्रिकाण्डशेषे।

ग—खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन—कलाविलासे २,२३; >खड़िया—हि.। खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्तिते=भा. प्र., १ख., १भागः।

घ—खटोपिका = खड्वा—मज्झिम. १,४५०,४५१।

छ—√खटना
छ—√खटाना } (बुं. ख.)—खटैहौ = इच्छितो भविष्यसि। (स्थैर्येऽपि)।

छ—खाट (<खड्वा। खट्यते = काङ्क्ष्यते शयनार्थिभिः।

+√खण्ड् (खडि) १/२८१ श	मन्थे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√कण्ड् (कडि) १/मदे (आ)। √खण्ड् १/१८०a खण्डने (प) काकृ।
		√खुण्ड् (खुडि) १/ मन्थे (आ) सा।
मन्थनम्	= भञ्जनम्(इह)—दुर्गादा.।	"आखण्डल प्रहूयसे"—ऋ. सं. ६,१,२४,२। आखण्डयितः खण्डं खण्डयतेः—निरु. ३,१०,६।

क—कळु—, केला = ताडने, खण्डने—वा. पॉकर्नीः।

ग—राज्यखण्डमिदं महत्—वा. रा. २,१०५,३। खण्डखण्डं ययुर्घनाः—मा. पु. ८३,२६।

घ—(खण्डति) खण्डित—पेतवत्थु १५८।

छ—खाँड़ (<खण्डः—राजनिर्घण्टे)

√खद् (खद) १/४८ श×	स्थैर्ये हिंसायां च (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। चकाराद् भक्षणे च-सा५०। खदने। स्थितौ—च। स्थैर्ये वधे—वो।	√स्खद् (स्खद) १/ खदने (प)। √खाद् (खाद्) १/ भक्षणे (प)। √खै १/ स्थैर्ये खननहिंसनयोः (प) वो।

अभि०ययस्व खदिरस्य सारम्—ऋ. ३,५३,१९; अ. वे. ३,६,१। खदिरः—तैआ. ५,२,४। खदत्—शब्रा. १,७,४,१०।

√खन् (खनु) १/८६३	अवदारणे (उ)	√खै १/ स्थैर्ये खननहिंसयोः (प) वो;खनने—शा।

श × क्षी-मै-सा-च-जै-काक्-
कात-शा-हे।
विदारे—वो।

क—खेना (क्स्)=खनने। लिथु. किनिस्=खनिः।
ख—क्साँ=छुच्छुन्दरिः (मनु. १२,६५)—वा. पॉकर्नीः।
ग—खनामि—ऋ. १०,१४५,१। खनति—तै. २,६,४,२।
घ—खनति—जातक २,२९५।
ङ—√खण (सक)=खनने। खणइ—महा.। वक्र-खणेमाण—सुर. २,१०३।
छ—√खनना*†=खनने, (२) विलेखने।

+√खम्ब् (खम्ब) १/४१४ गतौ (प)
मै-श-च-जै-काक्-कात- क्षी-सा-(हे)-वो।
शा ×
अर्वेत्यादौ रेफस्थाने नकारं कौशिको मन्यते—क्षी।

एतेन सति सम्भवे मध्ये मकारो रकारो वा जायते धातूनाम्।

+√खर्ख् (खर्ख) १/१२० हसने (प)
मै-सा-श-च-जै-काक्- क्षी।
कात-शा-हे-वो ×

>√खक्ख् (खक्ख) हसने (प) इति दुर्गः—क्षी।
अयं प्राकृतो धातुः दृष्ट०।
√गग्घ् (गग्घ) १/ हसने (प)।
√घग्घ् (घग्घ) १/ हसने (प)।
√घघ् (घघ) १/ हसने (प)।

ग—खर्खोद०—राजतर. ५,२३८। (खर्खा=भगास्यम्—क्षी)।

अस्य व्युत्पत्तिक्रमस्त्वित्थम्—√कर्क हासे—वो>√कक्क् हसने—कात.>√कक्ख् हसने—मै>√कख् हसने>√कग् हसने—कात,>√खर्ख् हसने—क्षी, >खक्ख् हसने >√गग्घ् हसने >√घघ् हसने।

√खर्ज् (खर्ज) १/२२४ व्यथने (प)
श × क्षी-मै-जै-काक्-कात-
शा-हे।
मार्जने, च=व्यथने-

√कर्ज् (कर्ज) १/ व्यथने (प)।
√खज् (खज) १/ मन्थे (प)।

क्षी २२५। क्षी-मै-जै-काक्र-कात-शा-हे। पूजने, च = व्यथने—सा। च ? व्यथा-मृजोः—वो।

√चक्क् (चक्क) १०/ व्यथने (प)। (√कर्ज् (विपर्य.) > जर्क् > √चर्क् > √चक्क्)।

क—कॅर्ट्-, कॉर्ट्-, क्र्-, स्केर्ज्-ः लिथु. क्रेग्ड्रे = खर्जति—वा. जू. पॉकर्नीः।

ग—खर्गलेव नक्तम्—ऋ. ७,१०४,१७। खर्जति-कात्या. श्रौ. ८,४,४; १६, ६,२०।

ङ—खज्ज (< खर्जः) = वृक्षविशेषः–स. २५६।

छ—√ खुजाना (खुजलाना) = आमर्शने, (मार्जने)।

+√ खर्द् (खर्द) १/५८ श × — दन्दशूके (प) क्षी-मै-सा-शा। दशने—च-जै-कात-हे-वो। दंशने—काक्र।

√ खर्ज् (खर्ज) १/ व्यथने (प)। √ खद् (खद) १/ स्थैर्ये हिंसायां च (प)। √ खज् (खज) १/ मन्थे (प)।

दन्दशूके = गर्हितदशनयुक्तायां क्रियायाम्–क्षी।
√ खज् > √ खद्, √ खर्ज् > √ खर्द्।

छ—खर्दा (बुं. ख.) = कुन्तः, शस्त्रविशेषः।
छ—√ खरादना = तक्षणादौ।

+√ खर्ब् (खर्ब) १/४१४ श-काक्र × — गतौ (प) क्षी-मै-सा-च-जै-कात-शा-हे-वो।

√ कर्ब् (कर्ब) १/ गतौ (प)। √ गर्ब् (गर्ब १/ गतौ (प)। √ खृ १/४१२ y गतौ (आ) काक्र। √ घर्ब् (घर्ब) १/ गतौ (प)।

क—द्रष्ट. √ खर्व् १/५७९।

ग—खर्बः = कुब्जकवृक्षः –राजनिर्घण्टः; दशाब्जसंख्या–लीलावती; खर्बा = गायत्रीस्वरूपा भगवती–दे. भाग. १२,६,३८।

+√खर्व् (खर्व) १/५७९ दर्पे (प)
श-जै×
क्षी-मै-सा-च-काकृ-कात-शा-हे ।
गर्वे—वो ।

√कर्व् (कर्व) १/ दर्पे (प)।
√गर्व् (गर्व) १/ दर्पे (प)।
√घर्ब् (घर्ब) १/ गतौ (प)।

क—द्रष्ट.√खण्ड् (खडि) १/२८१ मन्थे ।

ग—खर्वुरा = तरदीवृक्षः–राजनिर्घण्टः; खर्वूजं मूत्रलं बल्यम्–भा. प्रका.पू.ख., प्र. भा. (श.क.द्रु.)। वस्तुतो वत्रयोर्देशविशेषप्रयोगभेदेन गत्यर्थक√खर्व् धातोर-भिन्नोऽयम् ।

+√खल् (खल) १/५४४ सञ्चये, च = चलने (प)
श×
क्षी-च-शा-हे ।
सञ्चलने सञ्चये च—मै ।
सञ्चये—सा-जै ।
चलने—काकृ-कात ।
विलेखने—काकृ ।
क्षलजार्थे (= चाले चये)
—वो ।

√क्षर् (क्षर) १/ सञ्चलने (प)।
√क्षल् (क्षल) १/ सञ्चलने सञ्चये च (प)।
√खल्ल् १/२४८b चलने (प) काकृ ।
√स्खल् १/ चलने (प)।

क—कॅल्ऊउऑ–, कॅलॅऊउऑ = नग्नः, खल्वाटः, अरक्षितः । कल् = नग्नः, खल्वाटः । अर्मे. क्सलम् = मस्तकः, मूर्धा ? – वा. पॉकर्नीः ।

ग—खलात् क्षेत्रादगाराद् वा–मनु. ११,१७ = संचये । खलिः—भारतरत्नाकरे–२,९८ = तिलकिट्टम्–राजनिर्घण्टः ।

घ—(खलित्वा- थेरगाथा १,४५; मिलिन्दपञ्ह १८९ = सञ्चलने)√स्खल् धातुरपि स्यात् ।

ङ—खरका (<खलकः), खिरका, खिरैया (बुं.ख.) = सञ्चये–(धान्यमर्द-नसञ्चयादिस्थानम् ।)

+√खव् (खव) ९/५९ भूतप्रादुर्भावे (प)
जै×,श
क्षी-मै-सा-शा-हे ।
प्रादुर्भावे—च ।
भूतप्रादुर्भावे—काकृ-कात ।

>√खच् (खच) भूत-प्रादुर्भावे (प) इति दौर्गाः—क्षी ।
√खु ९/ भूतप्रादुर्भावे खच्वत् (= भूतिपूत्योरुत्पत्तौ) (प) मै ।
—वो ।

भूतप्रादुर्भावे = अतिक्रान्तोत्पत्तौ—क्षी ।

√खच् धातोर्लिपौ 'च्' इत्यस्याक्षरस्याधस्तनस्तिर्यग् ('–'इति) दण्डः लेखकप्रमादाद्ध्वस्तो भवेच्चेत् तर्हि पाठका एनं √खच् स्थाने √खव् इत्येव पठिष्यन्ति । संस्कृतसाहित्ये एवमनेके सन्ति प्रमादाः । यथा–√बुन्द् (उबुन्दिर्) १/१८६ निशामने (उ) इत्यस्य स्थाने केचन √चुन्द् (उचुन्दिर्) धातुमामनन्ति । अत्र प्रमादाद् वकाराधोभागे तिर्यङ्मसी लग्ना स्यात् ।

+√खष् (खष) १/६८५ मै-श-जै-च-काकृ-कात-शा×	हिंसार्थः (प) इति कण्ठः—क्षी। क्षी-सा। हिंसायाम्—हे। वधे—वो।	<√कष् (कष) हिंसार्थः (प)। √कह् (कह) १/३१६। हिंसायाम् (प) काकृ।

सुस्पष्टं √कष् धातुतो विकसितः।

छ—खस्सी (आरब्यः)=निर्वृषणः, (२) क्लीबः, (३) अजः (वध्यः)
[—"वे खसिया वे गाय कटावैं"—कबीरः।]

√खाद् (खादृ) १/४७ श×	भक्षणे (प) क्षी-मै-सा-जै-काकृ-कात-हे-वो। च ?	√खद् (खद) १/ स्थैर्ये हिंसायां च (प)। चाद् भक्षणे—सा।

क—खाद्=दन्तैः खण्डने। अर्मे. ख़सचनेम्=दन्तैः खण्डने।

ख—न. पर्सि. ख़सायीदन्=भक्षणे, चर्वणे–वा. पॉकर्नीः।

ग—अवखादः–ऋ. १,४१,४। खादति–तै. ६,२,११,४; काठ. २५,४; मै. ३,९,३; पै. १९,३१,१५।

ङ—√खाना=भक्षणे।

+√खिट (खिट) १/२९८ श×	उत्त्रासे (प) क्षी-शा-हे। त्रासे—मै-सा। उत्त्रासने—च-जै-काकृ-कात। भयभीमयोः—वो।	√किट् (किट) १/ त्रासे (प) मै।

क—स्केर्-कॆर्=छेदने। अल्बे. कॆट=कर्तरी–वा. पॉकर्नीः। द्रष्ट. √किट् १/३१६।

ग—खेटखर्वटवाटीश्च-भा. पु. १, ६, ११=कर्षकग्रामः। खेटकः= यष्टिः-(खेटति भयमुत्पादयत्यनेन। √खिट्+करणे घञ्, स्वार्थे कः) यथा दश-भुजाया दुर्गाया ध्याने-"खेटकं पूर्णचापं च"।

ङ—√खेड (सक)=प्रेरणे (उत्त्रासने)। खेडइ-चेइय. ३३७; कुम्र. ७१।

छ—√खेदना†
छ—√खदेड़ना
छ—√खदेरना
=प्रेरणे, अपनोदने, आखेटे।

खेड़ा (<खेटः)=ग्रामः। यथा 'बरखेड़ा'-(होशंगाबादसमीपे), 'जरुवा-खेड़ा' (सागरमण्डलसमीपे) स्थेशने (Railway stations)

+√खिद् (खिद) ४/५८ श×

दैन्ये (आ) इति दुर्गः—क्षी।
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
दैन्यके—वो।

√खिट् (खिट) १/ उत्त्रासे (प)।

'खिद्यते'-इति कर्मकर्तरि तु वामनः-क्षी।

क—द्रष्ट. √खिद् ६/१५३।

ग—कैकेय्याः कृतेऽयं खिद्यते जनः-वा. रा. २, ३९, ७। खिद्यन्ति-षब्रा. ५, १०। खिद्यति-मभार. २, २४२८; भा. पु. ३, ४, १६।

ङ—√खिज्ज (अक)=खेदे, (२) उद्वेगे। खिज्जइ, खिज्जए-स. ३४, गउड. पि ४५७।

छ—√खीजना-भेदे, उद्वेगे।

√खिद् (खिद)६/१५३ श

परिघाते (प)
क्षी-सा-च, काकृ (उ),
कात-शा-हे।
परितापे—जै।
परीघाते—मै।
परिघाते दवे—वो।

√खिद् (खिद) ७/ दैन्ये (आ)
√खिद्रम् =खेदनं छेदनं भेदनम्-निरु. ११,३७।

क—(स्) क् (ह्) अइ (द्)=ताडने, प्रेरणे। लैति. कएदो,-ऐर्= ताडने, खण्डने-वा. पॉकर्नीः।

ग—खिदति हन्ति नग्नम्-ऋ. ४,२५,९; संखिदेत्-छान्दो. ५,१,१२। वेदेषु सनुम्कः 'खिदन्ति' इति प्रयोगो नाधिगम्यते।

+√खिद् (खिद्) ७/१२ श	दैन्यै (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । दैन्यके—वो ।	

ङ—√खेअ (प्रेर.)=खेदे । खेएइ–विसे. १४७२; महा. ।

+√खु (खुङ्) १/९३८ मै-सा-श-च-जै-शा ×	शब्दे (आ) इत्येके-क्षी । क्षी-काकृ-कात-हे । ध्वनौ—वो ।	<√कु (कुङ्) शब्दे(आ) । √गु (गुङ्) १/ शब्दे (आ) ।
स्पष्टो विकासः ।		√खु ९/ भूतिपूत्योरुत्पत्तौ (प) मै ।
		√घु १/ शब्दे (आ) ।

+√खु ९/६२ क्षी-मै-सा-च-जै-काकृ-कात शा-हे-वो ×	भूतप्रादुर्भावे (प) इति केचित्—मै मै ।	<√खच् (खच) भूत-प्रादुर्भावे (प) । <√खव् (खव) भूत-प्रादुर्भावे (प) ।

द्रष्ट.-√खव् ९/५९ ।

×√खुज् (खुजु) १/१९७ श ×	स्तेयकरणे (प) क्षी-मै-सा-जै-कात-शा । स्तेये—च-हे-वो ।	√कुज् (कुजु) १/ स्तेयकरणे (प) । √कुच् १/५०e स्तेयकरणे (प) काकृ ।
(काकृ-√खुच् [खुचु]) स्तेयकरणे-काकृ । लैपिकी त्रुटिः । खुजु. इति भाव्यम् ।		√खुच् १/५० f स्तेयकरणे (प) काकृ ।
		√गुज् १/५० c स्तेयकरणे (प) काकृ ।
		√ग्रुच् (ग्रुचु) १/ स्तेयकरणे (प) ।
		√ग्लुच् (ग्लुचु) १/ स्तेयकरणे (प) ।

छ—√खोजना (<खोजनम् =स्तेये)=गवेषणे । स्तेयकरणं गवेषणे संक्रान्तं हिन्द्याम् ।

+√खुड् (खुड) ६/१०९ क्षी-श-च-जै-काकृ-कात-शा-हे-वो×	संवरणे (प) इत्येके-मै मै-सा ।	<√थुड् (थुड) संवरणे (प) ।
+√खुण्ड् (खुडि) १/२८२ मै-श च-जै-काकृ-कात-शा×	गतिवैकल्ये (आ) क्षी-हे । मन्थे—सा । खञ्जे—वो ।	√कुण्ट् (कुटि) १/ गतिवैकल्ये (प) √खुण्ड् (खुडि) १०/ खण्डने (प) । √खञ्ज् (खजि) १/ गतिवैकल्ये (प) ।

छ—खोंड़ा = (<खुण्डः) = विकलाङ्गः ।
छ—√खोंटना*(<खुण्डनम्) = शिरोभागच्छेदने । चुरादावेषोऽर्थः ।
छ—√खूटना (<खुण्डनम्) = रोधे, गतिवैकल्ये ।
छ—√खूँटना (<खुण्डनम्) = रोधे, (२) नैयून्ये, (३) त्रोटने (खुण्डने) ।
छ—√खूँदना = कुट्टने, मर्दने ।

+√खुर् (खुर) ६/६३ मै-सा-श-च-काकृ-कात×	विलेखने (प) क्षी-जै-शा-हे । क्षौर(क्षोर)च्छिदोः—वो ।	√क्षुर् (क्षुर)६/विलेखने (प) । √छुर् (छुर) ६/ छेदने (प) । √खॄ १/४१२y गतौ (आ) काकृ ।
√खुर् (खुर) ६/६१···· क्षी-श×	छेदने खण्डने च—मै । छेदने—सा-च-काकृ-कात । विखनने छेदने च—हे । विलेखने छेदने च—जै-शा । क्षौर(क्षोर)च्छिदोः—वो ।	√कुट् (कुट) १०/ छेदने (प) इत्येके इति स्वामी—सा । √कुट्ट् (कुट्ट) १०/ छेदन-कुत्सनयोः (प) । √खुर्द् (खुर्द) १/ क्रीडायामेव (आ) ।

क—स्कउर्‌ॉ—स्-ः वा. पॉकर्नीः ।

ग—तस्याः खुरन्यासपवित्रपांसुम्–रघु. २,२ ।

+√खुर्द् (खुर्द) १/२२ श-शा×	क्रीडायामेव (आ) क्षी-मै-सा-काकृ-कात । क्रीडायाम्—च-जै-हे-वो ।	√खुर् (खुर) ६/ विलखने (प) । √कुर्द् (कुर्द) १/क्रीडायामेव (आ) । √क्रुड् (क्रुड) १/२१४a चलने (प) काकृ ।

√क्रूड् (क्रूड) १/२१४b चलने (प) काकृ।

√खूर्द् (खूर्द) १/ क्रीडायाम् (आ) वो।

√गुर्द (गुर्द्) क्रीडायामेव (आ)।

√घुर्द् (घुर्द) १/३९०d क्रीडायामेव (आ) काकृ।

छ—√खोदना = विलेखने (अश्वादीनां क्रीडने), उत्कीर्णने।

छ—√खुतलना = (<खुतरना <खुदरना <(विपर्ययः) <खूर्दनम्) — बुं.ख. = मर्दने।

छ—(√खूँदना = कूर्दने, (२) पादमर्दने। अयम् उत्प्लवनार्थकेन√स्कुन्द् धातुना सम्बध्नाति)।

√खेल् (खेल) १/५३८ चलने (प) क्षी-मै-सा-च-जै-शा-हे।
शX
गतौ—काकृ-कात।
चालगत्योः—वो।

√क्लि‍ल् ६/ श्वैत्यक्रीडनयोः (प)।

√केल् (केल) १/ चलने (प)।

क्वेल् (क्वेल) १/७२१ चलने (प) जै।

√केण् १/२१३f गतिप्रेषणश्लेषणेषु (प) काकृ।

√खेण् १/२१३g गतिप्रेषणश्लेषणेषु (प) काकृ।

√खैल् १/२४७g गतौ (प) काकृ।

क—केइ (ए?) -ल् (ओ)-ः किलॉस्, की-लॉ-स्, केक्सि-लॉ-स्, केक्सि-लॉ-स् = चलने। लिथु. किऐले, क्यले; लेट्टि. किऐलव; पु. प्रशि. क्यलो = जलपक्षी-वा. पॉकर्नीः।

ग—खेलन्त्यन्ये नदन्त्यन्ये-वा. रा. ५,५५,२६।

ङ—√खेल (अक) = क्रीडायाम्। खेलइ-कप्पू।

ङ—√खिल्ल (अक) = क्रीडायाम्, नाल्ये। वक्र-खिल्लंत-सुपा. ३९९।

छ—√खेलना = क्रीडायाम्।

+√खेव् (खेवृ) १/५०२ सेवने (आ) क्षी-जै-शा-हे।
— श-च X

√सेव् (षेवृ) १/ सेवने (आ)।

	सेचने—मै-सा-काक्र-कात। सेवे—वो।	√केव् (केवृ) १/ सेवने (आ), सेचने-काक्र। √खेव् (खेवृ) १/ सेचने (आ) मै। √गेव् (गेवृ) १/ सेचने (आ) मै। √ग्रेव् (ग्रेवृ) १/ सेचने (आ) मै। √ग्लेव् (ग्लेवृ) १/ सेचने (आ) मै। √घेव् १/५०४f सेचने (आ) काक्र।

विकासक्रमो विवेचनीयः। सेवनार्थः सेचनार्थे भ्रान्त्या लेखकप्रमादाद् वा स्यात् संक्रान्तः, वकाराधोभागे तिर्यग्दण्डस्य मसीक्षेपणात्। सेवनार्थकः सुलभः √सेव् (षेवृ) इत्यत्र संगतत्वात्। √(षेव्) >√खेव् अथवा √केव् >√खेव् >√गेव् >√ग्रेव् >√ग्लेव् >√घेव् इति शृङ्खला।

+√खै १/८९७ शा ×	खदने (प) क्षी-मै-सा-(च-जै-कात-हे)। खादने—काक्र। खनने—शा। स्थैर्ये खननहिंसयोः—वो। खदनम्=स्थैर्यं हिंसा च—सा।	√खद् (खद) १/ खदने (प)। √स्खद् (स्खद) १/ खदने (प)। √खाद् (खादृ) १/ भक्षणे (प)। √खन् (खनु) १/ अवदारणे (प)।

नूनमत्र मूले √खन् धातुर्लक्ष्यते। नस्य, खात्वा, उत्खाय प्रभृतिस्थलेष्वात्वं √खै इत्यस्य खननार्थकत्वं चापि तत् पुष्टयति। द्रष्ट. इह शाकटायनीयोऽर्थः।

+√खोड् (खोडृ) १/५५१ गतिप्रतिघाते (प) इति मै-सा-श-च-जै-काक्र-शा ×	दुर्गः—क्षी। गतिप्रतीघाते—कात। प्रतिघाते—हे। खोटने—वो।	<√खोल् (खोलृ) गतिप्रतिघाते (प)। √कोल् १/२५२a गतिप्रतीघाते (प) काक्र। √खोट् १/ गत्याघाते (प) वो।

√खोट् (खोऋँ) १/ गति-
प्रतिघाते (प)।
√खुण्ड् (खुडि) १/ गति-
वैकल्ये (आ)।

छ—खोट (<खोड़ा <खोडः)=दोषः, दुर्गुणः। अत्र√खुण्ड् १/२८२ गतिवैकल्ये (आ) धातुनाऽस्य धातोः सुस्पष्टः सम्बन्धो ज्ञायते।

छ—खोलना (<खोडनम्, खोलनम् =प्रतिघाते-हे)=रोध-प्रतीघाते=उद्-घाटने।

+√खोर् (खोऋँ) १/५५०	गतिप्रतिघाते (प)	पूर्ववत्।
श-जै-काकृ-कात ×	क्षी-मै-सा-च-शा।	
	प्रतिघाते—हे।	
	खोटने—वो।	

क—स्कौरॉ-स्—: लैति. स्कोरुस्-वा. पॉकर्नीः।

ङ—खोर=पात्रविशेषः, कचोलकः-उपपृ. ३१५; णंदि.।

छ—खोरा† (<खोरः <खोडः)=विकलाङ्गः- "काने खोरे"- तुलसी.।

छ—खोरा=कंसपुत्रिका; [पारी (>प्याली-हि.)]।

छ—खोरिया (<खोरिका=पात्री-क्षी)=लघुकंसपुत्रिका।

छ—खोरि †=सङ्कीर्णा प्रतोली, (२) अपराधः।

छ—खोर †=सङ्कीर्णा प्रतोली, (२) पशूनां बुसादिभक्षणार्थं कण्डोलः।

छ—खौर (बुं. ख.)=नीशारः (>रशानी>रशाई>रजाई-हि.)।

+√खोल् (खोलृ) १/५५१	गतिप्रतिघाते (प)	>√खोड् (खोडृ) गति-प्रतीघाते (प)।
श-च-शा-हे×	क्षी-मै-सा-जै।	शेषः पूर्ववत्।
	गतिप्रतिघाते—काकृ-कात।	
	खोटने—वो।	

क—कॉइ=न्युब्जीभावे, कौटिल्ये। खॉइ (लिथु.कूल्युस्=बुसम्, शुष्कतृणम्)। अर्मे. क्सोय्ल्र, (षष्ठी) क्सुलि। रसन्-सुल्जत=अण्डकोषः। सर्बि. सुउल्जेवि=हैमी रेखा, हैमम् अन्नबीजम्-वा. पॉकर्नीः।

छ—खोल,खोली (<खोलम्=शिरस्त्रम्-क्षी)=उपधानस्योपरितनमाच्छादनम्, दर्म्मादिप्रतिघातार्थमाच्छादनम् (उपकरणम्), (२) कीटानामुपरितनं चर्म, यत् ते समये समये त्यजन्ति परिवर्तयन्ति च।

छ—√खोलना-द्रष्ट. √खोड्।

√ख्या २/४९ श	प्रथने (प) क्षी-हे। प्रकथने—मै-सा-च-जै-काकृ-कात-शा-हे। ख्यातौ कथने—वो। दर्शने—ह्वि.।	√चक्ष् (चक्षिङ्) १/ व्यक्तायां वाचि (आ) चक्षिङः ख्याञ्- (२,४,५४)। √क्शा–चक्शे–ऋ. प्रा.६,६,१५;अनु-क्शात्यै–मै. ३,१,१, काठ. ७,७। √क्षा–अक्षत्–ऋ. १०,११,७। क्षाम्–मै. ४,१४,३।

ग—अनुपूर्वाणि चख्यथुर्युगानि–ऋ. ७,७०,४। परि ख्यन्–१०,१०,२। सन्ततिर्हि तवाख्याति–वा. रा. ५,६४,२०।

+√गग्घ् (गग्घ) १/ १५८ हसने (प) इत्येके—क्षी मै-सा-श-च-कात×	क्षी-जै-काकृ-शा-हे-वो।	<√घग्घ् (घग्घ) हसने (प)। द्रष्ट.√खक्ख् १/१२०। जग्घति (<जक्षति) हासे–जातक ३,२२३।

ग—गगनैः–मभार. ३,५२,५१=हसद्भिरित्यर्थः (नील.)। गग्घनैः>गग्गनैः >गगनैः इति क्रमः। अत्र सिद्धौ नीलकण्ठः–"गाध हसने इत्यस्य वा धातोर्ल्युटि पृषोदरादित्वेन धकारलोपे रूपम्" इति दर्शयन् निकामं भ्रान्तः, हसनार्थक-गाध-धातोरसत्त्वात्। तस्मात्√गग्घ् हसने इत्यस्माल्ल्युटि भिसि 'गग्घनैः' इति रूपे, घकारलोपे सति रूपमुन्नेयम्।

छ—गघरी
छ—गाघर (बुं. ख.) } =गर्गरी। अस्य मुखे हस्तास्फालनेन हासवद् ध्वनिर्भवति।

वस्तुतः–"अव स्वराति गर्गरः"–ऋ. ८,५८,९। गर्गरोद्गारनिस्वन०–हरिवं. ३३९५ (√गृ ९/ शब्दे। (उणा. १/१२७) गः। गर्गम् = शब्दं राति, इति, गर्ग+√रा +कः ३/२/३) प्रभृतिभिर्ध्वनिवाचकः 'गर्ग'-शब्दः सिद्ध्यति। अस्यैव हसनार्थका विभिन्ना धातवो जाताः। भीमसूनोरभिधेयं घटवद् हसनत्वाद् 'घटोत्कच' इति जातम्—

तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम्।
प्रणम्य पादयोर्वीर ! स्थिता ते वचनङ्करी ॥ स्क.पु.१,६०,७।

प्राकृते गग्गर-शब्दः सुखदुःखनिमित्तकाव्यक्तकथनवाचकोऽस्ति–कुमा.; (हे. १/२१९), गग्गरी (<गर्गरी)शब्दश्च लघुघटार्थवाचकः–सुपा. ३३९। अयं देशजो नास्ति, दे. २,८९ इत्यत्र तथोल्लेखस्त्वविवेकात्।

+√गज् (गज) १/२४३ शब्दार्थः (प)
शX
क्षी-मै-सा-च-कात।
शब्दे—जै-काक्र-शा-हे।
स्वने—वो।

√कच् (कच) १/ शब्दे (प)।
√गञ्ज् (गजि) १/ शब्दार्थः (प)।
√गृ ९/२७ शब्दे (प)।
√गृज् (गृज) १/ शब्दार्थः (प)।
√गर्ज् (गर्ज) १/ शब्दे (प)।
√गर्द् (गर्द) १/ शब्दे (प)।

ग—गोगजोष्ट्रहयादिषु–मनु. ८,२९६। गजाश्चैव–वा. रा. २,९२,३२; गजनासोरु० २,३०,३०। गजपुष्पी–वा. रा. ४,१२,४६। गजपिप्पली–सुश्रु. २,४३१,८। गजमुख०–बृह. सं. ५८,५८। गजाशन०—सुश्रु. २,४४२,७। गजबृंहित०—सुश्रु. १,१०७,१०। गजपुर०–मभार. १३,७७११; गजदन्तमय०–२,१८५३। गजमुक्ता–कुमारसं. १,५।

छ—गज़ब (अर.), ग़ज़ल (फा.)। गज़ (फा.) = प्रमापकमुपकरणम्।
छ—गजी (फा.) = मनाङ्न्यूनायतं दैशिकं वस्त्रम्।

+√गज् (गज) १/२४९ मदने, च = शब्दार्थः (प)
क्षी-मै-सा।
मद्दे—च।
मदने—जै-शा-हे।
मद्दे स्वने च—वो।

√कज् (कज) १/२२७ मद्दे (प)।
√कड् (कड) ६/ मद्दे (प)।
शेषः पूर्ववत्।

पूर्वधातोरभिन्नोऽयम्। क्षी-च-जैनेन्द्राः पार्थक्येन संख्यान्ति।
ग—गजः–१ योत. ५९; योचू. ११८; शाण्डिल्यो. १,७,६।
घ—गज–जातक ४,४९४।
ङ—गज–प्रासू. १७१; इक.।
ङ—गय–अणु.; औप.; प्रासू. १५४; सुपा. ३३४।

+√गञ्ज् (गजि) १/२२४ शब्दार्थः (प)
श-जै-कातX
क्षी-मै-सा-च।
शब्दे—च शा-हे।
स्वने—वो।

√गृञ्ज् (गृजि) १/ शब्दार्थः (प)।

व—गंज् = विडम्बनायाम्, उपहासे। पु. गॉथि. गे-कंच् = गञ्जः (= उपहासः)–वा. पॉकर्नीः।

ग—गञ्जे दूरस्थिते निजे–राजत. ४,५८८; गञ्जवर० ५,१७६ । नेत्रे खञ्जनगञ्जने–सा. द. ४१, १२ । कालियविषधरगञ्जन–गीतगो १,१९ ।

ङ—गंजा = मदिरागृहम्–दे. २,८५ टी; गंजिअ (<गाञ्जिकः) = मद्य-विक्रेता; गंजिअ (<गञ्जितम्) = पराजितम्–उप. ९८६ टी; (२) विनाशितम्–पिंग. ।

छ—√गंजना (<गञ्जनम्) = न्यक्करणे, (२) विनाशने ।

छ—√गाँजना (<गञ्जनम्, फा. गंज) = राशीकरणे ।

अस्य धातोरिमेऽर्था यत्र तत्र प्रदेशेषु स्युर्विकीर्णाः । शब्दार्थकस्तु गंजाशब्दः, तत्स्थानां मद्यपानां शब्दायमानत्वात् । न्यक्कारेऽर्थेऽयं प्रत्युत्तरेण तिरस्कारात् प्रयुक्तः स्यात् कालान्तरे ।

+√गड् (गड) १/७७० सेचने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । सेके—वो ।
शX

√गल् (गल) १/ श्रवणेऽपि (प) ।
√गृ १/ सेचने (प) ।
√घृ १/ सेचने (प) ।

क—गेल्=मुष्टिबन्धे, दार्ढ्येन ग्रहणे, गोलाकारः, वर्तुलम् । दन्त्यविस्तारः–गेल्द्, ग्ले द्— : –वा. पॉकर्नीः ।

ङ—गड्डुल=तण्डुलादिधावनजलम्–धर्म. २ ।

छ—गड्डुआ (वा) (<गड्डुः)=जलपात्रम् ।

ञ—(कश्मीरभाषायाम्) गड्डु=अभिषेकः ।

+√गण्ड् (गडि) १/३५६ वदनैकदेशे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । गण्डे—वो ।
श

√गड्ड् १/१५९ वदनैकदेशे (प) काकृ ।

क—गेल्-, दन्त्यविस्तारः—गेल्-द्,—ग्ले-द् : नासिक्यम् (* ग्लेन्दो ? * गोल्न्दो–?)—वा. पॉकर्नीः ।

ग— वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते ।
तेनोन्नतेन गण्डेति विद्धि मानलसम्भवे ॥ मभार. १३,४४९९ ।

गण्डपार्श्वे निवेशितः–वा. रा. ५,३७,५ । गण्डोपधान०–सुश्रु. २,४१,९ ।

घ—गण्ड–संयुत्त. ४,८३ ।

ङ—गंड=कपोलः–भग.; सुपा. ८; (२) रोगविशेषः (गण्डमाला)–आचा., (३) स्तनः–उत्त. ८; (४) इक्षुसमूहः–उप. पृ. ३५९; (५) स्फोटकः—उत्त.१० ।

छ—गाल (<गल्ल <गण्डः)=कपोलः।

√गद् (गद) १/५० श	व्यक्तायां वाचि (प) क्षी-मै-सा-जै-काक्ृ-कात-शा-हे। वचने—च। भाषे—वो।	√कथ (कथ) १०/वाक्य-प्रबन्धे (प)।

ख—जइद्यॆमि (<गद्यामि)=याचे-अवेस्ता, यस्न ९,१९। अवेस्ताभाषायां दैवादिको धातुः।

ग—जगाद-मै. ४,९,१२।

ङ—√गद (सक)=भाषणे। वक्र-गदंत-नाट.—चैत. ४५।

छ—√गदना*=भाषणे।

√गम् (गम्लृ) १/९६७ श	गतौ (प) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे गत्याम्—वो।	√अच् (अचु) १/गतौ(प)। √अच्छ् १/३५५ h गतौ (प) काक्ृ। ग्+√अच्छ्=गच्छ्—इति वागीशः। √कम्ब् १/गतौ (प) वो। √अम् (अम) १/गत्यादिषु (प)। √खम्ब् १/गतौ (प)। √गम्ब् १/गतौ (प)।

क—गुऍमू—:*कुएमेति; स्को—*गुम्—स्को:।

ख—अवे. जमैति (गमति—निघ.२/१७); गसैति=गच्छति—जू. पॉकर्नीः।

ग—गमाते-तैब्रा. २,५,५,३। गच्छति-ऋ. १,१,४।

घ—गच्छति-पेतवत्थु (A) ५६।

ङ—√गम (सक)=गतौ, (२) ज्ञाने, (३) प्रापणे। भूका-गमिही-कुमा.।

+√गम्ब् (गन्ब) १/४१५ मै-श-च-जै-काक्ृ-कात-शा×	गतौ (प) (क्षी-सा-हे) वो।	√कम्ब् (कन्ब) १/गतौ (प) वो। √खम्ब् (खन्ब) १/गतौ (प) वो।

√घम्ब् (घन्ब) १/गतौ (प) वो।

अर्बेत्यादौ रेफस्थाने नकारं कौशिको मन्यते--क्षी।

√गर्ज् (गर्ज) १/२२१ शब्दे (प) द्रष्ट.√गृज् १/२४५ शब्दार्थः
श× क्षी-मै-सा-च-जै-काक्र-शा-हे। (प)।
शब्दार्थे—कात।
ऊर्जाशब्दे—वो।

क—ग्रा-क-: लिथु. गिग्ज् देति; रसन्-ग्रकति--जू. पॉकर्नीः। रसन्, च. स्ला. ग्रज, ग्रजति = काककुक्कुटशब्दे—वा. पॉकर्नीः।

ख—फार. गर्द = धूलिः।

ग—गर्जेति-सुबा. ६।

घ—गज्जति-दाठावंस ५,२९।

ङ—√गज्ज (अक) = शब्दे, मेघशब्दे। वक्र-गज्जंत-सुर. २,७५; रयण. ५८।

छ—√गर्जना
छ—√गरजना } = शब्दे, मेघशब्दे।

छ—√गाजना = शब्दे, (२) हर्षे।

छ—गजर (विपर्ययः < गर्जः) = प्रहरे प्रहरे घण्टानादः।

√गर्द् (गर्द) १/५५ शब्दे (प) √गर्ज् (गर्ज) १/२२१
श× क्षी-मै-सा-च-जै-काक्र-कात- शब्दे (प)।
शा-हे। √गर्द् १/३९४० कुत्सिते
रवे--वो। शब्दे (आ) काक्र।
अत्यानन्दे--ह्वि.।

क--गेल्-दन्त्यविस्तारः—: गेल्-द्, ग्ले-द् : गर्दभः-वा. पॉकर्नीः।

ग—समिन्द्र गर्दभं मृग नुवन्तम्-ऋ. १,२९,५; न गर्दभं पुरो अश्वान्नयन्ति-३,५३,२३। गर्दा-तै. ३,१,११,८ = कन्या, धूलिः।

ङ—गद्दह = खरः-सम. ५०; दे. २,८०; पाअ.। गाढव-मरा.।

छ—गर्दा = धूलिः।

+√गर्ब् (गर्ब) १/४१५ गतौ (प) √कर्ब् (कर्ब) १/गतौ (प)।
श× क्षी-मै-सा-च-जै-काक्र- √खर्ब् (खर्ब) १/गतौ (प)।
कात-शा-हे-वो। √घर्ब् (घर्ब) १/गतौ (प)।

छ—गरबा (नृत्यम्)-गुर्जरदेशे ।

+√गर्व् (गर्व) १/५७८ दर्पे (प)
श-जै×
क्षी-मै-सा-च-काक्र-कात-शा-हे ।
मदे—वो ।

√कर्ब् (कर्ब) १/दर्पे (प) ।
√खर्ब् (खर्ब) १/दर्पे (प) ।
√घर्ब् १/१६८d दर्पे(प)काक्र ।
√गॄ ६/निगरणे (प)—उणा. १/१५५—गर्वः ।

क—गुऍर=कठोरः, गुरुः-वा. पॉकर्नीः ।

ग—गुणाढ्या न च गर्विताः-वा. रा. १,७,६; गर्वः-२,३१,२०=अहङ्कारः ।

छ—√गर्वाना[†]=गर्वे । (गरूर<(ऊ<व)<गर्वः ।

√गर्ह् (गर्ह) १/६२९ कुत्सने (आ)
श×
क्षी-च-जै-काक्र-कात-शा-हे-वो ।
कुत्सायाम्—मै-सा ।

√गल्ह् (गल्ह) १/ कुत्सने (आ) ।
√गॄ ६/निगरणे (प) ।
√गॄ ९ शब्दे (प) ।

क—गल्—, * गल्—घ्, ग् (अ) लघ्=विलापे, शोके, कुत्सने, गर्हणे—जू. पॉकर्नीः ।

ख—अवे. गेरेजैति=दुःखे, शोके-जू. पॉकर्नीः ।

ग—गर्हसे-ऋ. ४,३,५ ।

घ—गरहति-संयुत्त. १,२४०; दीघ. १,१६१ ।

ङ—√गरह (सक)=निन्दायाम्, घृणायाम् । गरहइ-भग. ।

ङ—√गरिह (सक)=निन्दायाम्, घृणायाम् । गरिहइ, गरिहामि-महा. पडि. ।

√गल् (गल) १/५४५ अदने (प)
श-काक्र×
क्षी-मै-सा-च-जै-कात-शा-हे । स्रवणेऽपि, अनेकार्थत्वात्—क्षी ।
भक्षे स्रावे च—वो

√गॄ १/सेचने (प) ।
√गल् (गल) १०/स्रावणे (आ) ।
√गॄ ६/निगरणे (प) ।
√गिल् १/२५० a अदने (प) काक्र ।
गिल्ल् १/२५० b अदने (प) काक्र ।
गील् १/२५० c अदने (प) काक्र ।

क—गुऐल्ड-, गुऐलू-, गुले=स्रवणे, क्षेपणे, त्यागे। पु. उ. ज. कुअल्ल। पु. गॉथि. गाल्लेन्; न. उ. ज. क्वेल्ले, म. नि. ज. कुअल्म्-जू. पॉकर्नीः।

ग—गलः-गु. १७ (=कण्ठ-) [गलति=भक्षयत्यनेन]; गलितः-[धा. क्षरणे वृत्तिः उसं.] ध्या. ८५; नाप. ६, १२। गलन्त्यमी वाष्पाम्बुविन्दवः-कथास. ११, ५७। गलितं वसनम्-शिशु. ९, ७५।

घ—गळति=क्षरणे-विनय. १, २०४; मज्झिम. १, ३३६।

ङ—√गल (अक)=विशरणे, (२) नाशे, (३) क्षरणे, (४) द्रवे। गलइ-महा.।

छ—√गिरना=पतने, क्षरणे।

√गल्भ् (गल्भ) १/३८९ श×	धाष्टर्ये (आ)। क्षी-मै-सा-च-जै-कात-शा-हे। आधाष्टर्ये—काकृ। धृष्टत्वे—वो।	√गर्ह् (गर्ह) १/ कुत्सने (आ)। √गल्ह् (गल्ह) १/ कुत्सने (आ)। √गृभ् ९/ ग्रहणे (उ) वैदिकः।

अयं 'प्रगल्भ' इत्यस्य नामधा.-ह्वि., तन्न समीचीनम्, अपगल्भ०-, अवगल्भते इति प्रयोगोपलब्धेः।

ग—अपगल्भाय-मा. १६, ३२; का. १७, ५, १; तै. ४, ५, ६, १; मै. २, ९, ६; काठ. १७, १४; क. २७, ४। अवगल्भते-मभाष्ये ३, १, ११. २१। प्रजगल्भे-शिशु. १०, १८। प्रगल्भते-राजत. २, १६।

ङ—√पगब्भ (अक)=धाष्टर्ये, (२) सामर्थ्ये—पगब्भइ, पगब्भई-आचा., सूअ. १, २, २, २१।

√गल्ह् (गल्ह) १/६३० श×	कुत्सने (आ)। क्षी-च-जै-काकृ-कात-शा-हे-वो। कुत्सायाम्—मै-सा।	√गर्ह् (गर्ह) १/ कुत्सने (आ)। √गर्ह् (गर्ह) १०/ विनिन्दने (प)। √गल्भ् (गल्भ) १/ धाष्टर्ये (आ)।

नूनमयं √गर्ह्-धातुसम्बद्धस्तदुत्तरवर्ती।

छ—√गाल्हना*† ⎫ (<गल्पः ???)=भाषणे। अतिभाषणमपि क्वचिद्
छ—√गाल्ना*† ⎭ धाष्टर्याय धाष्टर्यं च कुत्सनाय भवतीति √गल्ह्
धातुरस्य मूले भाति।

+√गा (गाङ्) १/९३५ श×	गतौ (आ)। क्षी-मै-सा-च-जै-काक्र- कात-शा-हे-वो।	इणो गा लुङि २/२/४५। √गा ३/ स्तुतौ च च्छन्दसि, जनने च (प)। √गै १/ शब्दे (प)।

ह्विटनीर्गमनार्थकं √गा धातुं स्वीकरोति जुहोत्यादौ, न त्विह।

√गा ३/२५ श-जै-काक्र-कात-शा×	स्तुतौ च च्छन्दसि (प)। क्षी-मै-सा-च-(हे)। स्तुतौ जन्मनि—वो। गतौ—ह्वि.।	√गै १/ शब्दे (प)। √गा (गाङ्) १/ शब्दे गतौ (आ)। √इ (इण्) २/ गतौ (प) इणो गा लुङि २/४/४५। गाति, जिगाति–निघ. २/१४ गतिकर्मा।

क—गु॒एम्–तथा गु॒आ=गतौ, प्रापणे।

ग—जिगाति–ऋ. १, २, ३; खि. ४, ९, १; तै. १, ३, ४, १; मै. १, ६, १; जै. ३, २, ११। जिगाति–ऐब्रा. १, ३०; शाब्रा, ९, ६; शब्रा. १, ४, १, २१। अगात्–काब्रा. १, ३, १३।

+√गाध् (गाधृ) १/४ श (जै-४-गाढ्रैँ, ५-गादैँ)!	प्रतिष्ठालिप्सयोर्ग्रन्थे (आ)। क्षी-मै-सा-कात। प्रतिष्ठालिप्सार्थयोर्ग्रन्थे च—काक्र। प्रतिष्ठायाम्—च। प्रतिष्ठाग्रन्थयोर्लिप्से च—वो। प्रतिष्ठालिप्साग्रन्थेषु—जै-शा-हे।	√गाथ् १/३७५b प्रतिष्ठा-लिप्सार्थयोर्ग्रन्थे च (आ) काक्र √गाढ् १/१८९a तीव्रगतौ (प) काक्र। √गाहू (गाहू) १/ विलोडने (आ)। स नदीस्तुष्टाव गाधा भवत-निरु. २, २४।

क—गु॒आध्=निमज्जने, आर्द्रतायाम्—वा. पॉकर्नीः।

ग—गाधम्-ऋ. १,६१,११; अशीमहि गाधमुत प्रतिष्ठाम्-ऋ. ५,४७,७। गाधमेव प्रतिष्ठा-शब्रा. १२,२,१,२। खि. २,१४,३; तै. ४,३,११,४; मै. २,१३,१०, काठ. २९,८। अगाधः-वा. रा. १,३५,४=अतलस्पर्शः (तिल.)। गाधिः (गाधते=उच्चपदं लिप्सते) मभार. ३,११५,१९=विश्वामित्रमुनिपिता। गाधेत-यशस्तिलक., आश्वा. ३, श्लो. १५३=तरितुं शक्येत। अगाधम्-मभार. १२,३०८,३९=अप्रतिष्ठम्—(नील.)।

घ—गाधति-दीघ १,२२३=संयुत्त. १,१५।

ङ—√गाह (सक)=(१) पठने, अभ्यासे, (२) अनुभवे, (३) गवेषणे। गाहदि-शौ.।

√गाहू (गाहू) १/६४१ शः विलोडने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। विलोडे—वो। √गथ् १/६४७ विलोडने (प) काकृ। √गाध् (गाधृ) १/ प्रतिष्ठा-लिप्सयोर्ग्रन्थे च (आ)।

क—द्रष्ट.√गाध्।

ग—अतिगाहते-ऋ. ९, ६७, २०; अभिगाहमानः-१०,१०३,७; गाहात्-९,११०,८; कौ. २,८४४। गाहते-ऐब्रा. ३,४८।

गोप्तरि गाहमाने-रघु. २,१२=प्रविशति सति (सं.); तपस्विगाढाम्-९,७२=अवगाढाम्=सेविताम् (सं.)।

घ—अज्झोगाहति (<अभ्यवगाहते)-दीघ. १,१०१।

ङ—द्र.√गाध्।

छ—√गाहना=अवगाहने, (२) मन्थने (विलोडने), (३) क्षेत्रकर्षणे।

√गु (गुङ्) १/९३४ श× अव्यक्ते शब्दे (आ) क्षी-मै-सा-च-जै-शा। शब्दे—काकृ-कात-हे। ध्वनौ—वो। √कु २/ शब्दे (प)। √कु (कुङ्) १/ शब्दे (आ)। √उ (उङ्) १/ शब्दे (आ)। √खु (खुङ्) १/ शब्दे (आ)। √घु (घुङ्) १/ शब्दे (आ)। गवते (निघ. २/१४) गतिकर्मा।

क—गॉउ-, गोउ-, गॉउऍ-, गु-=शब्दे। लिथु.—*गॉउदिऍति। पु. च. स्लॉ.-गॉवॉ रिति—जू. पाकर्नीः।

ग—विश्वासु क्षासु जोगुवे-ऋ. ५,६४,२; जोगुवानः-१,६१,१४।

+√गु ६/१२५ क्षी-च-काक्×, श	पुरीषोत्सर्गे (प) मै मै-सा-जै-कात-शा-हे।	√गुध् ६/९२ पुरीषोत्सर्गे (प) च।

ग—गुदम्–मनु. ८,२२८। उभयथा साध्यम्–√गुद् १/२३ इत्यतः, √गु इत्यतश्च।

√+गुज् (गुज) १/२०० मै-श-च-कात×	अव्यक्ते शब्दे (प) अनिदिदित्येके–क्षी क्षी-सा-जै-शा-हे। शब्दे—काक्। कूजने—वो।	<√गुञ्ज् (गुजि) अव्यक्ते शब्दे (प)। √गु (गुङ्) १/ अव्यक्ते शब्दे (आ)। कूज् (कूज) १/ अव्यक्ते शब्दे (आ)। √कुच् (कुच) १/१८१ शब्दे तारे (प)। √कुञ्ज् (कुञ्ज) १/७४० अव्यक्ते शब्दे (प) काक्।

स्पष्टो विकासः √गु>√गुज्>√गुञ्ज्।

+√गुज् (गुज) ६/८९ श	शब्दे (प) क्षी-मै-सा-च-जै-काक्-कात-शा-हे। ध्वनौ—वो।	पूर्ववत्।

√कु>√कुच्>√कुञ्च्>√कूज्,√कु>√गु>√गुज्>√गुञ्ज् इति व्युत्पत्तिः।

√गुञ्ज् (गुजि) १/२०० श×	अव्यक्ते शब्दे (प) क्षी-मै-सा-च-जै-कात-शा-हे। पूर्वद्वयवत्। शब्दे—काक्। कूजने—वो।

क—गंज्–=अनुकरणे, उपहासे, आक्षेपे। गंजो–स्,—जू. पॉकर्नीः।

ग—गुञ्जन्–ऋतु. ६,१४; गीतगो. २,१। मञ्जुगुञ्जत्समीर०–शान्तिश. १,२७। गुञ्जा–सुश्रु. १,३२,१७; बृ. सं. ८२,८।

घ—√गुंज (अक)=भ्रमरादिरवे, (२) सिंहादिगर्जने। गुंजंति–महा.।

छ—√गुंजना=भ्रमरादिरवे।

छ—√गुंजना=भ्रमरादिरवे।

+√गुड् (गुड) ६/९० श	रक्षायाम् (प) क्षी-मै-सा-च-काकृ-कात-शा-हे। रक्षणे—जै। रक्षे व्याघाते च—वो।	√कुण्ठ् (कुठि) १०/ रक्षणे (प) सा। √कुण्ड् (कुडि) १०/ रक्षणे (प) इत्येके—क्षी। √गुड् १/१५३ माधुर्ये (प) काकृ। √गुण्ड् (गुडि) १०/ रक्षणे (प)। √गूड् १/१८६b निवासे (प) काकृ। √जुल् १०/८७ रक्षणे (प) काकृ।

ग—कार्ष्णायसमया गुडाः–मभार. ७,९२१२; समुशुण्डयश्मगुडका (पुरी)-३,६४३; शतघ्न्योऽथ गुडा गदाः–७,९२१३; (गडति=रक्षति–अनयेति)।

घ—गुळ=वर्तुलीकरणे–दीघ. १,५४=मिलिन्दपञ्ह ३,९५।

ङ—√गुड (सक)=कवचादिर्भिर्हस्तिनः सज्जायाम्, (२) युद्धार्थं तत्पर-तायाम्, सज्जायाम्। गुडह–सुपा. २८८।

छ—गौड़ा (<गुडाः–मभार. ७,९२१२)–बु. ख. = यष्टिविशेषः।

√गुड् (गुड) ६/१०३ मै-सा-श-च-जै-काकृ-कात-शा ×	प्रतीघाते (प) क्षी-हे। व्याघाते—वो।	>√घुट् (घुट) प्रतीघाते (प) इति दुर्गः–क्षी। √खोड् १/२५१ प्रतिघाते (प) हे। √खोर् १/४१२ प्रतिघाते (प) हे। √कुण्ठ् (कुठि) १/ गतिप्रतिघाते (प)। √कुण्ड् (कुडि) १/ वैकल्ये (प)। √कुट् (कुट) ६/ कौटिल्ये (प)।

√कुट् >√कुण्ट् १/३१९ >√कुण्ठ् >√कुण्ड् >√खोड् >√गुड् >√घुट् इति विकासः।

+√गुद् (गुद) १/२३ क्रीडायामेव (आ) द्रष्ट. √कुर्द् १/२१।
शा-च-काकृ-कात ×

क्षी-मै-सा।
क्रीडायाम्--शा-हे।
जै ?
खेलने—वो।

ग—गुदा-ऋ. १०,१६३,३। गुदा अन्त्राणि उदरम्-अ. वे. ९,७,१६; १०,९,१६। उत्सक्थ्या अव गुदं धेहि (रेतः) -वा. सं. २३,२१। अवशब्दयतो गुदम्-मनु. ८,२२८।

छ—√गोदना = विलेखने, क्रीडने (गुदगुदाना-हि.)।

+√गुध् (गुध) १/२३ क्रीडायामेव (आ) <√गुद् (गुद) क्रीडायामेव (आ)।
मै-सा-श-च-काकृ-कात-शा ×

इत्येके—क्षी।
क्रीडायाम्—हे।
क्रीडे—वो।
शेषः पूर्ववत्।

स्पष्टं √गुद् धातोर्विकासः (भेदः) प्रदेशविशेषे।

+√गुध् (गुध) ४/१२ परिवेष्टने (प) गध्यति मिश्रीभावकर्मा-निरु. ५,१५,५।
श

क्षी-मै सा-जै-काकृ-कात-शा-हे।
वेष्टने—च।
वेष्टे—वो।

√गुद् (गुद १/ क्रीडायामेव (आ)।
√गुध् (गुध) १/ क्रीडायामेव (आ)।
√गुध् ६/९२ पुरीषोत्सर्गे (प) च।

छ—√गूँधना = गोधूमचूर्णादिमर्दने (वेष्टने) [स्वयम्भूरनुस्वारः]।

+√गुध् (गुध) ९/४५ रोषे (प) √क्रुध् (क्रुध) ४/ कोपे (प)।

क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
रुषि—वो।

√गुध् (गुध) ४/ परिवेष्टने (प)।

क्रुध् > √गुध्। √गुध् ४/१२ धातुनाऽस्य पूर्णतः सम्बन्धः। क्रोधे सति वेष्टनमर्दनादिकं संपद्यत एव।

√गुप् (गुपू) १/३९३ श	रक्षणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । रक्षे—वो ।	√गुप् (गुप) १/ गोपने (आ)। √गुप् (गुप) ४/ व्याकुलत्वे (प)। √गुप् (गुपू) १०/ भासार्थः (प)। √कुप् (कुपू) १०/ भासार्थः (प)।

ग—जुगुपुः (द्वादशस्य ऋतं नरः)-ऋ. ७,१०३,९ । शौ. १९,२७,९ । गोपायति–ऐब्रा. ७,२२ । जुगुप्सेत्–मभार. १२,१३१,८=पालयितुमिच्छेत् (नील.) ।

घ—गोपेथ–धम्मपद ३१५ ।

ङ—√गोव (सक)=(१) रक्षणे, (२) आच्छादने । गोवइ, गोवेइ—सुपा. ३४६; महा. ।

छ—√गोपना*†
 छ—√गोना } =(गोपनम्) अप्रकाशने (आच्छादने) ।

+√गुप् (गुप) १/९५५ श×	गोपने (आ) क्षी-च-शा । गोपनकुत्सनयोः—मै-सा-काकृ-कात-हे । गुप्तौ—जै । गोपनकुत्सयोः—वो ।	√गुप् (गुप) ४/ व्याकुलत्वे (प)।

ग—विजुगुप्सते (विचिकित्सति—शब्रा. १४,७,२,१८) –बृहदारण्यको. ४,४,१५ । जुगुप्सेत–छान्दो. ५,१०,८; नाप. ५,७ ।

ङ—√जुउच्छ (सक)=निन्दायाम् , घृणायाम् । जुउच्छइ–से. ५,५ ।

+√गुप् (गुप) ४/१२१ श	व्याकुलत्वे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । व्याकुलत्वे च—जै । चकारो मुद्रणदोषदुष्टः ।	√कुप् (कुप) ४/ क्रोधे (प) । द्रष्ट. √गुप् १/३९३ ।

ङ—√गुप्प (अक)=व्याकुलत्वे । वकृ–गुप्पंत, गुप्पमाण–कुमा. ६,१०२; कप्प.; औप. ।

√गुफ् (गुफ) ६/३८
श

ग्रन्थे (प)।
क्षी-मै-सा-च-काक्र-
कात-शा-हे-वो।
ग्रन्थने—जै-शा-हे।

√गुम्फ् (गुम्फ)६/ग्रन्थे (प)।
√ग्रथ् १/३३१ कौटिल्ये
(आ) च।

ग—गुफिताश्चरणयोः पुनर्विस्तृताः (द्रग्भक्तयः)–धूर्तस. ६६,९।
ङ—√गुहना †(सक)=ग्रन्थने।

वस्तुतोऽयं धातुः–"पुराणवद् व्रततेरिव गुष्पितम्"–ऋ. ८,४०,६,√गुष्प् इत्यस्य विकासरूपः।

√गुम्फ् (गुम्फ) ६/३९
श

ग्रन्थे (प)
क्षी-मै-सा-च-काक्र-
कात-वो।
ग्रन्थने—जै-शा-हे।

√गुफ् (गुफ) ६/ ग्रन्थे (प)।
√ग्रन्थ् (ग्रथि) १/ कौटिल्ये
(आ)।
√ग्रन्थ्(ग्रन्थ)९/सन्दर्भे (प)।
√गुम्भितः–सार. २४४ः १७।

ग—निगुम्फनिर्झर०–शिवताण्ड. १३।
ङ—√गुंफ (सक)=ग्रन्थने। वक्र-गुंफंत–कुमा.।
ङ—√गुम्ह (सक)=ग्रन्थने, रचनायाम्। गुम्हदु–शौ.; स्वप्न. ५३।

√गुर् (गुरी) ६/११५
श

उद्यमे (आ)
क्षी-च-काक्र-कात-हे-वो।
उद्यमने—मै-सा-जै-शा।

√गॄ ६/ निगरणे (प)।
√गूर् (गूरी) १०/ उद्यमे
(आ)।
√गूर् (गुरी) ४/ हिंसा-
वयोहान्योः (आ)।

क—गुर्एर्=प्रशंसायाम्, स्तुतौ–वा. पॉकर्नीः।
ग—गुरस्व च–ऋ. ३,५२,२। नापगुरेत न निहन्यात्–तै. २,६,१०,२।
आत्मानमागुरते–तैब्रा. १,४,७,७१।

√गुर्द् (गुर्द) १/२२
मै-श×

क्रीडायामेव (आ)
क्षी-सा-काक्र-कात।
क्रीडायाम्—च-जै-शा-हे।
कूर्दे—वो।
अत्यानन्दे ?—ह्रि.।

>√खुर्द् (खुर्द) क्रीडाया-
मेव (आ) इति दौर्गाः
—क्षी।
द्रष्ट.√कुर्द् १/२१

ग—अगूर्दत्, अगूर्दन्–जै. १९१। गूर्दः–तांब्रा. १३,१२,४; जैब्रा. १,४४९। गूर्दम्–शांब्रा. ३०,३। लौकिके संस्कृते जातः स्यादात्मनेपदी।

+√गुर्व् (गुर्वी) १/५७१ उद्यमे (प) शX	क्षी-च-काकृ-कात-हे-वो । उद्यमने—मै-सा-जै-शा ।	√गॄ ६/ निगरणे (प)। √गुर् (गुरी) ६/ उद्यमे (प)। √गुल्फ् १/२०४ n गतौ (प) काकृ ।

गुर् ६/११५ इत्येतत्सम्बद्धोऽयम् ।

√गुह् (गुहू) १/८८१ श	संवरणे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । संवृतौ—वो ।	√कुह् १/३१६a हिंसागत्योः (प) काकृ । √गुह् १/३१६d हिंसागत्योः (प) काकृ । √गुह् १/३१६e हिंसागत्योः (प) काकृ ।

क—घेउघ्—, घुघ्—, घूघ्—(संवरणे) छादने । लिथु.—गूज़्ति—जू. पॉकर्नीः ।

ग—गूहते—ऋ. १०,२७,२४ । गूहन्ति—१०,१०८,४ । मभार० ६,३,२२,१६= परिवारयन्ति (नील.) । गूहेत् कूर्म इवाङ्गानि—मनु. ७,१०५ ।

ङ—गूह (सक)=गोपने, छादने । वक्त—गूहंत—स. ६१० ।

+√ गू १/९३४ मै-सा-च-जै-काकृ-कात-शा-हे-वो X	पुरीषोत्सर्गे (प) इत्येके—क्षी । क्षी-हे ।	>√गु (गुङ्) अव्यक्ते शब्दे (आ)।

उत्तरसूत्रादभिन्नोऽयं गणभेदार्थमिहोपन्यस्तः ।

+√गू ६/११८ मै-सा-श-च-जै-कात-शा X	पुरीषोत्सर्गे (प) क्षी-काकृ-हे । विट्सृतौ—मै ।	√गू १/ पुरीषोत्सर्गे (प)। √गुध् ६/९२ (प) च ।
√गु ६/१२५……	पुरीषोत्सर्गे—मै । मै-सा-जै-कात-शा-हे ।	

क—गू्ओउ—, गुऊ—विष्ठा, घृणितम् ,: पूतिगन्धि (विशेष०) । अर्मे.—कु तथा कॉय=विष्ठा । च. स्लॉ. ओ—गविति । čech (बोहे.) ओ—हविति=कुरूपणे ।

ख—गू—थ=विष्ठा—वा. पॉकर्नीः ।

ङ—गूह (<गूथम्)=विष्ठा—तंदु. ।

+√गूर् (गूरी) ४/४४ शु	च=हिंसावयोहान्योः (आ) इति दुर्गः—क्षी ।	<√घूर् (घूरी) हिंसावयोहान्योः (आ) ।
	क्षी ।	√गुर् (गुरी) ६/ उद्यमे (प) ।
	हिंसागत्योः—मै-सा ।	
	हिंसायाम्—च-काकृ-कात ।	√गुर्व् (गुर्वी) १/ उद्यमे (प) ।
	गतिहिंसयोः—जै-शा ।	
	गतौ हिंसायां च—हे ।	√जॄ (जॄष्) ४/ वयोहानौ (प) ।
	वधे गत्याम्—वो ।	

√जॄ ४/ >√गूर् (गूरी) >घूर् (घूरी) इति क्रमः । √गुर् ६/११५, √गुर्व १/५७१ इत्येताभ्यामपि गत्यर्थकत्वात् संबद्धः ।

+√गृ १/९२१ श×	सेचने (प)	√गल १/ स्रवणेऽपि (प) ।
	क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।	√घृ १/ सेचने (प) ।
		√घृ ३/ क्षरणदीप्त्योः (प) ।
	सेके—वो ।	√घृ १०/स्रावणे (प) ।

छ—√गराना*=निश्च्योतने, स्रावणे ।

[√गारना-(>गालनम्)=निष्पीडने, (२) *बहिष्कारे, त्यागे, अपनये ।

गरगरा=गण्डूषक्रिया (सेचनम्) । धातुरयं शब्दानुकृतिः। यत्र 'गर्' इत्थंभूतः शब्दो भवति निश्च्योतनगण्डूषक्रियादौ तत्रैवैष प्रयुज्यते ।

+√गृज् (गृज) १/२४५ श-कात×	शब्दार्थः (प)	√गज् (गज) १/ शब्दार्थः (प) ।
	क्षी-मै-सा-च ।	
	शब्दे—जै-काकृ-शा-हे ।	√गज् (गर्ज) १/ शब्दे (प)-द्रष्ट. ।
	ध्वनौ—वो ।	
		√गञ्ज् (गजि) १/ शब्दार्थः (प) ।
		गृञ्ज् (गृजि) १/ शब्दार्थः (प) ।

ग—जीमूत इव गर्जति—वा. रा. ५,५,२४।

√गर्ज् १/२२१,√गृज् धात्वो रूपाणां लिट् लकारस्य तिप्सिब्मिब्भिन्न-प्रत्ययेषु परेषु भेदो जायते-√गृज्-जगृजतुः, जगृजुः,√गर्ज-जगर्जतुः, जगर्जुः। आशी-

लिङि तु सुस्पष्टो भेदः कात्स्न्येन । परमिमानि रूपाणि यथागवेषितं साहित्ये नावाप्तानि मया । अन्यत्र लकारेषु तु गर्जवज्ज्ञानीयोऽयम् इति द्वावेव धातू मिथः संक्रान्तौ ।

+√गृञ्ज् (गृजि) १/२४६ शब्दार्थः (प) पूर्ववत् ।
श× क्षी-मै-सा-च-कात ।
शब्दे—जै-काकृ-शा-हे ।
ध्वनौ—वो ।

क—* गेल्-ज्—ः-वा. पॉकर्नीः ।

ग—गृञ्जन०- सुश्रु. २,५१९,४ । गृञ्जनक०-मभार. १३,४३६४ ।

√गृध् (गृधु) ४/१३३ अभिकाङ्क्षायाम् (प) √गॄ ६/ निगरणे (प) ।
श क्षी-मै-सा-च-जै-काकृ- √गॄ ९/ शब्दे (प) ।
कात-शा-हे । √गर्ध् (गर्ध) १०/ अभि-
लिप्से—वो । काङ्क्षायाम् (प) ।

क—घेल्ध्= काङ्क्षायाम् । सर्बि., च. स्लॉ. ज्लदेति । सेर्बो-क्रोटि. जुद्जेति-जू. पॉकर्नीः ।

ग—अगृधत्-ऋ. १०,३४,४ । गृध्यन्ति-शब्रा. ३,३,३,२२ । गृध्यतः-मभार. १४,१३,२ = सक्तस्य (नील.) ।

घ—गिज्झित (कर्मणि)-थेरगाथा २,१५२ ।

ङ—√गिज्झ (अक) = आसक्तौ, लाम्पट्ये । गिज्झइ-णाया. १,८ ।

छ—√गीधना = काङ्क्षायाम्, आसक्तौ, लाम्पट्ये । एकदाऽनुभूय सदा तत्काङ्क्षणे ।

+√गृह् (गृहू) १/६४२ ग्रहणे (आ) इति चन्द्र- <√ग्लह् (ग्लहू) ग्रहणे
श-जै-काकृ-कात-शा- दुर्गौ—क्षी (आ) ।
वो× क्षी-मै-सा-च-हे । √ग्रिह् (ग्रिहू) १/ ग्रहणे
(आ) क्वचित् कोशे—सा ।
√ग्रह् (ग्रह) ९/उपादाने (उ) ।
√ग्रह् १/ग्रहणे (आ) वो ।
√गर्ह् (गर्ह) १/कुत्सने(आ) ।

गर्हते (द्र. √गर्ह् १/६२९) इत्यादिरूपाणि तूपलभ्यन्ते, परन्तु तानि कुत्सनार्थकानि ।

√गॄ ६/१२९ निगरणे (प)
श× क्षी-मै-सा-च-जै-काकृ-कात- द्रष्ट. √गल् १/५४५ ।
शा-हे-वो ।

√गृ, √गिर्, √गिल् —ह्वि. ।

क—गुऍर्–,गुऍर् = निगरणे । अर्मे.–कॆर् । अल्बे. न्गूरने । लिथु. गेर्ति, ग्रियति ।

ख—जरैति = गिरति—जू. पाकर्नीः ।

ग—जगार–ऋ. १०,२७,१३ । गिरति–काठ. २३,६ । यद् गिरामि संगिरामि–शौ. ६, १३५,३ । गिलति, गिलन्ति–गुह्यकाण्डप. २६ । गिरति–मभार. ५,४६,१३ = उपसंहरति (नील.) ।

घ—मा राहु गिली–संयुत्त. १,५१ ।

ङ—√गिल (सक) = गिलने, भक्षणे । संकृ–गिलिऊण–नाट. ।

छ—√गिलना = गिलने, दन्तसाहाय्यमन्तरा भक्षणे ।

छ—गेरना = पातने, (२) उद्देलने (>उड़ेलना–हि.) ।

√गॄ ९/२७ शब्दे (प) √गुर् (गुरी) उद्यमे (आ) ।
श× क्षी-मै-सा-च-जै-काकृ- √गॄ ६/ निगरणे (प) ।
कात-शा-हे-वो । √गृज् (गृज) १/ शब्दार्थः (प) ।

क—गुऍर ( ) = स्तुतौ–जू. पॉकर्नीः, वा. पॉकर्नीः ।

ग—गृणीते–ऋ. १,७९,११ । अनु गृणाति–१,१४७,२ । गृणन्ति–खि. ३,६,१ । गृणाति ह वा एतद्धोता यच्छंसति–शब्रा. ४,३,२,१ । गृणन्ति–मभार. १२,४७,२६ = ध्यायन्ति (नील.) ; यशस्तिल., २ आ., १४९ = जानन्ति ।

+√गेप् (गेपृ) १/३६५ च = कम्पने, गतौ (आ) √केप् (केपृ) १/च = कम्पने, गतौ (आ) ।
श× सूत्रविभागात्–क्षी ।
क्षी-सा । √कम्प् (कपि) १/ चलने (आ) ।
कम्पने—मै-च ।
चलने—जै-कात-शा-हे । √खेप् १/१४२ चलने (आ) जै, ९३० शा ।
केप्वत् (= गत्यां चाले)—वो । √ग्लेप् (ग्लेपृ) १/ च = कम्पने, गतौ (आ) ।

√ग्लेप् (ग्लेपृ) १/ दैन्ये (आ)।

√कम्प् >√केप् >√गेप् >√ग्लेप् इति व्युत्पत्तिः।

छ—√घेपना=निधुवने, (२) हस्तपादेन सम्मर्द्य मिश्रणे।

+√गेप् (गेपृ) १/३६९ च=दैन्ये (आ) मै।
क्षी-सा-श-च-जै-काक्ष- मै। पूर्ववत्।
कात-शा-हे-वो ×

√कम्प् >√केप् >√गेप् >√ग्लेप् इत्यत्र परम्परया कम्पनार्थकत्वाद् दीनतया दैन्यार्थो जातः। भयेऽपि सति भवति कम्पनम्।

+√गेव् (गेवृ) १/५०२ सेचने (आ) मै।
क्षी-श ×
मै-सा-काक्ष-कात।
सेवने—च-जै-शा-हे।
सेवे—वो।

एव् (एवृ) १/ सेवने (आ)
क्+√एव=√केव्।
ग्रेव् १/५०४g सेचने (आ) काक्ष।
√ग्लेव् (ग्लेवृ) १/ सेचने (आ) मै।
√घृ १/ सेचने (प)।
√घेव् १/५०४f सेचने (आ) काक्ष।

द्रष्ट. √खेव् १/५०२।

√+√गेष् (गेषृ) १/६०९ अन्विच्छायाम् (आ)
मै-श-च-काक्ष- क्षी-सा-जै-शा-हे।
कात × अन्वेषे—वो।

√इष् (इष) ४/ गतौ (प)।
√इष् (इषु) ६/ इच्छायाम् (प)।
√एष् (एषृ) १/ गतौ (प)
ग्+√एष्=√गेष्।
गव्+√एष्=√गवेष् (गवेष) १०/मार्गणे (प)।
√ग्ल्+√एष् √ग्लेष् १/ अन्विच्छायाम् (आ)।

अन्विच्छा =गवेषणा—क्षी।

√गै १/९०२ शब्दे (प)
श क्षी-मै-सा-च-जै-काक्ष-
कात-शा-हे।

√कै १/ शब्दे (प)।
√गा ३/ स्तुतौ च च्छन्दसि (प)।

	गाने—वो ।	गायति-निघ. ३/१४-
√गा ४/···	गाने—ह्वि. ।	अर्चतिकर्मा ।

क—गे (इ)-ः गो (इ)-ः=गाने । पु. एसन्. गजि, गकति । लेट्टिश्-ग्यस्ति; ज्यस्ति—जू. पॉकर्नीः ।

ग—गायति-ऋ. १०,७१,११; काठ. १४,७ । गायते-मै. १,६,७ । आ गासि-ऋ. ८,२७,२ । गान्ति-म्रभार. ३,१५८५० ।

घ—गायिस्सति-विनय. २,१०८ ।

ङ—√गा
ङ—√गाअ } (सक)=गाने, आलापे, (२) वर्णने, (३) श्लाघायाम् ।

वक्त-गंत, गाअंत, गायमाण-गा. ५४६; पि. ४७९; पउम. ६४,२४ । कवक्त-गिज्जंत-गउड.; गा. ६४२; सुपा. २१ ।

छ—√गाना=सालापे ध्वनौ, (२) मधुरध्वनौ, (३) कथने, वर्णने ।

√गोष्ट् (गोष्ट) १/२५५ शX ('च'-तरङ्गिण्या लीबिश-संस्करणे मुद्रणदोषः) काक्त-√योष्ट् [योष्ट] लैपिकी त्रुटिः । 'गोष्ट' इति भाव्यम् ।	संघाते (आ) क्षी-मै-सा-च-जै-काक्त-कात-शा-हे-वो ।	गो+√स्त्यै १/ वेष्टने (प)= गो+स्त = √गोष्ट । √(पु) स्त (पुस्त) १०/ संघाते (प) । √(मु) स्त (मुस्त) १०/ संघाते (प) । √(लो) ष्ट् (लोष्ट) १/ संघाते (आ) ।

अयं धातुः 'गोष्ठ'-(गावो गोष्ठे असदन्-ऋ. १,१९१,४)-शब्दान्निष्पन्नो भाति । प्रत्यक्षं तु 'गोष्ठ' इत्यत्र 'गो'+स्थ इति विभागः । अत्र च गो+'स्त' इति । अयं 'स्त' अनेकत्र धातुषु सङ्घातार्थेषु पर्यन्ते तिष्ठति । यथा-√(पु) स्त् (पुस्त), √(मु) स्त् (मुस्त), √(यो) ष्ट् (योष्ट), √(लो) ष्ट् (लोष्ट) प्रभृति ।

छ—√गोट (<गोष्टः), >गोटा=शाटिकादिप्रान्तलग्नं चारुवसनम्, तूर्पः ।

छ—√गोंठना = वेष्टने ।

[+]√ग्रन्थ् (ग्रथि) १/३५ श-चX	कौटिल्ये (आ) क्षी-मै-सा-जै-काक्त-कात-शा-हे । जैह्मये—वो ।	√ग्रथ् १/१३१ कौटिल्ये (आ) च । √ग्रथ् १०/३२८ बन्धने (प) जै, २४६ शा । √गोड् १/१५४ बन्धने (प) काक्त ।

कौटिल्यम्=शाठ्यं वक्रता वा-सा ३६ ।

घ—गन्थति–संयुत्त. १,२१४=सुत्तनिपात १८५।
ङ—√गंथ (सक)=ग्रन्थने। गंथइ–पि. ३३३।
ङ—√गह (सक)=ग्रन्थने। गहेति–सूअनि. १४०।

√ग्रन्थ् (ग्रन्थ) ९/४१ श
सन्दर्भे (प)
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
दर्भे—वो।
पूर्ववत्।

क—ग्र्-एत् (हू)-: अनुनासिकः—सं.√ग्रन्थ्–जू. पॉकर्नीः।
ग—ग्रथ्नाति–मै. ३,८,७; तैब्रा. ३,३,३,४।
ङ—गुत्थ (<ग्रथित०)–स. ३०३; प्राप; गा. ६३.; कप्पू.।

√ग्रस् (ग्रसु) १/६२३ श×
अदने (आ)
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
भक्षे—वो।
√ग्लस् (ग्लसु) १/ अदने (आ)।
√ग्रह् (ग्रहू) १/ ग्रहणे (आ) वो।
√ग्लह् (ग्लहू) १/ ग्रहणे (आ)।
√घस् (घस्लृ १/ अदने (प) इति केचित्–क्षी।

क—ग्रस्-: ग्रॅस्-, ग्रोस्=भक्षणे–जू. पॉकर्नीः।
ग—ग्रसेताम्–ऋ. ३,३५,३। अग्रसत–तै. ३,४,३,१; मै. १,५,१२; ग्रसमानः–गी. ११,३०।

घ—घसति–जातक ३,२१०।
ङ—√गस=भक्षणे। वकृ–गसंत–उप. ३२० टी.; गसण (ग्रसनम्)–स. ३५७।
छ—√ग्रसना=भक्षणे, (२) दार्ढ्येन ग्रहणे।
छ—√ग़िरासना † *=दार्ढ्येन ग्रहणे।

√ग्रह् (ग्रह) ९/६१ श (जै–गृहञ्)
उपादाने (उ)
क्षी-मै-सा-च-जै-काकृ-कात-
शा-हे।
आदाने—वो।
√गर्भो गृभेर्गृणात्यर्थे–निरु. १०/२३/१
√गृह् (गृहू) १/ ग्रहणे (आ) चन्द्रदुर्गौ–क्षी।

√ग्रस् (ग्रस) १०/ ग्रहणे (प)।
द्रष्ट.√ग्रस् १/६३२।

क—ग्रेभ्-, ग्रेभं; धातुविस्तारः-ग्रेभा=ग्रहणे। तु.-ग्रेइभ्-इत्यापि। पु. च. स्ला. ग्रेति, ग्रबिति, लिथु. ग्रबॉति, सेर्वो-क्रोटि. ग्रबिति, बोहे. ह्रबिति।

ख—अवे.-गूरु॑ब्नाइति, गुउर्वयेइति; पु. पर्सि. गर्बायैति, [न. पर्सि. ग्रिफ्त (<सं. गृभीत०—ऐब्रा. २,१)]—जू. पॉकर्नीः।

ग—गृभ्णते-ऋ. ९,८६,४३। गृह्णते-मुण्डको. १,१,७। गृभ्णामि-मण्डलब्राह्मणो. १,२, १६। गृह्णामि-वरा. २,३५; २ संन्या. १७ : ५। गृह्णाति-बृ. २,१,१७।

घ—गण्हाति-जातक १,१५९=परामर्शे, विचारविमर्शे।

ङ—√गिण्ह (सक)=आदाने, (२) ज्ञाने। गिण्हइ-कप्प.; वकृ-गिण्हंत-सुपा. ६१९; णाया. १,१।

ङ—√गह (सक)=आदाने, (२) ज्ञाने। गहेइ-सण.।

छ—√गहना-(<गहण<ग्रहणम्)=धारणे, ग्रहणे।

+√ग्रिहू (ग्रिहू) १/६४१ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो× ग्रहणे (आ) क्वचित् कोशे—सा। सा। तदनार्षः—सा। <√गृहू (गृहू) ग्रहणे (आ)।

सायणः कस्यचन धातुपाठस्य मतमुद्धरति, निराकरोति च तत्।

+√ग्रुचु (ग्रुचु) १/१९४ श× स्तेयकरणे (प) क्षी-मै-सा-जै-काकृ-कात-शा। स्तेये—च-हे। गतौ चौर्ये च—वो। द्रष्ट. √कुज् १/१९६; √खुज् १/१९७।

√कुच् १/५०e काकृ >√कुज् १/१९६>√खुच् १/५०f काकृ>√गुज् १/५० c काकृ>√ग्रुच्>√ग्लुच् इति परम्परा।

+√ग्लस्(ग्लसु) १/६२४ श× अदने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। भक्षे-वो। द्रष्ट.√ग्रस् १/६२३।

√ग्रस् १/६२३ अयमेव धातू रलयोर्भेदेन भेदं प्राप्तः। अमरकोशं (३,२, ६०) विहाय क्वापि नोल्लेखः।

√ग्लह्(ग्लहू) १/६४२ ग्रहणे (आ)
श-च-काकृ-कात× क्षी-मै-सा-जै-शा-हे। द्रष्ट.√ग्रह् ९/६१।
आदाने--वो।
द्यूते--ह्वि.।

ग—ग्लहनम्-शौ. ७,११४,५; (७,१०९,५)। दुर्योधनो ग्लहते पाण्डवेन-मभार. २,२११५; तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ-८,४४०४; ७,५३२८; कितवोऽग्लहीष्यत्-२,२३९७ ; (२,६७,१९); ग्लहते-७,१५१,१०=पातयति (नील.)।

+√ग्लुच्(ग्लुचु) १/१९५ स्तेयकरणे (प)
श× क्षी-मै-सा-जै-काकृ-कात-शा। द्रष्ट.√ग्रुच् १/१९४।
स्तेये--च-हे।
गतौ चौर्ये च--वो।

द्रष्ट.√ग्रुच् १/१९४।

ग--ग्लुचुकायनि० (पा. अ. ४/१/१६०)। न्यग्लुचत्-मभाष्ये ३,१,५८. ३|५; न्यग्लोचीत्-३,१,५८. ४|६।

+√ग्लुञ्च् (ग्लुन्चु)१/१९८ गतौ (प) √ग्रुच् १/गतौ चौर्ये (प) वो।
सा-श-जै-काकृ-शा× क्षी-मै-च-कात-हे-वो। √ग्लुच् १/ गतौ चौर्ये (प) वो।
√ग्लुञ्च् (ग्लुन्च)१/१९९ सा।
द्रष्ट.√कुज्, १/१९६; √ग्रुच् १/१९४।

ग—न्यग्लुञ्चीत्-मभाष्ये-३. १,५८. ५।

+√ग्लेप् (ग्लेपृ) १/३६२ दैन्ये (आ)। द्रष्ट.√गेप् १/३६५; १/३६९।
श× क्षी-मै-सा-च-जै-कात-शा-वो।
√ग्लै १/८८८ हर्षक्षये (प)।
चलने दैन्ये च—हे। √ग्लै+√पा २/रक्षणे (प)।
दैन्ये, केप्वत् (=स्तुतौ गतौ [च])—वो। √ग्लैप् >√ग्लेप्।
काकृ-√ग्लैप् (ग्लैपृ)····दैन्ये—काकृ।

द्रष्ट.-√गेपृ १/३६९;√ग्लै>√ग्लैपृ>√ग्लेपृ।

+√ग्लेपृ (ग्लेपृ) १/३६६ च=कम्पने (आ)।
क्षी-मै-सा-च।
गतौ—क्षी-सा-काकृ-हे-वो। द्रष्ट. √गेपृ (गेपृ) १/३६५ (आ)।
चलने—जै-काकृ-कात-शा-हे।
केपृवत् (=गत्यां चाले)—वो।

द्रष्ट.√गेपृ (गेपृ) १/३६५।

+√ग्लेवृ (ग्लेवृ) १/५०३ सेवने (आ) द्र.√खेवृ १/५०२;√गेवृ १/५०२
श× क्षी-च-जै-शा-हे।
सेचने—मै-सा-काकृ-कात।
सेवे—वो।

द्र.√खेवृ १/५०२;√क्लेवृ १/५०१.

+√ग्लेषृ (ग्लेषृ) १/६१४ अन्विच्छायाम् (आ) मै।
क्षी-श-जै-शा हे। अन्वेषे—वो। द्रष्ट.√गेषृ १/६०९।

√ग्लै १/८८८ हर्षक्षये (प)। √क्लमु (क्लमु) ४/ ग्लानौ (प)।
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। √ग्लौ १/३२५ हर्षे (प) काकृ।
क्लमे—वो।
२/,४/ ह्वि.।

ग्लास्नावनुवमाश्च १/१८३ v एषामनुपसर्गाद्वा मित्त्वम्।
श-जै-शा-हे-वो×

क—गुऐल्ड-, गुऐले (इ)-=स्रवणे, योगे। क्लान्तौ—वा. पॉकर्नीः।

ग—अवग्लापयन्ति—ऋ. १,१६४,१०। ग्लायामः—शब्रा. ९,५,१,६४। ग्लायति—नारदपरिव्राजकोप. ३,३८; महा. २,४३। ग्लाति—मभार. १३,१५८,१२=ग्लायति (नील.)।

+√घंष् (घषि) १/६४३ मै-सा-श-च-काक्ट-कात- शा× (बा. ग. प. सायणमते पठितवान्)।	करणे (आ) इति चन्द्रः— क्षी। क्षी-हे। क्षतौ—जै। क्षरे—वो।	<√घंस् √घष् (घष) १/ कान्ति- करणे (आ) सा। √घस् (घस) १/ कान्ति- करणे (आ) सा। √कम् (कमु) १/ कान्तौ (आ) √कम्+स= √कंस्। √कश् १/३७० दीप्तौ (प) काक्ट। √घिंष् (घिषि) १/ कान्ति- करणे (आ) सा। घुंष् (घुषि) १/ करणे (आ)। √घूष् (घूष) १/ कान्ति- करणे (आ)।

अयं कैश्चिन्न मन्यते—दुर्गादासः।

√कम्+स्=√कंस्>√कश्>√घस्>√घंस्>√घंष्।

+√घंस् (घसि) १/६४३ मै-सा-श-च-जै-काक्ट- कात× (बा. ग. प. सायणमते पठितवान्)।	करणे (आ)। क्षी-शा-हे। क्षरणे—वो।	√घुंष् (घुषि) करणे (आ) इति दुर्गः—क्षी। शेषः पूर्ववत्।

अयं कैश्चिन्न मन्यते—दुर्गादासः।

+√घग्घ् (घग्घ) १/१५८ मै-सा-श-जै-काक्ट-शा×	हसने (प)। क्षी-च-कात-हे-वो।	>√गग्घ् (गग्घ) हसने (प) इत्येके—क्षी। द्रष्ट.√गग्घ् १/१५८।

द्रष्ट.√गग्घ् १/१५८।

ङ—घग्घर=चण्डातकम्, स्त्रीपरिधानम्—दे. २,१०७।

छ—घघरी=लघुचण्डातकम्।

छ—घाघ=गौडाभिजनानामनुभवशीलानां चतुराणां संज्ञा, कृषिवर्षत्वाँद्या-श्रित्य लोकोक्तीनां रचयितारः, (२) प्रौढः, (३) ऐन्द्रजालिकः। एते हसन्ति हासयन्ति च।

+√घघ् (घघ) १/१५७ क्षी-श-च-जै-काक्र-कात- शा-हे-वो ×	हसने (प) मै । मै-सा ।	द्रष्ट.√गग्घ् १/१५८ ।

छ—घाघ । द्र. पूर्ववर्ती धातुः ।

√घट् (घट) १/७५५ श	चेष्टायाम् (आ) । क्षी-मै-सा-च-जै-काक्र- कात-शा-हे । चेष्टे—वो ।	√कट् (कटी) १/ गतौ (प) । √खट् (खट) १/ काङ्क्षायाम् (प) । √गध् (अभिकाङ्क्षायाम्)—ऋ. ४,३८,४ । √घट् (घट) १०/ हन्त्यर्थः (प) । √घट् (घट) १०/ संघाते (प) ।

ग—घटते–१ योत. ६६ ।

घ—घटति–मज्झिम. १,८६; संयुत्त. १२६७ । (तुल.√ग्रन्थ् धा.) ।

ङ—घड=चेष्टायाम् , (२) रचनायाम् , (३) परिश्रमे, (४) साङ्गत्ये । वक्र–घडंत, घडमाण–से. १,५; निचू. १ ।

छ—√घटना=घटनायाम् , (२) साङ्गत्ये ।

छ—√घड़ना = रचनायाम् ।

छ—गढ़ना=रचनायाम् ।

√घट्ट् (घट्ट) १/२५७ श ×	चलने (आ) । क्षी-मै-सा-च-जै-काक्र- कात-शा-हे । चाले—वो ।	√घट् (घट) १/७५५ चेष्टायाम् (आ । √घट्ट् (घट्ट) १/१२० खण्डने (प) काक्र । √घृष्+त=घृष्ट । √घुट्ट् १/४३१ चलने (आ) काक्र ।

ङ—घट्ट=१- स्पर्शे, २–हलचालने, ३–संघर्षे, ४–आहतौ–घट्टइ–सुपा. ११६ ।

+√घण् (घण) ८/७ क्षी-मै-श-च-जै-काक्र- कात-शा ×	दीप्तौ (उ) इति शिव- <√घृण् (घृणु) दीप्तौ (उ) । स्वामी—सा । सा-हे-वो ।

+√घम्ब् (घन्व) १/४१६ मै-सा-श-च-जै-काक्र-कात-शा×	गतौ (प) इति कौशिकः—क्षी। (क्षी-हे) वो।	√कन् (कनी) १/ दीप्ति-कान्तिगतिषु (प)। √गम् (गम्लृ) १/ गतौ (प)। √कम्ब् १/ गतौ (प) वो। √खम्ब् १/ गतौ (प) वो। √गम्ब् १/ गतौ (प) वो।

अर्बेत्यादौ रेफस्थाने नकारं कौशिको मन्यते—क्षी।

+√घर्ब् (घर्ब) १/४१६ मै-सा-श-च-जै-काक्र-कात-शा×	गतौ (प)। क्षी-(हे)-वो।	√कर्ब् (कर्ब) १/ गतौ (प)। √क्रम् (क्रमु) १/ पाद-विक्षेपे (प)। √खम्ब् १/ गतौ (प) वो। √गम् (गम्लृ) १/ गतौ (प)। √गम्ब् १/ गतौ (प) वो। √घम्ब् १/ गतौ (प) वो।

√गम् >√गम्ब् >√घम्ब् >√घर्ब् इति व्युत्पत्तिः। रेफमकारयोर्विनि-मयनिदर्शनम्—√घम्ब् १/४१६।

+√घष् (घष) १/६४२ क्षी-मै-श-च-जै-काक्र-कात-शा-हे-वो×	कान्तिकरणे (आ) सा सा।	<√घस् (घस) कान्तिकरणे (आ) द्र√घंष्। स्पष्टो विकासः।
+√घस् (घस) १/६४२ क्षी-मै-श-च-जै-काक्र-कात-शा-हे-वो×	कान्तिकरणे (आ) इति स्वामी—सा।	द्र.√घंष्। स्पष्टो विकासः।
√घस् (घस्लृ) १/७०७ श-जै-काक्र-कात-शा×	अदने (ष) इति केचित्—क्षी क्षी-मै-सा-च-हे। भक्षे—वो।	√ग्रस् (ग्रसु) १/ अदने (आ)। √ग्लस् (ग्लसु) १/ अदने (आ)।

अयं न सार्वत्रिकः, "लिट्यन्यतरस्याम्" इत्यदेर्घस्लादेशविकल्पविधानवैयर्थ्य-प्रसङ्गात्—सा ७०२।

ग—घसत्-ऋ. १०,८६,१३। घासिं जघास (अश्वः)-ऋ. १,१६२,१४।
घ—घसति-जातकं ३,२१०।
छ—√घसना=भक्षणे (डिंगल.)।

+√घिंष् (घिषि) १/६४२ क्षी-मै-शा-च-जै-काकृ-कात-शा-हे-वो।	कान्तिकरणे (आ) इति चन्द्रकाश्यपौ—सा।	द्र.√घंष्। स्पष्टो विकासो भ्रान्तिर्वा।
+√घिण्ण् (घिणि) १/४२७ श×	ग्रहणे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√ग्रस् (ग्रस) १/ अदने (प)। √ग्रस् (ग्रस) १०/ग्रहणे (प)। √ग्रिहू १/ ग्रहणे (आ) सा। √खुण् १/४७७a ग्रहणे (आ) (काकृ) √घुण् १/४७७b ग्रहणे (आ)। √ग्रहू ९/ उपादाने (उ)। √घृण्ण् (घृणि) १/ ग्रहणे (आ)। √घुण्ण् (घुणि) १/ ग्रहणे (आ)।

√ग्रहू—गृह्णु (आति)>√गिण्ह-सुपा. ६१९>√घृण्ण् >√घिण्ण्, √घृण्ण्>√घुण्>√घुण्ण् इति क्रमः।

×√घुंष् (घुषि) १/९४३	करणे (आ) इति दुर्गः-क्षी (यु. मी. सं. कान्तिकरणे)। कान्तिकरणे—मै-सा। कान्तीकरणे—कात-हे। घूर्शे—वो। घूशः=कान्तिकृतिः-दुर्गादा.	<√घंस् (घसि) करणे(आ)। द्र.√घंष्। स्पष्टो विकासः।
+√घु (घुङ्) १/९३६ श×	शब्दे (आ) क्षी-मै-सा-च-जै-काकृ-	√उ १/३३६ d शब्दे (प) काकृ।

	कात-शा-हे । ध्वनौ—वो ।	√कु (कुङ्) १/९३७ शब्दे (आ) । √कू (कूङ्) ६/ शब्दे (आ) । √कव् (कव) १/ शब्दे (प) । √गु (गुङ्) १/ अव्यक्ते शब्दे (आ) ।

√गु १/९३४>√घु (घुङ्) इति विकासः ।
छ—घुग्घू (घु-घु—शब्दानुकृतिः) = उलूकः ।

√घुट् (घुट) १/७३७ श×	परिवर्तने (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे । परिवृत्तौ [च]—जै । परिवर्ते—वो । परिवर्ते ?—ह्वि. । शुद्धो धातुर्नास्ति—ह्वि. ।	√गुर् (गुरी) ६/ उद्यमे (आ) । √घुर् (घुर) ६/ भीमार्थ-शब्दयोः (प) । √घुट् (घुट) ६/ प्रतीघाते (प) । √घुण् (घुण) १/ भ्रमणे (आ) । √गुट् १/११३ i गतौ (प) काकृ । √घुट्ट् १/ चलने (प) काकृ ।

क—घेल़ (तथा घॅल़), घेुले-ःुले-,ुलॉ, ुलू-ः-वा. पॉकर्नीः ।

ग—घोटकानाम्-गरु. २३ । राजा तयैव सह शिविकया प्रायादवघोटितया (=अवगुण्ठितया)-मभार. ३,१३१५५ ।

घ—घोटक-जातक ६,४५२ ।

ङ—√घोट (अक)=भ्रमणे, चक्राकारेण भ्रमणे । घोडइ-से. ५,१० ।

छ—घोलना
छ—घोरना } =द्रवपदार्थे चूर्णादिमिश्रणाय द्रवस्य परिवर्तने, भ्रमणे ।

अयं शुद्धो धातुर्नास्तीति ह्विट्नुक्तं न सङ्गतम्, प्राकृते हिन्द्यां च तदुपलम्भात् ।

+√घुट् (घुट) ६/१०३ श×	प्रतीघाते (प) इति दुर्गः—क्षी	<√गुड् (गुड) प्रतीघाते (प) ।

क्षी-मै-शा-च-काक्-कात-हे । प्रतिघाते—जै-शा । प्रतिहतौ—वो ।	√घुड् ६/ व्याघाते (प) वो । द्रष्ट०√गुड् ६/१०३ ।

ङ—√घोल (सक)=घर्षणे, प्रतिघाते, (२) मिश्रणे। विसे. २०४४; से. ४,५२ ।

छ—√घोटना (<घोटनम् =प्रतिघाते, आवर्तने)=कस्यचन वस्तुनः प्रस्तरादौ प्रतिघाते, घर्षणे, घट्टने, (२) चूर्णीकरणार्थं घट्टने, प्रतिघाते।

छ—√घुटना (कर्मणि) ।चूर्णीकरणार्थं घट्टने, प्रतिघाते ।

छ—√घूटना=श्वासावरोधे, प्रतिघाते ।

छ—√घुटना
छ—√घुँटना } =श्वासावरोधे, प्रतिघाते ।

+√घुण् (घुण) १/४३० श×	भ्रमणे (आ) क्षी-मै-सा-च-जै-काक्-कात-शा-हे-वो ।	√गुर् (गुरी) ६/ उद्यमे (आ)। √घुर् (घुर) भीमार्थ-शब्दयोः (प)। √घुट् (घुट) परिवर्तने (आ)। √गोण् १/२१३j गतौ (प) काक् । √घोण् १/२१३k गतौ (प)।

ग—घोणा-मभार. १,१५६,३३; सुश्रु. शरीरस्थाने पञ्चमाध्याये; अश्ववैद्यके २,७ ।

ङ—√घोल (अक)=भ्रमणे। वक्-घोलंत-कप्प.; गा. ३७१; कुमा. ।

+√घुण् (घुण) ६/५८ श	भ्रमणे (प) क्षी-मै-सा-च-जै-काक्-कात-शा-हे-वो ।	पूर्ववत् ।

ग—घुणस्य(=कीटविशेषस्य)-पै. ५,२०,६। घुणदग्ध०-षव्रा. ४,४। घुणोपहत-काष्ठ०-सुश्रु १,२९,५ । पूर्ववदेव सर्वाण्यस्योदाहरणानि ज्ञेयानि । भ्वादि-तुदादिभेदार्थं पृथक् पठितौ स्तः ।

+√घुण्ण् (घुणि) १/४२८ ग्रहणे (आ) द्रष्ट.√घिण्ण् १/४२७।
श× क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे-वो ।

द्रष्ट.√घिण्ण् १/४२७ ।

+√घुर् (घुर) ६/६५ भीमार्थशब्दयोः (प) द्रष्ट√कुर् ९/६१ ।
श क्षी-मै-सा-जै-काक्र-कात-
शा-हे ।
भीमे—च ।
ध्वनौ भीमार्थे—वो ।

क—घॉउ-रॉस् = भयानकम्। इरिश्-गुर् = निशितम्, पीडापूर्णम्, वेदनामयम्—वा. पॉकर्नीः ।

क—घेर्-शब्दानुकृतिः । लैति.-हिर्रीरे (सं. घुर्घुरायन्ते-सुश्रु. १,१०४,१)-वा. पॉकर्नीः ।

ग—घोरान् नरकान् प्राप्य-मनु. १२,५४ = भयानकान्। घोरा [= गङ्गा]-काशीखण्डे २९,५५-(शब्दार्थे) । कण्ठे घुरघुरायते-भा.पु. ३,३०,१७-शब्दानुकृतिः ।

घ—घोर = भयानकम्-विनय. २,१४७ ।

ङ—√घोर (अक) = निद्रागतस्य घुरघुर-शब्दे । घोरंति-गा. ८०० ।

छ—√घुरना* = शब्दे, वादने-"घुरत निसान मृदंग संख धुनि"-सूर. ।

छ—√घोरना (<घोरणम्) = गर्जने, भयङ्करशब्दे ।

छ—√घुरकना
छ—√घुड़कना } (<घोरणम्) = तर्जनशब्दे । (निद्राशब्दे) ।

छ—√घुर्राना
छ—√गुर्राना } (शब्दानुकृतिः-घुर्र् इति) = भयार्थं घुरघुरवद् गम्भीरशब्दे ।

√घुष् (घुषिर्) १/६४४ शब्दार्थः (प)
क्षी- मै ।
अविशब्दने—सा ।
शब्दे—च-जै-काक्र-कात-
शा-हे ।
सततक्रन्दे—वो ।

√कु (कुङ्) १/९३८ शब्दे (आ) ।
√खु (खुङ्) १/ शब्दे (आ) ।
√गु (गुङ्) १/ शब्दे (आ) ।
√घु (घुङ्) १/ शब्दे (आ) ।
√गुज् (गुज) १/ शब्दे (प)।
√घुष् १०/११४ उत्सर्गे (प)
काक्र ।

ग—आघोषते दिवि-ऋ. १,८३,६। घोषत्-तैब्रा. ३,२,२,२। आघोषन्-ऋ १०,८६,१६।

ङ—√घोस=घोषणे। घोसइ-प्रामा.।

छ—√घोखना=अभ्यासे, कण्ठस्थीकरणे।

+√घूर् (घूरी) ४/४३ श	हिंसावयोहान्योः (आ) क्षी-मै-सा-जै-शा। हिंसायाम्—च-काकृ-कात। हिंसायां जरायां च-हे। हिंसाज्यान्योः—वो।	>√गूर् (गूरी) ४ हिंसावयोहान्योः (आ)। द्रष्ट. गूरी हिंसावयोहान्योः (आ)।

द्रष्ट. √गूर् ४/४३।

√घूर्ण् (घूर्ण) १/४३१ श-वो×	भ्रमणे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे	√गूर् (गूरी) हिंसागत्योः (आ) मै। √घुण् (घुण) १/ भ्रमणे (आ)।

ग—वायुश्च घूर्णते भीमः-मभार. ३,१२०८४।

ङ—√घुम्म=भ्रमणे। वक्क-घुम्मंत,-घुम्ममाण-हेका. ३३; णाया. १,९।

छ—√घूरना=नयभ्रमणे (व्यापारे)।

ङ—√घुम = भ्रमणे। घुमइ-पिंग.।

छ—√घूमना=भ्रमणे।

छ—√घुम्मरना
छ—√घुमड़ना } (<घूर्णनम् +अटनम् ?) = परिभ्रम्य तनने, उन्मण्डने।

√घूर्ण् (घूर्ण) ६/५९ श	भ्रमणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो (उ)।	पूर्ववत्।

ग—घूर्ण-घूर्ण-लाङ्गूलो. २१५ : १८। चचाल च जुघूर्ण च-वा. रा. ४,१५,२५। घूर्णति-मभार. १,२०६१।

छ—घूरना† =भ्रमणे, पादविहारे, (२) क्रोधेन निर्निमेषदर्शने।

[+]√घृ १/९२२ श×	सेचने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। सेके—वो।	√गृ १/९२१ सेचने (प)। द्र.√गृ १/९२१ सेचने (प)।

√घृ ३/१४ क्षरणदीप्त्योः (प) द्र. प्राक्तनो धातुः ।
श-जै-शा× क्षी-मै-सा-काकृ-कात-हे ।
क्षरणे—च ।
सेके भासि च—वो ।

ग—जिघर्मि-ऋ. २,१०,४ । तै. ४,१,२,४; काठ. १६,२ । जिघर्ति देवान्-ऋ. १०,६,४ । घ्रन्-शौ. ७,१९,२ (=दीप्तौ); पै.२०,३,७ ।

+√घृण् (घृणु) ८/६ दीप्तौ (उ) घृणिः-निघ. १/१७ ज्वलतो
श क्षी-मै-सा-च-जै-काकृ- नामधेयम् ।
कात-शा-हे-वो । √घृ ३/१४ क्षरणदीप्त्योः (प) ।
√घृन् ८/७ दीप्तौ (उ) हे, वो ।
घृणः-निघ. १/९अहर्नाम ।

ग—घृणाः घृणा तपन्तमति सूर्यं परः-ऋ. ९,१०७,२०; शं हिमा शं घृणेन-१०,३७,१०; घृणेः ६,१६,३८ । न घृणीनां न रम्याणाम्-हरिवंश. ३५८८ ।

यद्यप्ययं धातुः √घृ ३/१४ इत्यस्य विकसितं रूपं तथापि 'घृणि'-शब्द-साधनाय√घृण् आवश्यकः । उणादावयं निपातनात् साध्यते√घृ धातुतः, तदगतिक-गतित्वम् ।

+√घृण्ण् (घृणि १/४२९ ग्रहणे (आ) द्रष्ट. √घिण्ण् १/४२७ ।
श× क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो ।

द्र० √घिण्ण् १/४२७ ।

√घृष् (घृषु) १/७०१ संघर्षे (प) √घृ ३/ क्षरणदीप्त्योः (प) ।
श × क्षी-मै-सा-जै-काकृ- √हृष् (हृषु) १/ अलीके
शा-वो । (प) ।
संहर्षे—च-कात-हे । √हृष् (हृष) ४/तुष्टौ (प) ।

ग—सर्वाणि गात्राणि निघर्षसि त्वम्-मभार. ८,१७९७ ।
घ—घंसति=संघर्षे—संयुत्त. २,२३८ ।
ङ—√घस्=संघर्षे । घसइ-महा. ।
ङ—√घास=संघर्षे, पीडने । कर्मणि—घासइ-सूअ. १,१३,५ ।

छ—√घसना†*=घर्षणे ।
छ—√घिसना=घर्षणे ।

√घ्रा १/९१० शगन्धोपादाने (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । गन्धग्रहणे—वो । √जिघ्र्-हिरण्यकेशीये-'अभिजिघ्र्य'-२,४,१७। √जिघ्र्-गो. गृ.-अभिजिघ्र्य २,८,२२। √जिघ्र्-गो. गृ.-अभिजिघ्रणम्-८,२४।

ग—अत्रा सं जिघ्रते युजा—ऋ. ९,१४,४। जिघ्रति-शब्रा. १४,५,४,१५। उपाघ्राति-मभार. ३,१४५०४।

घ—घायित्वा-जातक १,२१०।
ङ—√जिंघ = आघ्राणे। कु-जिंघणिज्ज-कप्प.।

+√ङु (ङुङ्) १/९३८ शब्दे (आ) श × क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। ध्वनौ—वो।

ग—ङवन्दिते! ङलिप्सिते! ङकारवर्णरूपिणि!-स्तुतिपञ्चाशत्। ङः=भैरवः। (श. क. द्रु.)।

+√चक् (चक) १/९० तृप्तौ (आ) श × क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। चाकनत्-निघ. ३/११ पश्यतिकर्मा। √चर्क् १/४११c तृप्तौ (आ) काकृ। √चक्क् १/४११b तृप्तौ प्रतिघाते च (आ) काकृ।

(ग—चकमानाय-तैआ. ३,१५,१। चकमानः-निघ. २/६ कान्तिकर्मा।)
छ—√छकना (<चकनम्-तृप्तौ)=तृप्तौ, पानभक्षणतृप्तौ।
छ—√छाकना †*(<चकनम्-तृप्तौ)=तृप्तौ, पानभक्षणतृप्तौ।
छ—√छकाना (<चकनम्-तृप्तौ) (सक)=तर्पणे, पाययित्वा खादयित्वा तर्पणे।

√चक् (चक) १/७७५ तृप्तौ प्रतिघाते च (प) मित् श × क्षी-मै-सा-काकृ-कात। √चक्क् १/४११b तृप्तौ प्रतिघाते च (आ) काकृ।

च ? | √चक्क् भ्रान्तौ-सौ.धा.-वो ।

तृप्तिप्रतिघातयोः—जै ।

प्रतिघाते तृप्तौ च—शा-हे ।

लोटने तृप्तौ च—जै ।

प्रतिघाततृप्त्योः—वो ।

कम्पने—ह्वि. ।

ग—चकन्ति-, चकित०-ह्वि. । मया कोऽपि नाधिगतः प्रयोगः, केवलं मृच्छकटिकस्य चकिता०-९,२१ प्रयोगं हित्वा ।

छ—√चकना*=विस्मयें, आश्चर्यें, सहसा कम्पने, स्पन्दे ।

छ—√चकाना*=विस्मये, आकुलीभावे ।

√चकास् (चकासृ) २/६३ दीप्तौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।
शं

√काश् (काशृ) १/ दीप्तौ (आ) ।
√चाकश् २/३७b दीप्तौ (प) काकृ ।

ग—चकास्ति-शिशु. १,८ । चकाशेते-मभार. ३,४३८ (८,२३२८) ।

√चक्ष् (चक्षिङ्) २/७ व्यक्तायां वाचि (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे ।
श

वचने—च ।

वदे—वो ।

√चकास् २/ दीप्तौ (प) ।
√काश् (काशृ) १/ दीप्तौ (आ) ।
√क्शा-अन्वक्शायम्-मै.१,९,८ ।
√ख्या २/प्रथने (प) "चक्षिङः ख्याञ्" चष्टे-निघ. ३/११-पश्यतिकर्मा ।

ग—चष्टे—ऋ. १,१९०,७; चक्षतु-पै. २०,३७,३ ।

√चञ्च् (चन्चु) १/१८७ गत्यर्थः (प) क्षी-मै-सा-च

गतौ-जै-कात-शा-हे ।

इतौ—वो ।

(काकृ—√चञ्च् [चचि]) गतौ—काकृ ।

नर्तने—ह्वि. ।

√तञ्च् (तन्चु) गत्यर्थः (प) ।

ग—चञ्चत्-कथासरि. २२,१७५ । ऋतुसं. ३,३ । चञ्चति-गीतगो. ४,८ ।

√चट् (चटे) १/२९१ क्षी-मै-श-च-जै-काकृ- कात-शा-हे-वो×	वर्षावरणयोः (प) इति काश्यपः—सा । सा । गतौ (?)—ह्वि. ।	<√कट् (कटे) वर्षावरणयोः (प)। √चट् १/१०९a प्रैष्ये माने च (प) काकृ।

ग—उच्चचाट–भा. पु. ५,९,१८; २,७२८ । चापचटितकोटिम्–पञ्चत.–१३१,१ ।
ज—√चाडु=जलान्तः क्षेपणे ।

+√चण् (चण) १/७९० श-च×	दाने (प) क्षी-मै-सा-जै-काकृ- कात-वो । 'गतौ' इत्येके—मै ८०० । 'गतौ' इत्यन्ये—सा । गतिहिंसार्थात्— चाणयति—क्षी । गतौ—शा । गतौ हिंसादानयोश्च—हे । गतौ हिंसे च—वो ।	√शण् १/ दाने (प) । √सन् (षणु) ८/ दाने (उ) ।

ग—चणकः–कथासरि. ६,४० ।

छ—√चांडना=उत्पाटने, उज्जासने, (२) खनने, खात्वा पातने ।

+√चण्ड् (चडि) १/२७६ श	कोपे (आ) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे । रोषे—वो ।	√चण् १/ गतिहिंसार्थयोः (प)–चाणयति । √चण्ड् १/१७४ तैक्ष्ण्ये (प) काकृ ।

ग—चण्डस्य नप्त्यः–अ. वे. २,१४,१ । चण्डाश्च शौण्डाश्च महाशनाश्च–मभार. ३,२३३,११=अत्यन्तकोपनाः । चण्डग्राहवती नदी–मभार. १,६७५२; वा. रा. ५,७४,२८ । अपराधचण्डात्–रघु. २,४९ ।

घ—चण्ड–विनय. २,१९४ ।

छ—चाँड़ (<चण्डः)=(१) प्रबलः, (२) उग्रः, उद्धतः, (३) श्रेष्ठः ।

छ—चँड़ाई (<चण्डः)=१–शीघ्रता, २–सम्भ्रमः ।

√चत् (चते) १/८५०	च=परिभाषणे, याचने (उ) (यु. मी. सं.)	चतति—निघ. २/१४ गतिकर्मा ।

याचने—क्षी-मै-च-जै-
कात-हे।
याचने, च=परिभाषणे—
सा-काक्ट-शा।
याचे—वो।
तिरोभावे ?—ह्वि.।
गत्यर्थे च—भट्टभास्करमिश्रः-
देवराजयज्वा—निघ. २/१४।

ग—चातयते-ऋ. ४,१७,९। अचीचतन्-तैआ. २,४,१। अचीचतन्-मै. ४,१४,१७; चातनैः-गोब्रा. १,२,१८। रे रे चातक! सावधानमनसा-भर्तृ. नी. श.।

+√चद् (चदे) १/८५१	च=परिभाषणे, याचने (उ) (यु. मी. सं.) याचने—क्षी-मै-च-जै-कात-हे। याचने, च = परिभाषणे— सा-काक्ट-शा। याचे—वो।	√चत् (चते) १/ याचने (प)।

√चत्>√चद् इति स्याद् विकसितोऽयम्।

√चन् (चनु) १/७९५ श-च× √चन् (चंन)…	च=हिंसार्थः (प) क्षी। काक्ट ? हिंसार्थः—मै-सा-कात- शा। हिंसायाम्—जै-हे। हिंसे—वो। प्रसन्नतायाम्—ह्वि.।	√चन् १/२०७ स्मरणे (प) काक्ट। √चन्न् १/२२० n संभक्तौ (प) काक्ट। चनः—निरु. ६,१६,२= अन्ननाम।

ग—चनिष्ठत्-ऋ. ८,७४,११। √चनस्य्—चनस्यतम्-ऋ. १,३,१।

√चन्द् (चदि) १/६५ श×	ह्लादने दीप्तौ (प) क्षी। ह्लादने दीप्तौ च—मै- सा-कात।	चन्द्रश्चचन्दतेः कान्तिकर्मणः-निरु. ११,५,३।

आह्लादने—च-काक्ष ।
दीप्तिह्लादनयोः—
जै-शा ।
दीप्त्याह्लादनयोः—हे ।
ह्लादे दीप्तौ—वो ।

ग—चनिश्चदत्-ऋ. ५,४३,४ । चन्दनेन-खिसा. २६,१५ । चन्द्राः-जै. ३,५५,१ ।

+√चप् (चप) १/३९७ शX	सान्त्वने (प) क्षी-मै-सा-च-जै-काक्ष-कात-शा-हे । सान्त्वे—वो ।	√चप् (चप) १०/ कल्कने (प)।

क—चम्प्=नम्रतायाम् ।

ख—न. पर्सि.-चुप=वामे, वामहस्ते-वा. पॉकर्नीः ।

ग—शिष्याय चपेटां ददाति-मभाष्ये १,१,१ ।

छ—√चँपना (<चपनम्)=कुञ्जीभावे, आर्जवे, (२) व्रीडायाम्, (३) उपकारभारेण नम्रीभावे ।

√चम् (चमु) १/४६४ जैX,श	अदने (प) क्षी-मै-सा-च-काक्ष-कात-शा-हे । भक्षे—वो ।	√चम् (चमु) ५/ भक्षणे (प)। √छम् (छमु) १/ अदने (प)। √जम् (जमु) १/ अदने (प)।

न कम्यमिचमाम्-१/८०३bb
श-जै-शा-हे-वोX

ग—चमसः-ऋ. ४,३५,४ । आचामति, आचामेत्-काठ. २९,३ । पर्याचान्तमनिर्दशम्-मनुं. ४,२१२ । विचमति-मभाष्ये-७,३,७५, ४/३३४ ।

छ—√अँचोना (<आचमनम्)।

[+]√चम् (चमु) ५/२८ श-च-जै-काक्ष-कात-शा-हेX	भक्षणे (प)। क्षी-मै-सा । भक्षे—वो ।	√चम् (चमु) १/ अदने (प)।

+√चम्व् (चन्व्) १/४२० गतौ (प)
मै-श-च-जै-काकृ-कात-शा ।
क्षी-सा-वो । हे ?

<√चर्व् (चर्व) गतौ (प)।
√छम्व् १०/८० गत्याम् (प)
जै ।

अर्वेत्यादौ रेफस्थाने नकारं कौशिको मन्यते—क्षी ।

+√चय् (चय) १/४७४ गतौ (आ)
श-शा ×
क्षी-मै-सा-च-काकृ-कात-हे-वो ।
(जै—√बय् (बयै) स्यान्मुद्रणदोषः । 'चयै' इति भवेत् । जै ।

√चि (चिञ्) ५/ चयने (उ)।
चयूसे—निरु. ४,२५,५=चातयसि=नाशयसि । तुल. प्राणगमने √चय—ङ ।

क—चुएइ—=समादरे, परीक्षणे—वा. पॉकर्नीः ।
ङ—√चय=प्राणगमने, एकस्माज्जन्मनोऽपरस्मिञ्जन्मनि गमने । चयइ—भवि. ।

√चर् (चर) १/५५८ गत्यर्थः, भक्षणेऽपि (प)
क्षी-मै ।
गत्यर्थः, भक्षणार्थोऽपि—सा ।
गत्यर्थः—च-कात ।
भक्षणे—जै ।
गतौ भक्षणे च—शा-हे ।
गमनेऽदने आचारे—वो ।
काकृ-√चव् (चव) अतिसंभवेद् इयं लैपिकी त्रुटिः । गतौ—काकृ ।

√चल् (चल) १/ कम्पने (प)।

ग—चरति—ऋ. १,९५, १० ।
घ—चरन्तो—जातक १,१५२ ।
ङ—√चार=भक्षणे । चारेइ—धर्मवि. १४३ ।
ङ—√चर=गतौ, (२) भक्षे, (३) सेवने, (४) ज्ञाने । चरइ—उव.; महा. ।
छ—√चरना=पशूनां घासादिभक्षणे ।
छ—√चरना=भ्रमणादौ ।

+√चर्च् (चर्च) १/७०९ परिभाषणे (प)
श-शा-हे-वो ×
क्षी-मै-च ।
परिभाषणहिंसातर्जनेषु—सा-जै ।

√जर्च् (जर्च) १/ परिभाषणे (प) इत्येके—क्षी ।
√जर्ज् (जर्ज) परिभाषणे (प) इत्यन्ये—क्षी ।

	परिभाषणतर्जनयोः—काक्र-कात ।	√जर्त्स् (जर्त्स) परिभाषणे (प) इति चन्द्रदुर्गौ—क्षी ।
	दीप्तौ—काक्र-कात ।	√झर्च् (झर्च) परिभाषणे इत्यपरे—क्षी ।

किमत्र सत्यम्! देवा ज्ञास्यन्ति—क्षी ।

ग—चर्चित(खङ्ग)०—देवीमा. ११,२८=लिप्त० ।

छ—√चचोरना (<चर्चनम्)=चूषणे, रक्तपानादिहिंसायाम् (वुं. ख.) ।

+√चर्च् (चर्च) ६/२१ शा×, श	परिभाषणे (प) इति च दुर्गः—क्षी ।	>√चर्छ् (चर्छ) परिभाषणे(प) यु. मी. सं. ।
	क्षी-मै-च-जै-काक्र-कात-हे । परिभाषणभर्त्सनयोः—सा ।	√जर्ज् (जर्ज) ६/परिभाषणे (प)।
द्रष्ट.√चर्च् १/७०९ ।	उक्तौ भर्त्से—वो ।	√झर्झ् (झर्झ) ६/परिभाषणे (प)।

+√चर्छ् (चर्छ) ६/२१ मै-सा-श-च-जै-काक्र-कात-शा-हे-वो×	परिभाषणे (प) क्षी (यु.मी.सं.) ।	पूर्ववत् ।

ग—पयोधराश्चन्दनपङ्कचर्च्छिताः—ऋतुसं. १,६ ।

+√चर्ब् (चर्ब) १/४२० श×	गतौ (प)	>√चम्ब् (गतौ) (प) ।
	क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो ।	√चर् (चर) १/गतौ (प) ।
		√चम्ब्१/२०६० मर्दने (प) ।
		√चब् १/२०६p मर्दने (प) ।

क—चुर्एर्प्=स्वतो वेष्टने, भ्रमणे । चुर्एर्ब्—इत्यपि । लैति.—चुचुर्वित—वा. पॉकर्नोः ।

√चर्व् (चर्व) १/५७६ श×	अदने (प)	>√चुरादौ चर्वयति—क्षी ।
	क्षी-मै-सा-च-जै-काक्र-कात-शा-हे ।	√चर् (चर) १/भक्षणेऽपि (प) क्षी ।
	भक्षे—वो ।	

ग—चर्वयत्यति भैरवम्—देवीमा. ७,१० । चर्व्यते—मृच्छक. ।

घ—चप्पेति–विनय. २,११५ ।
ङ—√चव्व (सक)=भक्षणे–संक्षि. ३४ ।
छ—√चबाना (<चर्वणम्)=चर्वणे ।

√चल् (चल) १/८१६ श×	कम्पने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । गतौ--वो ।	√चर् (चर) १/गतौ (प) । √चर्व् (चर्व) १/गतौ (प) ।

कम्पने चलिः, मित्–१/८०३ ।

ग—चलाचलासः–ऋ. १,१६४,४८ (<चराचर०); चलन्ति—पन्ना. ५,११ ।
घ—चलति–संयुत्त. १,१०७ ।
ङ—√चल=(१) कम्पने, (२) चलने । चलइ—महा.; गउड. ।
छ—√चलना=गमने, प्रस्थाने ।

+√चल् (चल) ६/७७ श×	विलसने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । विलासे—वो ।	√चल् (चल)१/कम्पने (प) । √चल् (चल) १०/भृतौ (प) ।

छ—√चलकना=चमत्कृतौ, द्युतौ ।
छ—√चिलकना=विद्युद्विलासे, चमत्करणे, विलसने ।

+√चष् (चष) १/८७५ श-शा ×	भक्षणे (प) क्षी-मै-सा-च-काकृ-कात-हे । भुक्तौ--जै । भक्षे--वो ।	√चष् (चष) १/वधे (प) वो ।

ङ—√चक्ख (सक)=आस्वादे । चक्खइ–पि. २०२ ।
छ—√चखना=आस्वादे ।
छ—√चसना (<चषणम्) [द्रष्ट. √चष् वधे १/वो]=प्राणत्यागे ।

+√चषघ् (चषघ) ५/२२ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो ×	हिंसायाम् (प) इत्येके—क्षी ।	√सघ् (षघ) हिंसायाम् (प) । √चष् (चष) १/वधे (प) वो ।

छ—√चसना = प्राणत्यागे ।
छ—√चासना=मारणे ।

छ—√चाकना=मारणे, गलकर्तने (बुं. ख.)।

+√चह् (चह) १/७२२ कल्कने (प)
शX
क्षी-हे।
परिकल्कने-
मै-सा-च-जै-काकृ-कात-शा।
शाठ्ये--वो।
कल्कनम्=शाठ्यम्--क्षी।
कल्कनम्=दम्भः--क्षी १०/।

√चुह् १/३१५ b परिकल्कने (प) काकृ।
√डह् १/३१५ c परिकल्कने (प) काकृ।

छ—√चहकना=पक्षिणामारावे, (२) सोल्लासं हर्षेण जल्पनाधिक्यम्। (दम्भे)।

छ—√चहचहाना=शब्दानुकृतिः।

√चाय् (चायृ) १/८६५ पूजानिशामनयोः (उ)
शX
क्षी-मै-सा-काकृ-कात-हे।
पूजायाम्—च।
निशामने पूजायां च-
जै-शा।
निशामेऽर्चे—वो।

√चि (चिञ्) ५/ चयने (उ)।

ग—चायमानः-ऋ. ७,१८,८। अचायत्-तै. २,१,४,६; तांब्रा. ५,४,१४।

√चि (चिञ्) ५/५ चयने (उ)
श
क्षी-मै-सा-जै-काकृ-
कात-शा-हे।
चये—च।
चित्याम्—वो।

√चि (चिञ्) चये (प) मित्।
√कि ३/ ज्ञाने (प)।

ग—अवचिन्वती-ऋ. ३,६१,४; चयते-१,१६७,८। चिनुते-मै. ३,१,३। चिन्वति-शांब्रा. १९,४।

+√चिट् (चिट) १/३११ परप्रैष्ये (प)
शX
क्षी-मै-सा-जै-शा।
प्रैष्ये—च-कात-हे।
प्रैष्ये माने च—काकृ।
प्रेषे—वो।

परप्रैष्यम् = दासत्वम्-क्षी ।

ग—चेटः = दासः, चेटी = दासी (संस्कृतनाटकेषु)—ततः प्रविशति द्वितीया चेटी—मा. अ.-प्रस्तावनान्ते । नागानन्दनाटके चेटी-शब्दो बाहुल्येन प्रयुक्तः ।

ङ—अरे चेडा (<चेट !)-नागानन्दे-१६८ पृ. ।

छ—चेला, चेली, चेरा, "चेरी छोड़".-तुलसी. ।

√चित् (चिती) १/३८ संज्ञाने (प) √कि ३/ ज्ञाने (प) ।
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । √चिन्त् (चिति) १०/ स्मृत्याम् (प) ।
ज्ञाने—वो ।

ग—चेतति-ऋ. १,१०,२; मै. ४,१०,४ । चितयन्ति-ऋ. ७,६०,६; चितयन्ते १,१७१,५ ।

छ—√चेतना (<चेतनम्) = संज्ञायाम् , (२) अवहितौ ।

+√चिरि ५/३० हिंसायाम् (प) √जिरि ५/ हिंसायाम् (प) ।
श-जै-शा× क्षी-मै-सा-च-हे ।
जिघांसायाम्—काकृ-कात ।
हिंसे—वो ।

छ—चीरना = छेदने, वधे । (<चीर्णनम् ?) ।

+√चिल् (चिल) ६/७६ वसने (प) √चिल्ल् (चिल्ल) १/ शैथिल्ये (प) ।
जै×, श क्षी-मै-सा-च-कात-शा-हे ।
वेष्टने—काकृ ।
वासे—वो ।

ग—चैलाजिनकुशोत्तरम्-गी. ६,११ ।

घ—चेल = वसनम्—अंगुत्तर. १,२०६ ।

घ—चेलक = परिहितवसनः-दीघ. १,१६६; मज्झिम. १,७७ ।

+√चिल्ल् (चिल्ल) १/५३३ शैथिल्ये (प)
श× क्षी-च-जै-काकृ-कात-शा-हे-वो ।
शैथिल्ये भावकरणे च—मै-सा ।

हावकरणे शैथिल्ये च—
शा-हे ।
हावकृतौ शैथिल्ये च—वो ।

ग—चिल्ली = वास्तुकी–सुश्रु. सूत्रस्था., ४६ अध्याये । चिल्लीषु–यशस्तिल. च., ३ आश्वा., १९१ पृ. = भ्रूषु । भावकरणे = अभिप्रायसूचने भ्रुवौ पर्याप्ते ।

+√चीप् (चीपृ) १/८८३ क्षी-सा-श-च-जै-काकृ-कात-शा-हे-वो ×	आदानसंवरणयोः (उ) इत्यन्ये—मै ।	<√चीव् (चीवृ) आदान-संवरणयोः (उ) । √चीय् (चीयृ १/ संवृत्या-दानयोः (उ) वो ।

लेखकप्रमादाद् वकारस्य पकारो जातः स्यात्, देशभेदेनोच्चारणभेदाद् वा । पकारयकारयोर्भ्रान्तिर्भवत्येवेति वोपदेवेन √चीय् (चीयृ) धातुरपि पठितः । √चीव् धातुं श-जै-शाकटायनान् विहाय समेऽनुमोदन्ते ।

+√चीभ् (चीभृ) १/३८१ श ×	च = कत्थने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । कत्थे—वो । (कथने—जै । मुद्रणदोषः) ।	√शीभ् (शीभृ) १/ कत्थने (आ)

+√चीव् (चीवृ) १/८६४ श-जै-शा ×	आदानसंवरणयोः (उ) इति दुर्गः–क्षी । क्षी-मै-सा-कात । आदाने—च । संवरणादानयोः—काकृ । झषीवत् (=आदानसंवरणयोः)—हे । ग्रहसंवृतौ—वो ।	√चीप् (चीपृ) १/ आदान-संवरणयोः (उ) मै । √चीय् (चीयृ) १/ संवृत्या-दानयोः (उ) वो ।
√चीव् (चीव)········	आदानसंवरणयोः—क्षी ।	

ग—प्रेतचीवरवसास्वनोग्रया–रघु. ११,१६ । चीरचीवरपरिच्छदाम्–मालतीमा. १ । "पुच्छभाण्डचीवराण्णिङ्" (पा. अ. ३/१/२०) ।

+√चुच्य् (चुच्यी) १/५१४ शा-च × (काक्र-√चुच् [चुची]) चुच्यतीति व्याख्यायाम्।	अभिषवे (प) इति दुर्गः -क्षी। क्षी-मै-सा-जै-कात-शा-हे-वो। काक्र।	<√शुच्य् (शुच्यी) अभिषवे (प)। √चूच् (चूची) ४/ [१/२३१d] अभिषवे (प) काक्र।

छ—√चुचाना } (<चुच्यनम्)=क्षरणे।
छ—√चुचुआना }

+√चुट् (चुट) १/३२१ शा-च-जै-काक्र-शा ×	अल्पीभावे (प) इति दुर्गः- क्षी क्षी-मै-सा-कात-हे। तुच्छने—वो।	<√चुण्ड् (चुडि) अल्पीभावे (प)। √चुण्ट् (चुटि) १/ अल्पीभावे (प) इत्येके-क्षी।

छ—√छोंटना (<चोटनम्) [बुं. ख.]=अल्पीभावे।

+√चुट् (चुट) ६/९७ शा ×	छेदने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।	√छुट् (छुट) ६/९८ छेदने (प)। √चुण् ६/९०a छेदने (प) कात; ९१a काक्र; १४३ हे।

छ—चोट (<चोटः=छेदः)=आघातः, प्रहारः।
छ—√चुटाना=क्षताङ्गत्वे, आहतौ।
छ—√चोटाना=क्षताङ्गत्वे, आहतौ।

+√चुड् (चुड) ६/११० शी-मै-शा-च-जै-काक्र-कात-शा-हे-वो×	संवरणे (प) सा सा।	√त्रुड् (त्रुड) ६/ संवरणे (प)।
+√चुड्ड् (चुड्ड) १/३४४ जै-काक्र-कात ×, शा	हावकरणे (प) क्षी-च-शा-हे। भावकरणे—मै-सा। हावे, कृतौ—वो।	√चुद् (चुद) १०/ संचोदने (प) √चुद्+ड=√चुड्ड्।

√चुड्ड् (चुड्ड) १/६१५ भावकरणे—जै।
हावकरणे—काकृ-कात।
हावे, कृतौ—वो।
हावः = भावसूचनम्-क्षी।

छ—चुड्ड (<चुड्डम् =भगम्-क्षी)=योनिः, भगम् (पाञ्चालभा.)।
छ—चुड्डो- = स्त्रीजनान् प्रत्याक्रोशः। छिन्ननारि! इति।

+√चुण्ट् (चुटि) १/३२१ अल्पीभावे (प) इत्येके— <√चुण्ड् (चुडि) अल्पीभावे (प)।
सा-श-जै-काकृ-कात- क्षी
शा× क्षी-मै-च-हे।
तुच्छने—वो।

छ—√छोंटना (<चुण्टनम्)=अल्पीभावे (बुं. ख.)।
छ—√चोंटना (<चुण्टनम्)=अल्पीभावे (बुं. ख.)।

√चुण्ड् (चुडि) १/३२१ अल्पीभावे (प)
मै-श-च-काकृ-कात- क्षी-सा-जै-शा-हे-वो।
(हे)×

<√चुण्ट् (चुटि) अल्पीभावे (प) इत्येके—क्षी।
<√चुट् (चुट) अल्पीभावे (प) इति दुर्गः—क्षी।

छ—चौंढा (<चुण्डः) जलपातनाय वीनाहे क्रमशो निम्नभागः। तत् स्थलं यत्र क्षेत्रसेचनकूपाच्चर्मद्रोण्या जलं निस्सार्य पात्यते। (तत्र निम्नभागत्वाज्जललेशोऽपि न तिष्ठति, इति 'अल्पीभावः' सङ्गतः)। सर्वथाभावेऽप्यल्पीभावः प्रयुज्यते। यथा—√'छोंटना'—(बुं. ख.)।

+√चुत् (चुतिर्) १/४० क्षरणे (प) द्रमिडा इत्यप्याहुः—क्षी
श-च-जै-काकृ-कात-
शा× क्षी-मै-सा-हे।
क्षरे—वो।

<√श्चुत् (श्चुतिर्) क्षरणे (प)।
√श्चुत् (श्चुतिर्) क्षरणे (प)।
√च्युत् (च्युतिर्) १/ आसेचने (प)।
√च्यु (च्युङ्) १/ गतौ (आ)।

[छ—√चुँअना, √चूँना = (<च्यवनम्?)=क्षरणे]

+√चुप् (चुप) १/४०१ श×

मन्दायां गतौ (प)
क्षी-मै-सा-च-जै-कात-शा-हे।
कुण्ठायां गतौ—काक्र।
शनैर्गतौ—वो।

√चुप् १/२०० b कुण्ठायां गतौ (प) काक्र।

ग—इष्टकाः चुपुणीकाः-तै. ४,४,५१। चोपति-मभार. ३,१०६४८।

+√चुप् (चुप) ६/११४ क्षी-मै-श-च-जै-काक्र-कात-शा-हे-वो×

स्पर्शे (प) इति केचन—सा।
भाष्यविरोधादुपेक्ष्याः—सा।

<√छुप् (छुप) स्पर्शे (प)।
√स्पृश् (स्पृश) ६/ संस्पर्शे (प)।

√चुम्ब् (चुबि) १/४२३ श-काक्र×

वक्त्रसंयोगे (प)
क्षी-मै-सा-च-जै-कात-शा-हे।
चुम्बने—वो।

ग—आस्फोटयामास चुचुम्ब पुच्छम्-वा. रा. ५,१०,५४।
ङ—√चुंब=चुम्बने। वक्र-चुंबंत-गा. १७६; ५१९।
छ—√चुंबना * (<चुम्बनम्)=चुम्बने, (२) स्पर्शे।
छ—√चूमना * (<चुम्बनम्)=चुम्बने, (२) स्पर्शे।
ज—√चु } =चुम्बने।
ज—√चो }

+√चुल्ल् (चुल्ल) १/५३१ श

हावकरणे (प)
क्षी-मै-च-कात-शा-हे।
भावकरणे—सा-जै।
काक्र ?
हावकृतौ—वो।

√चुड्ड् (चुड्ड) १/ हावकरणे (प)।
√चुल १/२४३ a पाकाग्नि-कुण्डे (प) काक्र।

हावकरणे= अभिप्रायसूचनेऽर्थे—क्षी।
छ—चुल=खर्जूः, उन्मादः। कामोद्वेगः।
छ—चुलचुलाना=खर्जने। कामोद्वेगे।
छ—चूल्हा (<चुल्लः [मू])।

+√चूर् (चूरी ४/४७ श	दाहे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो (प) ?	√चूर्ण् (चूर्ण) १०/ प्रेरणे (प) प्रेरणम् = दलनम्-क्षी ।

ग—पातकान्यपि चूर्यन्ते-स्क. पु. १,६,९३ ।

छ—√चुरना (<चूरणम्) = पाके (अग्नौ क्ष्वेलितेन जलेन कस्यचन वस्तुनः पाके) ।

छ—√चुराना (<चूरणम्) = पाके ।

√चूष् (चूष) १/६६६ श× काकृ√चुष् (चुष) चुषादेर्दीर्घ इति व्याख्यया चूषति ।	पाने (प) क्षी-मै-सा-च-जै-कात-शा-हे-वो ।	

ग—चूष्यते, चूषयति (चूषति) इति ह्वि. । मया नावाप्तम् ।

छ—√चूसना (<चूषणम्) ।
छ—√चोखना† (<चूषणम्) ।
बुं. ख.—छ—√चोंखना (<चूषणम्)
छ—√चुहना† (<चूषणम्)
} = दन्ताद्यैरापीडय कस्यचन वस्तुनो रसपाने ।

+√चृण् (चृणु) ८/५ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	अर्दने (प) इति नन्दी-<√तृण् (तृणु) अदने (प) । क्षी क्षी ।	√चृत् (चृत) ६/ हिंसा-ग्रन्थनयोः (प) ।
√चृत् (चृती) ६/४५ श (काकृ-कात√वृत् [वृती]) स्यात्लैपिकी त्रुटिः ।	हिंसाग्रन्थनयोः (प) क्षी-मै-सा-शा । ग्रन्थे हिंसायां च—जै । हिंसाग्रन्थयोः—हे । हिंसायाम्—च । हिंसे ग्रन्थे—वो । ग्रन्थे हिंसायां च—काकृ । हिंसायाम्—कात ।	√चृत् (चृत)१०/संदीपने(प) इत्येके—क्षी । √चॄ ९/२३ वयोहानौ (प) मै ।

ग—अव...चृत-ऋ. १,२५,२१। आ...चृततु-शौ. ५,२८,१२, पै २,५९,११।

+√चॄ ९/२३ क्षी-सा-श-च-जै-काकृ-कात-शा-हे-वो× | वयोहानौ (प) इत्येके-मै। | <√जॄ वयोहानौ (प)। <√धॄ वयोहानौ (प)। इति त्वेके इति मैत्रेयः—सा।

+√चेल् (चेलृ) १/५३६ श-जै× | चलने (प) क्षी-मै-सा-च-शा-हे। गतौ—काकृ-कात। केलवत् (=चालगत्योः)—वो। | √चल् (चल) १/कम्पने (प)। √छेल् १/२४७ c गतौ (प) काकृ। √केल् (केलृ) १/चलने (प)।

ग—चारुचेलं वसाना—(प्रेक्टिकल सं. इं. डि. [आप्टेः])।

√चेष्ट् (चेष्ट) १/२५४ श× | चेष्टायाम् (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। ईहे—वो। चेष्टा=ईहा—क्षी।

ग—चेष्टते-पाशु. २,८; वरा. ३, १४; राधा. १,१८। विचेष्टते-मनु. ८,३३४।

√च्यु (च्युङ्) १/९३९ श | गतौ (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे। जै ? गत्याम्—वो। | च्यवते-निघ. २/१४-गतिकर्मा। √छ्यु (छ्युङ्) १/ गतौ (आ)।

ग—च्यवम्-ऋ. १,१६५,१०; अचुच्यवीतन-१,३७,१२। च्यवते-तै. ३,५,१०, ३। उत्पद्यन्ते च्यवन्ते च-मनु १२,९६=विनश्यन्ति (मन्व.)।

घ—चवति-दीघ. १,१४।

ङ—√चु=(विनाशे) मरणे, (तु. मनु. १२,९६), (२) पतने—भवि.।

√च्युत् (च्युतिर्) १/३९ श× | आसेचने (प) क्षी-मै-सा-च-काकृ-कात-हे। क्षरणे—जै-शा। क्षरे—वो। | √श्च्युत् (श्च्युतिर्) १/ क्षरणे √चुत् (चुतिर्) १/ क्षरणे इति द्रमिडाः-क्षी। √श्चुत (श्चुतिर्) १/ क्षरणे इति कौशिकः—क्षी।

आसेचनम्=ईषत्सेकः—क्षी।

ग—'च्योतति' इत्युदाहरणं सूत्रसाहित्ये दर्शयति ह्वि.।

+√छद् (छदिर्) १/८०३ c ऊर्जने (प) मित् छदयते—निघ. ३/१४=
जै, ×, श क्षी-मै-सा-च-काकृ- अर्चतिकर्मा।
कात-शा-हे, वो (उ)। अचच्छदत्—निरु. ९,८=
छादयित्वोत्साहयति।

ऊर्जनम्=बलं जीवनं च—दुर्गादा.।

ग—छदयति—ऋ. ३,९,७; ऐब्रा. १,३०; मन्त्रब्रा. २,६,१३।

+√छम् (छमु) १/४६५ अदने (प) √चम् (चमु) १/ अदने (प)।
जै×,श क्षी-मै-सा-च-काकृ- √जम् (जमु) १/अदने (प)।
कात-शा-हे। √झम् (झमु) १/ अदने (प)।
भक्षे—वो।

छ—छेमड़ा (<छमण्डः)=मृतपितृकः, बन्धुहीनः (वङ्ग.)। (छमति=भक्षयति जन्मग्रहणानन्तरं पितरं नाशयतीत्यर्थः)।

+√छष् (छष) १/८७६ हिंसायाम् (उ) √चष् (चष) १/ वधे
श-च× क्षी-मै-सा-जै-काकृ- (प) वो।
कात-शा-हे। √चषघ् (चषघ) ५/ हिंसायाम् (प)। इत्येके—क्षी।
वधे—वो। √खष् १/५१९ हिंसायाम् (प) हे।
√जष् (जष) १/हिंसायाम् (प)
√झष् (झष) १/ हिंसार्थः (प)

अयं कैश्चिन्न मन्यते—दुर्गादा.।

√छिद् (छिदिर्) ७/३ द्वैधीकरणे (उ) √चृत् (चृती) ६/ हिंसाग्रन्थनयोः (प)।
क्षी-मै-सा-च-जै-शा-हे। √छेद (छेद) १०/ द्वैधीकरणे (प)।
द्विधाकरणे—काकृ-कात। √छिद्र (छिद्र)१०/भेदे (प)।
छेदे—वो।

ग—अच्छेदि–ऋ. १,११६,१५ । छिनत्ति–तै. १,७,२,४ ।

+√छुट् (छुट) ६/९८ छेदने (प) श-च× क्षी-मै-सा-जै-काकृ-कात-शा-हे । छेदे—वो । ण्यन्ते⋯वेष्टयित्वा कर्षणे—ह्वि. ।

√कुट् (कुट) १०/ छेदने (आ) सा । √खुर् (खुर) ६ छेदने (प) सा । √चुट् (चुट) ६/ छेदने (प) ।

ग—छोटिका०, छोटित०—ह्वि. ।

ङ—√छुट्ट (अक)=बन्धनछिन्नतायाम्, मुक्तौ । छुट्टइ—भवि. । छुट्टह–धम्म. ९ टी.

छ—√छूटना=च्युतौ ।

√छुड् (छुड) ६/११० संवरणे (प) इत्येके–मै । क्षी-श-च-जै-काकृ-कात-शा-हे× मै-सा । ण्यन्ते⋯ वेष्टयित्वा कर्षणे–ह्वि ।

√स्थुड् (ष्ठुड) ६/ संवरणे (प) मै । √थुड् (थुड) ६/संवरणे (प) । √खुड् (खुड) ६/ संवरणे (प) ।

ह्वि· छोडयतीत्युदाहरणं प्रस्तौति ।

+√छुप् (छुप) ६/१३७ संस्पर्शे (प) क्षी-(यु. मी. सं.) काकृ-कात । स्पर्शे—क्षी-मै-सा-च-जै-हे-वो । स्पर्शने—शा ।

√चुप् (चुप) ६/ स्पर्शे (प) केचन पठन्ति ते भाष्यविरोधादुपेक्ष्याः—सा । √स्पृश् (स्पृश) ६/ संस्पर्शे (प) ।

घ—छुपति—विनय. १,१९१ ।

छ—√छोपना=सक्त्यर्थं स्पर्शो, क्लिन्नाया मृदोऽन्येन पदार्थेन तथा योजनं स्पर्शो वा यथा सा तत्र सक्ता भवेत् ।

√छुर् (छुर) ६/९२ श छेदने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । विकिरणे—ह्वि. ।

√क्षुर् (क्षुर) ६/६२ विलेखने (प) । √खुर् (खुर) ६/६३ विलेखने (प) ।

ग—छुरिकया—कथासरि. २५,१४९। सिन्दूरैश्छुरयन् महीम्-२४,१। छुरितम्-शिशु. १,२२=खचितम्।

ङ—√छुर (सक)=(१) लेपने, (२) छेदने, (३) व्याप्तौ-वा. १२, पउम. २८, २८।

√छृद् (उच्छृदिर्) ७/८ दीप्तिदेवनयोः (उ) √छृद् (छृद) १०/ संदीपने (प) इत्येके-क्षी।
श
क्षी-मै-सा-जै-काकृ-कात-हे।
दीप्तौ—च।
दीप्तिवमनयोः—शा।
वमने—हे।
देवने त्विषि वमने—वो।

ग—आच्छृणत्ति-तै. ५,१,७,४; मै. ३,१,८; छृणत्तु-४,९,१।

√छो ४/३७ छेदने (प) √शो ४/ तनूकरणे (प)।
श
क्षी-मै-सा-च-काकृ-कात-शा-हे।
छेदे—जै।
लूनौ—वो।
√छा... ह्वि.।

ग—छ्यति—तै. ५,२,१२,१; शब्रा. ४,३,२,३।

+√छ्यु (छ्युङ्) १/९४० गतौ (आ) √च्यु (च्युङ्) १/ गतौ (आ)।
सा-जै-काकृ-शा×, श क्षी-मै-च-कात-हे। √जु ६/ गतौ (प)।
गत्याम्—वो। √ज्यु (ज्युङ्) १/ गतौ (आ)।
√झ्यु (झ्युङ्) १/ गतौ (आ) मै।

√जक्ष् (जक्ष) २/६० भक्षहसनयोः (प) √घस् (घस्लृ) १/७०७ अदने (प)।
श
क्षी-मै-सा-जै-कात-शा-हे। √हस् (हसे) १/ हसने (प) सन्नन्ताद्-√जक्ष।
भक्षणे—च।
भक्षणहसनयोः—काकृ।
भक्षणहासयोः—वो।

ग—जक्षीयात्—ऋ. १०,२८,१ = भक्षणे । जक्षतः—ऋ. १,३३,७ = हसने ।
घ—जग्घति—जातक ३,२२३ ।

+√जज् (जज) १/२३८ श ×	युद्धे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । युधि—वो ।	√जञ्ज् (जजि) १/ युद्धे (प) । √जग् १/४१० j आदाने (आ) । काकृ । जञ्झतीः-ऋ. ५,५२,६; जञ्झतीरापो भवन्ति शब्दकारिण्यः—निरु. ६,१६,६ ।
√जञ्ज् (जजि) १/२३९ श ×	युद्धे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । युधि—वो ।	√जिञ्ज् १/३१३० हिंसागत्योः (प) काकृ । शेषः पूर्ववत् । √जङ्ग् १/२०४ m गतौ (प) काकृ ।

ग—असुर्येव जञ्जती—ऋ. १,१६८,७ । [अर्थः, व्यु. च. ? । विप. राति-(वैतु. वें. नाप.) [सेना-]इति]-अर्चिषा जञ्जणाभवन्-ऋ. ८,४३,८ । ह्विटनीरर्थेऽनिश्चितमतिः ।
छ—जंग (फार.)=युद्धम् ।

+√जट् (जट) १/३०१ श	संघाते (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । संहतौ—वो ।	√जठ् १/१३४ धारणे (प) काकृ । √झट् (झट) १/३०२ संघाते (प) ।

क—जेर् = वेष्टने, गुण्ठने । जटा * जेर्-त = चूडा—(वा. पॉकर्नीः) ।

ग—जटाः-मभार. ३,११२,२ । मनु. ६, ६ ।
घ—जटा-सुत्तनिपात २४९ ।
ङ—जडा (<जटा)-हेका. २५७; सुपा. २५१ ।
छ—√जड़ना (<जटनम्)=जटने (सङ्घाते), प्रतिवपने, खचने, मिथो लग्नतायाम् ।

छ—जड़िया = स्वर्णकाराणां जातिभेदः ।

√जन् (जन) ३/२४ जनने (प) √जन् (जनी) ४/३९ प्रादुर्भावे
श-जै-शा × क्षी-मै-सा-च- (आ)।
काक्र-कात-हे।
जनौ—वो।

ग—जज्ञान-ऋ. ३,२९,३; भा. पु. ५,७,१३।

√जन् (जनी) ४/३९ प्रादुर्भावे (आ) मित्
श क्षी-मै-सा-च-जै-काक्र-कात-
शा-हे।
जनौ—वो।

जनीजॄष्क्नसुरञ्जोऽ-
मन्ताश्च १/८०३ m
श-जै-शा-हे-वो ×

ग—जायते-ऋ. २,३,९। जनयति-तै. २,२,१०,५।
घ—जायति-जातक ३,४५९।
ङ—√जण (सक)=जनने। जणंति-प्रासू. १५; १०८; महा.।
ङ—√जा (सक)=जनने। वक्र-जायंत-कुमा.। संक्र-जाइउं-स. १३०।
छ—√जनना (<जननम्)।

√जप् (जप) १/३९६ व्यक्तायां वाचि मानसे च (प) √जाप्१/२०१aआलस्ये।
श क्षी-मै-सा-जै-काक्र-कात-शा। (प) काक्र।
वचने—च। √जल्प् (जल्प) १/
व्यक्ते वचने मानसे च—हे। व्यक्तायां वाचि (प)।
हृदुच्चारे वाचि—वो।

ग—जपति-शत्रा. १,१,२,१२।
घ—जपति-जातक ४,२०४।
ङ—जवइ-रंभा.।
छ—जपना।

√जभ् (जभ) १/३८५ गात्रविनामे (आ) √जम्भ् (जभि) १/४११ a
मै-सा-श-च-जै-काक्र- (जभते) गात्रविनामे (आ) च;
कात-शा-हे-वो × क्षी। हे ७८२; जै१६२;काक्र ४७२।

√जभ् (जभ) १/३८९ मै-सा-कात-वो । (जम्भते)
क्षी-च-जै-काक्र-शा-हे
×,श

√जृम्भ् (जृभि) १/ गात्रविनामे (आ)।

√जभ् (जभी) १/३८९ गात्रविनामे (आ)
क्षी-श-च-जै-काक्र-कात-वो× इत्येके—मै ।
मै-सा-शा-हे ।

ग—अग्निर्जम्भैः...अत्ति-ऋ. १,१४३,५ । जम्भसाधकाः-मभार. ५,६४,२० । ता इमा जभितुं पापाः-भा. पु. ३,२०,२६ ।

+√जभ् (जभ) १/९८८ विपरीते मैथुने (प)
क्षी-श-च× इत्येके—मै ।
मै ।
विपरीतमैथुने—सा ।
मैथुने—जै-काक्र-कात-शा-हे।
यभने—वो ।

<√यभ् (यभ) विपरीते मैथुने (प) ।

√यभ्>√जभ् इति लौकिको जकार उच्चारणभेदात् ।

√जम् (जमु) १/४६६ अदने (प)
जै×,श
क्षी-मै-सा-च-काक्र-कात-शा-हे ।
भक्षे—वो ।

√चम् (चमु) १/ अदने (प)।
√छम् (छमु) १/ अदने (प)।
√झम् (झमु) १/४६७ अदने (प) ।
जमति-निघ. २,१४-गतिकर्मा ।
जमत्—१,१७ = ज्वलतो नामधेयम् ।

ग—जमदग्निः-खि. ५,३,४; तै. २,२,१२,४; मै. २,७,१९ । जाजमत्-मभार. १३,१,९३,९८ = पुनः पुनर्भक्षयन्तः (नील.) ।

(ज)—सन्तल.-जाम्, कुर्कू.-जोम्, शवर.-जुम्, मैथिल.-जम् ।

+√जम्भ् (जभि) १/९६५ विपरीतमैथुने (प)
मै-सा-श-च-जै-काक्र-कात-शा-हे× इति दौर्गाः—क्षी
क्षी ।
यमने—वो ।

>√यभ् (यभ) विपरीतमैथुने (प) ।
√जम्भ् १/३६१b गर्त्रे (प) काक्र ।

+√जर्च् (जर्च) १/७०८ परिभाषणे (प) इत्येके–क्षी (क्षी–यु. मी. सं. ×) क्षी ।		<√चर्च् (चर्च) परिभाषणे (प) ।
मै-सा-श-च-जै-हे-वो×	परिभाषणहिंसातर्जनेषु —शा ।	√झर्छ् (झर्छ) १/ परिभाषणे (प) ।
	परिभाषणतर्जनयोः—काक्ृ-कात ।	

+√जर्च् (जर्च)६/१९ परिभाषणे (प) इति दुर्गः—क्षी		<√जर्ज् (जर्ज) परिभाषणे (प) ।
च-जै-काक्ृ×,श	क्षी-कात-शा-हे ।	द्रष्ट.√जर्ज् ६/१९ ।
	परिभाषणसंतर्जनयोः—मै ।	
	परिभाषणभर्त्सनयोः—सा ।	
	उक्तौ भर्त्से—वो ।	

किमत्र सत्यम् ! देवा ज्ञास्यन्ति–क्षी ।

+√जर्ज् (जर्ज) १/७०८ परिभाषणे (प) इत्यन्ये—क्षी		√जॄ (जॄष्) ४/ वयोहानौ (प) ।
श-च-काक्ृ-कात-शा-हे-वो×	क्षी ।	
	परिभाषणसंतर्जनयोः—मै ।	
	परिभाषणहिंसातर्जनेषु—सा-जै ।	

ग—जर्जरः-शिशु. ४,२३=विदीर्णे (हिंसेयम्) ।

+√जर्ज् (जर्ज) ६/१९ परिभाषणे (प)		√चर्च् (चर्च) ६/ परिभाषणे (प) ।
श-च-कात-शा×	क्षी-जै-हे ।	√छर्छ् ६/२४d परिभाषणतर्जनयोः (प) काक्ृ ।
	परिभाषणसंतर्जनयोः—मै ।	√जच्छ् (जच्छ) ६/ उक्तौ भर्त्से (प) वो ।
	परिभाषणभर्त्सनयोः—सा ।	√जर्ज् (जर्ज) १/ परिभाषणे (प) ।
	परिभाषणतर्जनयोः —काक्ृ ।	√जर्झ् (जर्झ) ६/ परिभाषणे (प) ।
	तर्जने—हे ।	
	भर्त्से वाचि—वो ।	

		√जर्त्स् (जर्त्स) ६/ परिभाषणे (प)। √झर्च् (झर्च) ६/ परिभाषणे (प)। √झर्झ् (झर्झ) ६/ परिभाषणे (प)।
+√जर्झ् (जर्झ) ६/२० मै-सा-श-च-जै- काकृ-कात-हे×	परिभाषणे (प) क्षी-शा। भर्त्सोक्त्योः—वो।	द्र. √जर्ज् ६/१९।
+√जर्त्स् (जर्त्स) १/७०८ मै-सा-श-जै-काकृ- कात×	परिभाषणे (प) इति चन्द्र- दुर्गौ—क्षी। क्षी-च। परिभाषणहिंसातर्जनेषु— शा-हे। रक्षे झर्झे च—वो।	√तर्ज् (तर्ज) १/ भर्त्सने (प)। वर्णविपर्ययेण √जर्त् + स्=√जर्त्स् इति बोध्यम्।
+√जल् (जल) १/८१७ श×	घात्ये (प) क्षी-शा-हे। धान्ये—मै-च-जै-काकृ-कात। घातने—सा। धान्ये—वो	√जल् १/२४८ g चलने (प) काकृ। (येन यो व्यापारो दृष्टस्तेन स निर्दिष्टः)। √गॄ ६/निगरणे (प)। √जॄ ९/वयोहानौ (प)। √जलम्-निघ. १/१२=उदकनाम।

घात्यम्=जडत्वमतैक्ष्ण्यमित्यर्थः-क्षी।
घातनम्=तैक्ष्ण्यम् इति स्वामी-सा।

व—जुऍल्-, जुऍले (इ)=(१) प्रक्षेपे, प्रवाहे (२) निरसने-वा. पॉकर्नीः।

ग—देवसंघातप्लुतजलाम्-वा.रा. २,५०,१८ (गी. प्रे. सं.)। जडः=शीतलः। यथा-"हर्षजडेन पाणिना"-रघु. ३,६८=हर्षशिशिरेण-(मल्लि.)। जडवल्लोक आचरेत्-मनु. २,११०=मूकवत्। जडः=बधिरः-मनु. ९,२०१।

√जल्प् (जल्प) १/३९५ व्यक्तायां वाचि (प) √जल् (जल) १/घात्ये (प) ।
श
क्षी-मै-सा-जै-काकृ-कात-शा । √लप् (लप) १/व्यक्तायां वाचि (प) ।
वचने—च ।
व्यक्ते वचने—हे । √रप् (रप) १/ व्यक्तायां वाचि (प) ।
वाचि—वो ।
√ह्लप् (ह्लप) १/ व्यक्तायां वाचि (प) ।
√जप् (जप) १/ व्यक्तायां वाचि (प) ।
√जल्पति—निघ. ३/१४ =अर्चतिकर्मा ।

ग—जल्प्या—ऋ. १०,८२,७ । जल्पन्—शब्रा. ११,५,१,४; । जजल्पेव तदा लङ्का—वा. रा. ५,१०३ ।

ङ—√जप्प=वाचि । जप्पंति—पि. २९६ ।
ङ—√जंप=वाचि । जंपइ—प्राप्र. ।
छ—√जल्पना=प्रलापे ।

+√जष् (जष) १/६७८ हिंसार्थः (प) √कष् (कष) १/ हिंसार्थः (प)।
श×
क्षी-मै-सा-कात । √चषघ् (चषघ) ५/ हिंसायाम् (प) ।
हिंसायाम्—च-जै-काकृ-शा-हे
√छष् (छष) १/ हिंसायाम् (प)
वधे—(उ) वो । √झष् (झष) १/ हिंसार्थः (प) ।

ग—जषाः—अ. वे. ११,२,२५ । तै. ५,५,१३,१ । √झष् (झष) १/ हिंसार्थः (प)।

√जस् (जसु) ४/९८ मोक्षणे (प) जसति (निघ.२/१४)
श
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । =गतिकर्मा ।
व्यत्ययेन शप्—देवराजयज्वा ।
मोक्षे—वो ।
श्रान्तौ—ह्वि. ।

ग—सर्वे साकं नि जस्यत—ऋ. १,१९१,७; जसुः—१०,३३,२; जसुम्—१०,६८,६। जजास ते विषम्—अ. वे. ५,१३,१ ।

√जागृ १/६१ निद्राक्षये (प) √गॄ १०/विज्ञाने (आ)।
श क्षी-मै-सा-च-काक्व-कात- √गॄ ९/शब्दे (प)।
शा-हे।
निद्राक्षये—जै।
जागरे—वो।

ग—जागृहि—ऋ. ९,६१,२४। जागर्ति-मै. ३,६,३,।
घ—जग्गति-जातक ५,२६९।
ङ—√जग्ग=निद्राक्षये, अवहितौ। जग्गइ, जग्गि-प्रासू. ९८।

ङ—√जागर = निद्राक्षये। वक्व-जागरमाण—विसे. २७१९। हेक्व-जगरित्तए—कप्प.।

छ—√जागना, √जगना = निद्राक्षये।

√जि १/५६० जये (प) अक. √चि (चिञ्) ५/चये (प)।
जै शा हे×,श क्षी-मै-सा-च-कात-वो।
(काक्व-√जी) काक्व।

जयः=उत्कर्षः—क्षी।
ग—जयति-ऋ. ६,२१,४; तै. २,१,३,२।
घ—जेति-जातक २,३।

√जि १/९३१ अभिभवे (प) सक. √चय् (चय) १/गतौ (आ)।
श× क्षी-मै-सा-च-जै-काक्व-कात
शा-हे।
अभिभवे जये च—वो।

ग—आ जयन्-ऋ. २,२७,१५।
ङ—√जय (सक)=जये, (अक) उत्कृष्टत्वेन वर्तने। जयइ-महा.।
ङ—√जिण=जये। वक्व-जिणंत-पिं. ४७३; पउम. १११,१७।

√जिन्व् (जिवि) १/५८७ प्रीणनार्थः (प) √जिन्वति-निघ. २/१४-गतिकर्मा।
श-च-जै× क्षी-मै-सा-कात।
प्रीणने—काक्व-शा-हे-वो। √इन्व् (इवि) १/प्रीणनार्थः (प)।
उत्तेजने, तीव्रतायाम्—हि.।

√दिन्व् (दिवि) १/प्रीणनार्थः (प) ।
√धिन्व् (धिवि) १/प्रीणनार्थः (प) ।

ग—आ जिन्वथः-ऋ. ४,४५,३ । जिन्वति-ऋ. १,१६२,३ ।

+√जिम् (जिमु) १/४६८ अदने (प) इत्येके—क्षी <√जम् (जमु) अदने (प) ।
श-च-जै × क्षी-मै-सा-काकृ-कात-शा-हे । भक्षे—वो ।
√चम् (चमु) १/४६४ अदने (प) ।
√छम्(छमु) १/अदने (प) ।
√झम् (झमु) १/अदने (प) ।
√झिम् १/२२१ f अदने (प) काकृ ।
√जिल् १/२५० J अदने (प) काकृ ।
√जील् १/२५० I अदने (प) काकृ ।

ग—जेमितुम्–नैषध. १६,८७=भोक्तुम् ।

ङ—√जेम (सक) अदने । वकृ–जेमंत–पउम. १०३,८५ । जेमिय (<जेमितुम्)–णाया. १,१ पत्र. ४१ टी. ।

ङ—जिभण (<जेमनम्)–श्रा. १६; चैत्य. ५९ ।

ङ—जेमण (<जेमनम्)—ओघ. ८८; औप. ।

ङ—जिमिअ (<जिमितम्)—पउम. २०,१२७; पुष्प. ३५; महा. ।

छ—√जीमना
छ—√जेंवना } =अदने । "बैठि कबीरा जीम"—कबीरदासः ।

+√जिरि ५/३१ हिंसायाम् (प)
श-जै-शा × क्षी-मै-सा-च-हे । जिघांसायाम्—काकृ-कात । हिंसे—वो ।
√चिरि ५/ हिंसायाम् (प) ।
√रि ५/ हिंसायाम् (प) ।

+√जिष् (जिषु) १/६८८ सेचने (प)
श × क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । सेके—वो ।

√जीव् (जीव) १.५६१ प्राणधारणे (प) √चीव् (चीवृ) १/ आदान-
श क्षी-मै-सा-च-जै-काक्र- संवरणयोः (उ)।
कात-शा-हे।
प्राणे—वो।

ग—जीवति-ऋ. १०,३३,९।
ङ—जीवइ—कुमा.।
छ—√जीना (<जीवनम्)।

+√जु १/९२८ गत्यर्थः (प) जवति-निघ. २,१४ गतिकर्मा।
क्षी-मै-श-च-जै-काक्र- सा।
कात-शा × वेगवचन इत्यपरे—सा।
गतौ—हे।
रंहसि—वो।

√जू... शीघ्रगामित्वे (आ)—ह्वि.।
ग—जवनी-ऋ. १,५१,२। जवनः—श्वेताश्व. ३,१९; नाप. ९, १४।

√जु (जुङ्) १.९४१ गतौ (आ) इति नन्दी-क्षी <√ज्यु (ज्युङ्) गतौ (आ)।
मै-श-च-जै-कात-शा × क्षी-सा-काक्र-हे।
गत्याम्—वो।
√जू... शीघ्रगामित्वे—ह्वि.।

ग—जवेते—ऋ.३,३३,१। जवते—तै. ६,१,७,२; मै.३,७,५; शब्रा. १०,३,५,२।
घ—जवति—संयुत्त. १,३३; जातक ४,२१३=शीघ्रगामित्वे।

+√जुङ्ग् (जुगि) १/१५६ वर्जने (प) √युङ्ग् (युगि) १/
श × क्षी-मै-सा-च-जै-कात-शा-हे। वर्जने (प)।
त्यागे—वो। √भुङ्ग् (भुगि) १/
(काक्र-√ तुङ्ग् [तुगि]) वर्जने—काक्र। वर्जने (प)।
लैपिकी त्रुटिः। 'जुगि' √वुङ्ग् (वुगि) /१
इति भाव्यम्। वर्जने (प)।
√रुङ्ग् (रुगि) १/
वर्जने (प)।

ग—जुङ्गः=वृद्धदारकः। यथा—जुङ्गक्ष्यैगन्धाच्छगलान्त्रवेगी वृद्धदारकः-वैद्यकरत्नमालायाम्-(श. क. द्रु.)।

+√जुड् (जुड) ६/४७ च-जै-शा ×, श ?	गतौ (प) इति दुर्गः–क्षी क्षी-मै-सा-काक्र-कात-हे-वो।	<√जुन् (जुन) गतौ (प)। √जु१/९२८गत्यर्थः (प) सा। √जुड् (जुड) ६/बन्धे (प)। √जुन् १/२२०k संभक्तौ (प) काक्र। √जुड् (जुड) १० / प्रेरणे (प)।
+√जुड् (जुड) ६/९९ श	वन्धने (प) क्षी-मै-सा-काक्र-शा-हे। वन्धे—च-जै-कात-वो।	पूर्ववत्। √युज्+त = युक्त >जुट्ट >√जुड् इति स्यात्। √यु २/ बन्धने (प)। √यौट् (यौटृ) १/बन्धे (प) सा।

ङ—√जोड (सक)=बन्धने, संयोजने। वक्र–जोडेंत–सुर. ४,१९। संक्र–जोडिऊण–महा.। जोडिअ(=योजितम्)–सुपा. १४९; ३५१।

छ—√जोड़ना
छ—√जोरना } =बन्धने, योजने।

छ—√जुड़ना
छ—√जुरना } =बन्धने, योजने।

छ—√जूरना=बन्धने, योजने।

छ—जूरना*=बन्धने, योजने।

छ—√जुलना=संयोगे, साक्षात्कारे।

+√जुत् (जुतृ) १/३१ श×	भासने (आ) क्षी-मै-सा-शा-हे दीप्तौ—जै। च-काक्र-कात ? द्युत्याम्—वो।	>√ज्युत् (ज्युतृ) भासने (आ) इति कौशिकः–क्षी। √द्युत् (द्युत) १/दीप्तौ (आ)। √युत् (युतृ) भासने (आ)।

घ—उज्जोत–जातक १,१८३=भासने।

+√जुन् (जुन) ६/४७ मै-श-काक्र-कात×	गतौ (प) क्षी-सा-च-जै-सा-हे-वो।	द्रष्ट. √जुड़ ६/४७।

ग—जुनन्ति–तैब्रा. २,५,५,३। अयं √जु (जू) धातुतः क्र्यादावपि शक्यते साधयितुम्। ह्विट्नीमहाशयेन तथैव कृतम्, जुनातीति रूपोपलब्धेः।

√जुर्व् (जुर्वी) १/५७० (क्षी) मै-सा-च-जै-काक्र-कात-शा-हे ×	हिंसार्थः (प) इति दौर्गाः– क्षी (यु. मी. सं.)। वधे––वो। अपनोदे, नाशे––ह्वि.।	<√धुर्व् (धुर्वी) हिंसार्थः (प)। √जूर् (जूरी) ४. हिंसावयोहान्योः (आ)। √धूर्वति–निघ.२ १९ = वधकर्मा। √जॄ (जॄष्) ४.२२वयोहानौ (प)। √ज्वर् (ज्वर) १/रोगे (प)।
√जूर्व्–······		

ग—जूर्वन्–ऋ. १,१९१,९। निजूर्वसि–१०,१८७,३; ६,६,६; संजूर्वसि ८,४९,७।

√जुष् (जुषी) ६/८ श	प्रीतिसेवनयोः (आ) क्षी-मै-सा-जै-काक्र-कात-शा-हे। सेवायाम्—च। मुदि सेवे—वो।	√जुष् (जुष) १०/परितर्पणे (प)। जुषते–निघ. २/६=कान्तिकर्मा।

ग—अभि····अजुषन्त्–ऋ. ४,३३,९। जोषिषत्–ऋ. २,३५,१। जुषताम्–खि. १,३,१। जुषते–शांब्रा. १०,१;शब्रा ३,६,४,७।

ङ—√झूस् (सक)=(१)सेवायाम्, (२) प्रीतौ, (३) क्षये। वक्र–झूसमाण–आचा.; संक्र–झूसित्ता, झूसित्ताणं–औप.; पि. ५८३। झोसेइ–आचा.।

√जूर् (जूरी) ४/४४ श	हिंसावयोहान्योः (आ) क्षी-मै-सा-जै-शा। जरायाम्––च। जीर्णे––काक्र-कात। जरायां हिंसायां च––हे। ज्यानौ वधे––वो।	√जॄ (जॄष्) ४/२२ वयाहानौ (प)। √जुर्व् (जुर्वी) १/हिंसार्थः (प)। √ज्वर् (ज्वर) १/रोगे (प)।
√जुर् ४/·······	ज्यानौ(प)––ह्वि.।	

ग—जूर्यति–ऋ. १,१२८,२।

ङ—√जूर (अक)=(१) जीर्णे, शुष्कतायाम्, (२) सक–वधे––रींज.।

ङ—√झूर जीर्णे=वक्र–झूरंत, झूरमाण–सण। उप. पृ. २७।

छ—√झुरना = जीर्णे, शुष्कतायाम्–"हाड़ भई झुरि किंगड़ी"–जायसीः।

+√जूष् (जूष) १/६७२ च=हिंसायाम् (प)
श×
क्षी-मै-सा-च-जै-काक्ठ-कात-शा-हे।
वधे (उ)—वो।

√जुष् १/२९३ k हिंसायाम् (प) काक्ठ।
√यूष् (यूष) १/ हिंसायाम् (प)।
√ईष् (ईष) १/ गतिहिंसादर्शनेषु (आ)।

ङ—√जूस (सक)=क्षीणे, संतापे, विनाशे–ठा. २,१; कप्प.।
√झूस (सक)=क्षीणे, संतापे, विनाशे। संक्ठ–झूसेत्ता–अंत. २७।
√झोस (सक)=क्षीणे, संतापे, विनाशे। झोसेइ–आचा., संक्ठ–झोसेत्ता–सुर. ६,२४७।

√ जृ१/९३२
मै-सा-श-च-जै-काक्ठ
कात-शा-हे×

अभिभवे (प)
क्षी।
अभिभवे न्यक्कारे—वो।
नाशे, क्षये—ह्वि.।

<√त्रि अभिभवे (प) इति दुर्गः–क्षी।
जरते–निघ. ३/१९=अर्चतिकर्मा।
जरा स्तुतिर्जरतेः स्तुतिकर्मणः–निरु. १०,८,१।

ग—धत्तं रत्नानि जरतं च सूरीन्–ऋ. ७,६७,१० ? (=अर्चतम् ?)।

√जृम्भ् (जृभि) १/३८६ गात्रविनामे (आ)
श
क्षी-मै-सा-च-जै-काक्ठ-कात-शा-हे।
जृम्भे—वो

√जभ् (जभ) १/ गात्रविनामे (आ)।
√जम्म् (जभि) १/ गात्रविनामे (आ) च।
√जृम्ब् १/२०६ s मर्दने (प) काक्ठ।
√जृम्भ् १/३६१ a गर्वे (प) काक्ठ।

ग—जृम्भिताः–खि. ४,५,२६। जृम्भसि–तेजोबिन्दूप. ५,७४। जृम्भकः–भा. २९।
ङ—वक्ठ–जंभंत, जंभाअंत–गा. ५४६; से. ७,६५; कप्प.।

छ—√जँभाना
छ—√जम्हाना
} =जृम्भणे

√जॄ (जॄष्) ४/२२ श×	वयोहानौ (प) क्षी-मै-सा-जै-काकृ-कात- शा। जरायाम्—च। ज्याने—वो। जरसि—हे।	√चॄ ९/२२ वयोहानौ (प) मै। √झॄ (चॄष्) ४/ वयोहानौ (प)।

जनीजॄष्क्नसुरञ्जोऽमन्ताश्च १/८०३॥

श-जै-शा-हे-वो×

ग—जीर्यति-तै १,५,७,३; अ. वे. १०,८,३२।

+√जॄ ९/२३ श	वयोहानौ (प) क्षी-मै-सा-जै-काकृ- कात-शा-हे। जरायाम्—च। ज्याने—वो।	जिनाति—ऋ ५,३४,५ > जृणाति ! शेषः पूर्ववत्।

यथा तु भाष्यवार्तिकवृत्तिन्यासपदमञ्जर्यादि, तथायं धातुर्नास्तीति प्रतीयते इति जीर्यतावुपपादितम्। आत्रेयमैत्रेयदेवपुरुषकारादिषु दर्शनादिहास्माभिर्लिखितः—९/२२ सा।

+√जेष् (जेषृ) १/६११ श×	गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात- शा-हे। गत्याम्—वो।	√जेहृ (जेहृ) १/ प्रयत्ने (आ)। √एष् (एषृ) १/ गतौ (आ)। जेहते-निघ. २/१४=गति- कर्मा। √जेहृ (जेहृ) १/ गत्यर्थोऽपि (आ) सा।

√जेहृ (जेहृ) १/६३६ श×	प्रयत्ने (आ) क्षी-मै-सा-च-जै-काकृ- कात-हे। यत्ने—वो। प्रयतने—शा। गत्यर्थोऽपि—सा।	√एष् (एषृ) १/ प्रयत्ने (आ)। √येष (येषृ) १/ प्रयत्ने (आ)।

ग—जेहमानम्-ऋ. १,११०,५; तै. ४,६,,३। जेहमाना-शौ. १८,३,५७।

+√जै १/८९९	क्षये (प)	√क्षि १/ क्षये (प)।
श×	क्षी-मै-सा-च-जै-काक्र-काત-शा-हे-वो।	√क्षै १/ क्षये (प)।
		√सै १/ क्षये (प)।

√ज्ञा ९/३६	अवबोधने (उ)
श	क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
	बोधे—वो।
√ज्ञा १/८०३ ण	मारणतोषणनिशानेषु—मित्
श-जै-शा-हे×	क्षी-च।
	मारणतोषणनिशामनेषु—इत्येके—क्षी।
	क्षी-मै-सा-काक्र-कात।
	मारण आलोके निशाने तोषणे स्तुतौ—वो।

ग—जानाति—ऋ. ४४,६; तै. १,२,१४,३; मै. ४,११,५। ज्ञासे—तैब्रा. ३,६,८,१।

ङ—व्रक्र—जाणंत, जाणमाण—कप्प.; विपा. १,१।
ङ—√णा। भवि.—णाहिइ—विसे. १०१३।
ङ—√याण। याणइ—पि. ५१०; उव.; भग.।

√ज्या ९/२८	वयोहानौ (प)	√जि १/अभिभवे (प)।
श	क्षी-मै-सा-काक्र-कात-शा-हे।	√जॄ ९/ वयोहानौ (प)।
	हानौ—च-जै-श।	√जॄ (जॄष्) ४/ वयोहानौ (प)।
	जरायाम्—वो।	

ग—जिनाति—ऋ. ५,३४,५; मै. १,६,१०; शब्रा. १३,१,५,४। ज्यास्यन्ति—काठ. २३,९।

+√ज्यु (ज्युङ्) १/९४१	गतौ (आ)	√जु (जुङ्) १/ गतौ (आ)।
काक्र×, श	क्षी-मै-सा-च-जै-कात-शा-हे।	√च्यु (च्युङ्) १/ गतौ (आ)।
	गत्याम्—वो।	√छ्यु (छ्युङ्) १/ गतौ (आ)।

ग—जुज्यूषन्ति—शब्रा. ३,२,४,१६ (=गतौ)।

√ज्युत् (ज्युतृ) १/३१ मै-सा-श-च-जै- काकृ-कात-शा ×	भासने (आ) इति कौशिकः-क्षी । क्षी-हे । द्युत्याम्—वो ।	<√जुत् (जुतृ) भासने (आ) । √द्युत् (द्युत) १/दीप्तौ (आ) । √युत् (युतृ)१/भासने (आ) । ज्योतते-निघ. १/१६= ज्वलतिकर्मा । √ज्युत् १/४०५ विभासे (प) जै ।

ग—ज्योतताम्-मै. २,१२,४ । अवज्योतयति-शत्रा. ११,६,१,१० ।

छ—√जोयना * † (<ज्योतनम्)=द्युतौ, ज्वलने-"चौसठ दीवा जोय के" -कबीरदासः ।

छ—जोयसी * † (<ज्योतिषी) ।

+√ज्यो १/६०४ मै-सा-श-च-जै- काकृ-कात-शा-हे ×	उपनयननियमव्रतादेशेषु (आ) क्षी । नियमव्रतादेशोपनीतिषु—वो ।

√त्रि १/९३२ श-काकृ-कात ×	अभिभवे (प) इति दुर्गः—क्षी । क्षी-मै-सा-च-जै-सा-हे-वो । गतौ—ह्वि. ।	<√जृ अभिभवे (प) ज्रयति-निघ. २/१४- गतिकर्मा ।

ग—ज्रयति-ऋ. ९,७१,५ । ज्रयसानस्य-१०,११५,४ ।

√ज्वर् (ज्वर) १/७६९ श ×	रोगे (प) मित् क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो । औष्ण्ये—ह्वि. ।

ग—ज्वरम्-खिसा. २९,४२ । अप्रिये न स संज्वरेत्-मभार. ३,१३७४३ ।

छ—जुर (<ज्वरः) बुं. ख. ।

छ—जूड़ी (<जूर्तिः)=शीतज्वरः ।

√ज्वल् (ज्वल) १/७९७ श ×	दीप्तौ (प) मित् क्षी-मै-सा-च-जै-काकृ- कात-शा-हे । चलत्विषोः—वो ।	√ज्वल् १०/२४४ प्रकाशने (प) काकृ । √ज्वर् (ज्वर) १/ रोगे (प) ।

ज्वलह्वलह्मलनमामनु-
पसर्गाद्वा १/८०३
श-जै-शा हे-वो×

ग—ज्वलति-तै. ५,४,१,३; गोब्रा. १,२,२०; तैआ. १०,१,१५। ज्वलयन्ति-आर्षे. ७ : ४ ।

ङ—√जल (अक)=(१) ज्वलने, (२) दीप्तौ। जलइ-महा.।
ङ—√वल=ज्वलने। 'बलवुं'-गुर्जरभा.।

√ज्वल् (ज्वल) १/८१५ दीप्तौ (प)
श×
क्षी-मै-सा-च-जै-काकृ-कात।
चलने—च।
चलने दीप्तौ च—शा-हे।
चलत्विषोः—वो।

√ज्वर् (ज्वर) १/ रोगे (प)।
√ज्वल १०/२४४ प्रकाशने (प)।

ग—ज्वलति-पूर्ववत्। ज्वालयते, ज्वालयति-नृपू. २,११। ज्वालय-ज्वालय-लाङ्गूलोपनि. २१४ : १८।

ङ—√जाल (सक)=दहने-महा.।
ङ—√जालाव (सक)=दहने। वकृ-जालावंत-महानि. ७।
छ—√बालना (<ज्वालनम्। जलोपे) प्रकाशने।

√झट् (झट) १/३०२ संघाते (प)
काकृ×,श
क्षी-मै-सा-च-जै-कात-शा-हे।
संहतौ—वो।
संभ्रमे, व्याकुलतायाम्—ह्वि.।

√जट् (जट) १/३०१ संघाते (प)।

ग—झटिति-कात्या. श्रौ. १,५,७। यत्रोज्झटितास्तेन म्लेच्छाः-राजत. १,११६।
छ—√झटकना=सहसापहरणे।
छ—झाड़, झाड़ी।

+√झम् (झमु) १/४६७ अदने (प)
जै×,श
क्षी-मै-सा-च-काकृ-कात-हे।
भक्षे—वो।

द्रष्ट.√जम् १/४६७।

√चम्>√छम्>√जम्>√झम्>√झिम्-काकृ १/२२१f इति स्याद् विकासक्रमः।

+√झर्च् (झर्च) १/७०९ परिभाषणे (प)
मै-सा-श-च-जै-काक्र-कात-शा-हे-वो× इत्यपरे—क्षी क्षी ।

<√झर्झ् (झर्झ) परिभाषणे (प) ।
√चर्च् (चर्च) १/ परिभाषणे (प) ।
√झर्छ् (झर्छ) १/ परिभाषणे (प) ।

किमत्र सत्यम् ! देवा ज्ञास्यन्ति—क्षी ।

+√झर्च् (झर्च) ६/२० परिभाषणसंतर्जनयोः (प) पूर्ववत् ।
क्षी-च-जै-काक्र-कात ×, श् मै-शा-हे ।
परिभाषणभर्त्सनयोः—सा ।
उक्तौ भर्त्से—वो ।

+√झर्छ् (झर्छ) १/७०९ परिभाषणे (प)
मै-सा-श-च-जै-काक्र-कात-हे-वो× क्षी ।

>√झर्च् (झर्च) परिभाषणे (प) ।
√झर्छ् (झर्छ) ६/ भर्त्सोक्त्योः (प) वो ।
पूर्ववत् ।

किमत्र सत्यम् ! देवा ज्ञास्यन्ति—क्षी ।

+√झर्झ् (झर्झ) १/७१० परिभाषणे (प) द्रष्ट. √जर्ज् ६/१९ ।
श-हे-वो× क्षी-च ।
परिभाषणसंतर्जनयोः—मै ।
परिभाषणहिंसातर्जनेषु—सा-जै-शा ।
परिभाषणर्जनयोः—काक्र-कात ।

ङ—झज्झरी = परस्पर्शवारणाय चण्डालयष्टिः ।
छ—झर्झर = वाद्यविशेषः (परिभाषणे), हिरण्याक्षपुत्रनाम ।
छ—झँझोड़ना (<झर्झनम्) = क्षोभणे, सरभसं कम्पने ।

+√झर्झ् (झर्झ) ६/२० परिभाषणे (प) पूर्ववत् ।
श-शा× क्षी-च-जै-हे ।
परिभाषणसंतर्जनयोः—मै ।
परिभाषणभर्त्सनयोः—सा ।
परिभाषणतर्जनयोः—काक्र-कात ।
तर्जने—हे ।
भर्त्सोक्त्योः—वो ।

ग—झर्झरी-हरिवंश. २३७,२ =वाद्यम्। यावत्-झर्झती, झर्झन्ती-प्रभृति-रूपाणि नोपलभ्यन्ते तावदयं न शक्यते स्वीकर्तुम्।

छ—पूर्ववत्।

छ—√झगरना
छ—√झगड़ना } (<झझरना <झर्झनम्)=भर्त्सनादौ।

+√झष् (झष) १/६७९ हिंसार्थः (प)
शX
क्षी-मै-सा-कात।
हिंसायाम्—च-जै-
काक्ृ-शा-हे।
वधे—वो।

√जष् (जष) १/ हिंसार्थः (प)।
√शष् (शष) १/ हिंसार्थः (प)।
√जस् १/ हिंसायाम् (प)।
√यूष् (यूष) १/ हिंसायाम् (प)।

षष्ठस्वरी चायमिति केचित्-झूषति-दुर्गादा.।

ङ—√झूस (सक)=क्षीणे, संतापे, विनाशे। संक्रु-झूसेत्ता-अंत. २७।

+√झष् (झष) १/८७७ आदानसंवरणयोः (उ)
श-काक्ृ-कातX
क्षी-मै-सा-हे।
आदाने—च।
संवरणे आदाने च—जै-शा।
ग्रहेऽपिधाने—वो।

पूर्ववत्।

ग—लीनमीनझषग्राहाम्-वा. रा. २,१४४,४—झषः=मकरः। झषाणां मकरश्चास्मि—गी. १०,३१।

ङ—√झोस (सक)=आवरणे, प्रक्षेपणे-वव. १।

+√झॄ (झॄष्) ४/२३ वयोहानौ (प)
श
क्षी-मै-सा-जै-कात-शा।
जरायाम्—च।
जरसि—हे।
ज्याने—वो।
(काकृ√कॄ[कॄष्]) वयोहानौ—काकृ।
लैपिकी त्रुटिः।
झॄष् इत्युचितम्।

√च ९/ वयोहानौ (प) मै।
√जॄ (जॄष्) ४/ वयोहानौ (प)।

ग—झरः=समूहो निर्झरो वा। यथा नैषधे–प्रभाझरचक्रभ्रमिम्–२,३२।

छ—√उझलना
छ—√उझालना †
छ—√उझिलना †
} (<उज्झरणम्)=अवपातने, उच्चस्थानाद् द्रव-पदार्थस्य पातने।

√झ्यु (झ्युङ्) १/९६३ क्षी-सा-जै-काकृ-कात-शा-हे-वो×,(श)	गतौ (आ) मै। मै-च।	द्रष्ट. √ज्यु १/९४१। √झु १/५५२d गतौ (आ) काकृ।
√टल् (टल) १/८१८ श×	वैक्लव्ये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। विप्लवे—वो। 'विक्लवे' इति भाष्यम्।	√ट्वल् (ट्वल) १/ वैक्लव्ये (प)। √टल (टल) १/२५० x अदने (प) काकृ। √टल्ल् १/२५०y अदने (प) काकृ।

ह्विट्नीः 'टलति' इत्युदाहरणं प्रस्तौति। मया नाधिगतम्।

छ—√टरना
छ—√टलना
} (<टलनम्) १ अपसृतौ, (२) अनुपस्थितौ, स्थगने, (३) अन्यथाभावे, उचितनिश्चयाभावे। इदं कातर्यम्। विक्लवः=कातरः। द्रष्ट.—√क्रन्द् १/७६६।

सद्दनीति ग्रन्थे ८१० 'टल्' धातोः 'विलम्बे'-अर्थो विद्यते। स समीचीनो भाति।

छ—ठाल, ठाला=निष्क्रियता, व्यवसायराहित्यम्, (२) अवकाशः।

छ—√टालना
छ—√टारना
} =अपसारणे।

छ—अटल (<अ+टलः)=स्थिरः।

+√टिक् (टिक्) १/१०० श-जै-शा×	गत्यर्थः (आ) क्षी-मै-सा-च-कात। गतौ—काकृ-हे। गत्याम्—वो।	√टीक् (टीकृ) १/ गत्यर्थः (आ) <टीक <टीकम < त्रिकम <त्रिविक्रम-(अभि. अनु., १४३ पृ.)। टिक<टिकम< त्रिक्रम< त्रिविक्रम (अ. अ., १४३ पृ.)

√टिक् १/७० गतौ (आ)
जै, शा ४२p, हे ६३३।
√तिक् (तिक्ृ) १/ गत्यर्थः
(आ) सा।

छ—अटकना (<अ+टेकनम्)=विस्मरणे, गतिरोधे।

√टीक् (टीकृ) १/१०१ गत्यर्थः (आ)
श
क्षी-मै-सा-च-कात।
गतौ—जै-काकृ-शा-हे।
गत्याम्—वो।

√तीक् (तीकृ) १/ गत्यर्थः
(आ) सा।
शेषः पूर्ववत्।

ग—टीकमानैः-यशस्तिल. च., ३ आ., ३७२ पृ.=सञ्चरद्भिः।
छ—√टीकना=तिलकाद्यङ्कने।

+√टौक् (टौकृ) १/९५ गत्यर्थः (आ) इति
मै-सा-श-च-जै-काकृ-कात-शा-हे-वो× दुर्गः—क्षी।
क्षी।

<√त्रौक् (त्रौकृ) गत्यर्थः
(आ)।
√ढौक् (ढौकृ) १/
गत्यर्थः (आ)।

ङ—टोक्कग=मद्यमापनपात्रम्-दे. ४,४।
छ—√टोकना=(१) अवरोधे, (२) कुदृष्टौ, (३) मल्लानामाह्वाने।

+√ट्वल् (ट्वल) १/८१९ वैक्लव्ये (प)
श×
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
विप्लवे—वो।

√टल् (टल) १/ वैक्लव्ये
(प)।
√टु १/५५२g गतौ (आ)
काकृ।
√ठु १/५५२h गतौ (आ)
काकृ।

ङ—टोलगइ (<ट्वलगतिः)=गुरुवन्दने दोषविशेषः-पव. २।
छ—(टाल) टूल=व्याजः, विक्लवः। सद्दनीतिग्रन्थे ८११ धातोरस्य 'विलम्बे' इत्यर्थो दृश्यते। सः समीचीनो भाति।

+√डिप् (डिप) ४/११८ क्षेपे (प)।
श
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
नुदि—वो।

√तिप् (तिप) १०/ क्षेपे
(प)।
√टिप् (टिप) १०/ क्षेपे
(प)।

√स्तिप् (स्तिप) १०/ क्षेपे (प) ।
√डिप् (डिप) ६/९१ क्षेपे (प) ।

ङ—डिंफिअ = जलपतितम्, जलक्षिप्तम्–दे. ४,९ ।

+√डिप् (डिप) ६/९१ क्षेपे (प) ।
श, (जै) ।
क्षी-मै-सा-च-जै-काकृ- पूर्ववत् ।
कात-शा-हे ।
क्षेपणे—जै ।
नुदि—वो ।

ङ—√डिव (सक) = उल्लंघने । डिंव–वव. १ ।
ङ—डेवण = उल्लंघनम्–ओघ. ।

?√डी (डीङ्) १/९५३ विहायसां गतौ (आ) ।
श
क्षी-(यु.मी.सं.), कात-शा-हे ।
विहायसा गतौ—मै-सा-जै-काकृ ।
गतौ—क्षी-च ।
नभोगतौ—वो ।

√डी (डीङ्) ४/२७ गतौ (आ) ।
श
क्षी-च-जै-कात-शा-हे-वो ।
विहायसा गतौ—मै-सा ।
√डी (डीङ्) १/९५३ गतौ (आ) ।
दीयते (डीयते)—निघ. २/१४ गतिकर्मा ।

डीनशब्दं विहायान्ये शब्दा अप्राप्याः–ह्वि. ।
ग—अतिडीन०, अभिडीन०–मभार. ८,१९०० ।
घ—डेति–दीघ. १७१; अंगुत्तर. २,२०९ । उड्डेति–मज्झिम. १,३६४ ।
ङ—डीण = अवतीर्णम्–दे. ४,१० ।
छ—√उड़ना (<उड्डयनम्) ।

√ढौकृ (ढौकृ) १/९४ गत्यर्थः (आ) ।
श
क्षी-मै-सा-च-कात ।
गतौ—जै-काकृ-शा-हे ।
गत्याम्—वो ।
√त्रौकृ (त्रौकृ) १/ गत्यर्थः (आ) ।
√टौकृ (टौकृ) १/ गत्यर्थः (आ) ।

ग—तैः क्षणादाशु ढौकितम्–मभार. १२,४१८१। तस्मै पात्रीमढौकयत्–कथासरि. १६,३९। उपढौकयन्ति–कात्या. श्रौ. ७,२,२=उपहरन्ति। वक्त्रं ढौकते–शाकु. ३,३७ श्लोकतः परवर्ति गद्यम्=अन्यत्र चालयति। अढौकि–नैष. १६,१०१ =अर्पिता (प्रका.)।

ङ—√ढुक्क (सक)=उपहारे, (२) उपस्थितौ, (३) प्रवृत्तौ, (४) साक्षात्कृतौ। वक्क–ढुक्कंत–पिंग.।

ङ—√ढोअ (सक)=उपहारे, (२) उपस्थितौ, (३) प्रवृत्तौ, (४) साक्षात्कृतौ। ढोएज्जह–महा.।

छ—√ढूँकना=प्रवेशे।
छ—√ढूँकना=कुब्जीभावे, आर्जवे।

+√तंस् (तसि) १/६७३ मै-सा-श-च-जै-शा×	अलङ्कारे (प) इति दुर्गः—क्षी। क्षी-काक्र-कात-हे। अलङ्कृतौ—वो। कम्पे—ह्वि.।	√तंस् (तसि) १०/ अलङ्कारे (प)। इति दुर्गः—क्षी। √तंस (तसि) १०/३८५ अलङ्कारे (प)।

ग—[ततस्त्रे ?–ऋ. ४,२३,५। अतंसयत्–मा. २३,२४; तै. ७,४,१९,४]। नोत्तंसं क्षिपति क्षितौ श्रवणतः–सा. द. १३,८। चूडोत्तंसति–भर्तृह. ३,१।
ङ—उत्तंस=कर्णाभरणम्–पाअ.; शिरोभूषणम्–गउड.।
ङ—अवतंसिय (<अवतंसितम्)=विभूषितम्–कुमा.।
ङ—अवयंस=शिरोभूषणविशेषः–कुमा., गा. १७३।

मैत्रेयसायणौ चुरादौ पठतो न भ्वादौ। क्षीरस्वामी तूभयत्र दुर्गमुद्धरति। संस्कृते प्राकृते च सोपसर्गोत्तंसावतंसशब्दौ प्राप्येते।

√तक् (तक) १/११६ श×	हसने (प)। क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। सहने हासे—वो। सहने इति दुर्गः—क्षी, हे। द्रुतगतौ—ह्वि.।	√तक्क् १/३२b हसने (प) काक्र। तकति–निघण्टौ–२/१४=गतिकर्मा। शकुनिः,–शक्नोति तकितुमिति वा–निरु. ९,३,२। तकितुम्=गन्तुम्—दुर्गाचा.।

ग—तक्ति-ऋ. ९,१६, १; तकवानस्य १,१२०,६; तकन्तीः—पै. १२,७,३। वेदे लोके चार्थपार्थक्यम्।

√तक्षू (तक्षू) १/६४६ श×	तनूकरणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। कार्श्ये, तक्षे—वो। विधाने, निर्माणे—ह्वि.।	√तङ्क् (तकि) १/ कृच्छ्रजीवने (प)। √तक् (तक) १/ सहने (प)।

ग—अश्वयूपाय तक्षति-ऋ. १,१६२,६। तक्षति-तै. ४,६,८,२; मै. ३,१६,१। अपतक्ष्णुवन्ति-शब्रा. ३,७,१,८।

ङ—√तक्ख (सक)=तनूकरणे। कर्मणि-तक्खिज्जइ-कुप्र. १७। वकृ-तक्खमाण-अणु.।

ङ—√तच्छ (सक)=तनूकरणे। संकृ-तच्छिय-सूअ. १,४,१। कवकृ-तच्छिज्जंत-सुर. १,२८।

+√तक्षू (तक्ष) १/६६७ क्षी-श-च-शा-हे×	त्वचने (प) मै। मै-सा-जै-काकृ-कात। त्वचि ग्राहे—वो। त्वचनम् = संवरणम्—मै।	√तक्षू (तक्षू) १/ तनूकरणे (प)।

+√तङ्क् (तकि) १/११७ क्षी-श×	कृच्छ्रजीवने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। दौस्थ्ये—वो।	√तञ्च् (तन्चू) ७/ सङ्कोचने (प) इति द्रमिडाः—क्षी।

ग—दृष्ट्वा पथि निरातङ्कम्-याज्ञवल्क्य. ३,२४५। निरातङ्काः-रघु. १,६३।
छ—तंगी (फार.)=दुःखम्, कष्टम्।
छ—तँगाना=पीडने, कष्टे।
छ—तँगना=पीडने (अक)।

+√तङ्ग् (तगि) १/१४८ श-जै-काकृ-कात-शा×	गत्यर्थः (प) क्षी-मै-सा-च। गतौ—हे। गते स्खलने च—वो। तगिः-स्खलने रूढः-क्षी।	√त्वङ्ग् (त्वगि) १/ गत्यर्थः (प)।

क—स्तेउ=प्रेरणे, अपनोदे, प्रापणे, ताडने, स्फुरणे। स्तेउ-क्, स्तेउ-ग्-*स्तेइग्-*स्तिग्—:किश्रिक्-संगु=गमने-वा. पॉकर्नीः।

ग—किराततङ्गणाकीर्णम्-मभार. ३,१४०,२४।

+√तञ्च् (तन्चु) १/१८८ श. कात×	गत्यर्थः (प) क्षी-मै-सा-च। गतौ—जै-काक्ट-शा-हे इतौ—वो।	√तन् (तनु) ८/ विस्तारे (उ)। √तञ्ज् (तन्जू) ७/सङ्कोचने (प)। √तञ्च् (तन्चू) ७/ सङ्कोचने (प) इति द्रमिडाः। √त्वञ्च् (त्वन्चु) १/ गत्यर्थः (प)।
√तञ्च् (तन्चू) ७/२२ श	सङ्कोचने (प) इति द्रमिडाः-क्षी क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे। सङ्कुचि—वो।	<√तञ्ज् (तन्जू) सङ्कोचने (प)। शेषः पूर्ववत्।

ग—सोमेनातनच्मि-वा. सं. १,४; तै. २,५,३,५। आतनक्ति (दुग्धं दध्ना)-कात्या. श्रौ. ४,३,२३।

+√तञ्ज् (तन्जू) ७/२२ मै-श-च-जै-काक्ट-कात-शा×	सङ्कोचने (प) क्षी-सा-हे। सङ्कोचे—वो।	>√तञ्च् (तन्चू) सङ्कोचने (प)।
√तट् (तट) १/३०४ श	उच्छ्राये (प) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे-वो। तटतटाशब्दे—ह्वि.।	√तड् (तड) १०/ आघाते (प)।

ग—तटति-षम्रा. ५,७। यदास्य पृथिवी तटति (=तटतटेति शब्दं करोति)-अद्भु. ब्रा. १,४०। ह्विटनीः प्रथममुदाहरणं नोपलब्धवान्।

घ—तड=तटम्-कुमा.।

छ—तड़ (<तटम्)=समाजविभागः, पक्षः, (२) स्थलम्।

+√तण्ड् (तडि) १.२७८ श-कात×	ताडने (आ) क्षी-मै-सा-च-जै-शा-हे तोडने—काकृ। त्विषि आहतौ च—वो	√तड् (तड) १०/ आघाते (प)। √तण्ड् १/१७९ समूहे (प) काकृ। तन्दते—ऋ. १,१३८,१ (= त्यागे, श्रान्तौ, नैर्बल्ये)

ग—तण्डुलः कणः-अ. वे. १०,९,२६। तण्डिः=महाभारतवर्णित ऋषि—शान्ति. २४४,१७।

ङ—तंड=खलीनलग्ना लाला, (२) मस्तकहीनः (वि.), (३) स्वरादधिकम्—दे. ५,१९।

√तन् (तनु) ८/१ श	विस्तारे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। विस्तृतौ—वो।	√तन् (तनु) १०/श्रद्धोपकरणयोः (प)। √ताय् (तायृ) १/ सन्तानपालनयोः (आ)।

क—तॆन्—, तॆन्द्—,=विस्तारे, कर्षणे। लैति. तॆन्दॉ, तॆतॆन्दि=कनिष्ठः, पश्चाद्वर्ती। पु. च. स्ला. तॆनॆतॉ, तॊनॉतॉ =रज्जुः—जू. पॉकर्नीः।

ग—ततनन्-ऋ. ७,८८,४; पै. १७,२५,५। तनुते-ऋ. १,१०१,७; तै. १,६,८,४।

छ—√तनना=विस्तारे।

√तप् (तप) १/९७० श	संतापे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। दवैश्ययोः—वो।	√तप् (तप) ४/ ऐश्वर्ये (आ)। √पत् (पत) ४/ ऐश्वर्ये (आ) इति द्रविडाः-क्षी। निपत्यते—निघ. २/२१= ऐश्वर्यकर्मा।

वा ग्रहणाद् ऐश्वर्येऽपि भ्वादिरित्येके-क्षी।

ग—तपति-ऋ. २,२४,९; मै. १,१०,१४।

ङ—√तव=तापे। तवइ-गा. २२४।

छ—√तवना*† =तपने।

छ—√तपना=तपने।

छ—√तचना† =तपने।

छ—√तयना*† =तपने।

√तप् (तप) ४/४८ श	ऐश्वर्ये [वा] (आ) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे । द्वैश्ययोः—वो ।	√तप् (तप) १/ द्वैश्ययोः (प) वो । √तप् (तप) १०/ दाहे (प) ।

ग—तपस्तप्यामहे—अ. वे. ७,६१,२। सोऽतप्यत तपो घोरम्–वा. रा. १,५८,१ ।
ङ—√तप्प=तपश्चर्यायाम्, (२) औष्ण्ये । तप्पइ–पिंग.; प्रासू. ५३ ।

√तम् (तमु) ४/८९ श	काङ्क्षायाम्, (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे । खेदेच्छयोः—वो ।	√दम् (दमु) ४/ उपशमे (प)। √तम्ब् १/२०६d मर्दने (प) काकृ ।

ग—ताम्यति–तैब्रा. १,४,४,२ ।
ङ—√तम्म (अक)=खेदे । तम्मइ–गा. ४८३ ।

+√तय् (तय) १/४७५ श ×	गतौ (आ) क्षी-मै-सा-च-काकृ-कात । 'रक्षणे च' इत्येके—सा । गतौ रक्षायां च—शा-हे । गतौ रक्षणे च—शा-हे । गतिरक्षणयोः—वो	√ताय् (तायृ) १/ सन्तान- पालनयोः (आ)। √त्रै (त्रैङ्) १/ पालने (आ)। √दे (देङ्) १/ रक्षणे (आ)। √दय् (दय) १/ दानगति- रक्षणहिंसादानेषु (आ)।

छ—तय (अर.)=(१) समाप्तम्, (२) निश्चितम् ।

+√तय् (तय) १/४७७ मै-सा-श-च-जै-काकृ- कात-शा-हे-वो ×	रक्षणे, च=गतौ (आ) क्षी ।	पूर्ववत् ।

पूर्वस्मादभिन्नः क्षीरेणैव पृथक् संख्यातः ।
ङ—ताइ (<तायिन्)=रक्षकः, पालकः–उत्त. ८ ।

√तर्ज् (तर्ज) १/२२२ श-जै ×	भर्त्सने (प) क्षी-मै-सा-च-काकृ-कात- शा-हे । वाग्भर्त्सयोः—वो ।	√तर्ज् १/६७ व्यथने (प) काकृ । √तर्ज् (तर्ज) १०/ संतर्जने (प)।

२९

√चर्च् (चर्च) परिभाषण-भर्त्सनयोः (प) सा ।
√जर्च् (जर्च) परिभाषण-संतर्जनयोः (प) मै ।
√जर्ज् (जर्ज) ६/ परिभाषण-भर्त्सनयोः (प) सा ।

ग—तर्जद्भिरिव वानरैः–वा.रा. २,९६,२६ । गदया तर्जमानः–मभार. ६,३७८५ ।

ङ—√तज्ज (सक) = भर्त्सने । तज्जइ–भवि. ।

छ—√तर्जना
छ—√तरजना } =भर्त्सने ।

+√तर्द् (तर्द) १/५६ श × हिंसायाम् (प) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे । हिंसे—वो । √तृद् (उत्तृदिर्) ७/ हिंसानादरयोः (प) ।

ग—ततर्द—तैब्रा. २,५,४,२ । रूपमिदं रुधादावपि शक्यते साधयितुम् ।

+√तस् (तसु) ४/९९ उपक्षये (प) क्षी-मै-सा-कात-शा-हे-वो । उपक्षेपे—च-काक्ट । क्षये—जै । √दस् (दसु) ४/ उपक्षये (प) ।

क—तेंस्=विस्तारे—वा. पॉकर्नीः ।

ख—अवे. वितस्ति=विस्तारः, वितस्तिः—वा. पॉकर्नीः । 'उपक्षेपे'—इत्यनेन सङ्गतम् ।

ग—सामानि चक्रुस्तसराण्योतवे—ऋ. १०,१३०,२; वा. सं. १९,८३ । तायुरिति स्तेननाम । तस्यतेर्वा स्यात्–निरु. ४,२४,१=क्षयार्थस्य । उपक्षीणो ह्यसौ भवति, अधार्मिकत्वात्—दुर्गाचार्यः ।

ङ—टसर=विमोटनम्–दे. ४,१ ।

छ—टसरा=वस्त्राद्युपक्षये, दीर्णतायाम् (मसक जाना, दरकना–हि.) ।

√ताय् (तायृ) १/४८६ श × सन्तानपालनयोः (आ) क्षी-मै-सा-जै-काक्ट-कात-शा-हे । सन्ताने—च । √तय् (तय) १/ रक्षणे च=गतौ (प) । √त्रै (त्रैङ्) १/ पालने (आ) ।

पालनसन्तत्योः--वो। √दय् (दय) १/ दानगति-रक्षणहिंसादानेषु (आ)।
√दे (देङ्) १/ रक्षणे (आ)।

ग—शरसि संताय्यमाने–वा. सं. ३९.५।

ङ—√ताअ (सक्र)=रक्षणे। कृ.–तायव्व–श्रा. १२।

+√तिक् (तिक्) १/१०२ क्षी-श-च-जै-शा ×	गत्यर्थः (आ) मै·सा-कात। गतौ—काक्-हे। गत्याम्--वो।	√तीक् (तीक्) १/१०४ गत्यर्थः (आ) सा। द्रष्ट. √टिक् १/१००।
+√तिक् (तिक) ५/२० श	च=आस्कन्दने (प) क्षी-मै-सा-हे। हिंसायाम्--च-शा-हे। जिघांसायाम्--काक्-कात। आस्कन्दे वधे--वो। गतौ, च=आस्कन्दने-सि. कौ.।	√तिग् (तिग) ५/२१ आस्कन्दने (प)। √तिक् (तिक्) १/ गत्यर्थः (प)। √स्तिघ् (ष्टिघ) ५/ आस्कन्दने (प)।

ङ—थेग=कन्द विशेषः–श्रा. २०; जी. ९।

छ—√तेखना*†=(<तेकनम्, तीक्ष्णम् इत्यपि स्यात्)=क्रोधे। क्रोधोऽपि हिंसा, तत्परिणामेन तथा सत्त्वात्।

+√तिग् (तिग) ५/२१ च×, श	च=आस्कन्दने (प) क्षी-मै-सा-हे। हिंसायाम्--जै-शा-हे। जिघांसायाम्--काक्-कात। हिंसास्कन्दयोः—वो।	>√तिघ् (तिघ) हिंसायाम् (प) इत्येके–क्षी। √तिक्ष् ५/१७d जिघांसायाम् (प) काक्। √तीक्ष् ५/१७e जिघांसायाम् (प) काक्।

ङ—थिग्गल=भित्तिद्वारम्–दस. ५,१,१५; (२) स्फटितवस्त्रसन्धानम्,–पण्ण. १७; विसे. १४३९ टी.।

√तिज् (तिज) १/९५६ श (?)	निशाने क्षमायां च (आ) क्षी-मै । निशाने—सा-च । क्षमायाम्—सा । क्षमानिशानयोः—जै-शा-हे । निशातने—काकृ । शातने क्षमायां च—कात । शीते क्षान्तौ च—वो ।	√तिज् (तिज) १०/ निशाने (प) । √तेज् (तेज) १/ पालने (प) ।
√तितिक्ष् ...	शातने क्षमायां च—काकृ ।	

ग—तेजते-ऋ. १०,१३८,५ । तेजमानः-शत्रा. ३,६,४,१४ । तितिक्षते-शत्रा. ३,१,२,१५ ।

ङ—√तिइक्ख (सक) = मर्षणे । तिइक्खए-आचा. ।

छ—√टेना (<तेजनम्)-निशाने—"कपट छुरी उर पाहन टेई"-तुलसी. ।

+√तिप् (तिपृ) १/३५७ श×	क्षरणार्थः (आ) क्षी-मै-सा-च-कात । स्रुतौ—जै । श्च्युतौ—वो । क्षरणे—काकृ-शा-हे ।	√स्तिप् (ष्टिप) १/ क्षरणार्थः (आ) । √तेप् (तेपृ) १/ क्षरणार्थः (आ) । √स्तेप् (ष्टेपृ) १/ क्षरणार्थः (आ) ।

ङ—√तिप्प (अक)=(१) क्षरणे, (२) पश्चात्तापे, (३) रोदने, (४) [सक] सुखच्युतौ । तिप्पामि-सूअ. २,१; २; २,५५ । तिप्पणया=अश्रुविमोचनम्-ठा. ४,१; औप. ।

√तिम् (तिम) ४/१५ श	आर्द्रीभावे (प) क्षी-मै-सा । आर्द्रभावे—च-जै-काकृ-कात-शा-हे । क्लेदने—वो ।	√तीम् (तीम) ४/ आर्द्रीभावे (प) । √स्तीम् (ष्टीम)४/ आर्द्रीभावे (प) । √स्तिम् (ष्टिम) ४/ आर्द्रीभावे (प) ।

ग—तिमिताश्चाभवन् सर्वे-वा. रा. ५,१,२६ । वृष्टिर्बभूव, वानरांस्तिम्यतोऽवलोक्य-हितो. ७९,५ ।

ङ—√तिम्म (सक)=(१) आर्द्रीभावे, (२) [अक] आर्द्रत्वे। संक्—तिम्मेउं-पिंड. ३५० ।

छ—√तिमाना †=आर्द्रीभावे ।

+√तिल् (तिल) १/५३४ शा-च-जै-शा ×   गतौ (प) इत्यपि दुर्गः क्षी-मै-सा-काकृ-कात-हे-वो ।   <√तिल्ल् (तिल्ल) गतौ(प)।

छ—√ठिलना=प्रवेशे-"ठिले दीह दल पुहुमि हिलाई"-लाल. ।

छ—ठेलना (प्रे.)=प्रवेशे ।

ज—टेला=मुष्टिप्रसारणे (कस्यचन वस्तुन आदानाय)।

+√तिल् (तिल) ६/७५ श   स्नेहने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । स्निहि—वो ।   √तिल् (तिल) १०/ स्नेहने (प)।

ग—प्रतिलामि-वा.सं. २३,२४=स्निह्यामि[महीध.]। भ्रमात्मकमध्ययनम्-ह्वि. । तिलम्-साब्रा. १,८,१० । तिलाः-तांब्रा. १६,१,१०; शब्रा. ९,११,३ । तिलस्य-गोब्रा. २,१,१७ ।

+√तिल्ल् (तिल्ल) १/५३४ मै-श-च-कात ×   गतौ (प) क्षी-सा-जै-काकृ-शा-हे-वो ।   >√तिल (तिल) गतौ (प)।

ङ—थिल्लि=यानविशेषः-(१) अश्वद्वयवाह्यम्, (२) अश्वतरादिवाह्यम्-सूअ. २,२,६२; णाया. १,१ टी.-पत्र. ४३; औप. ।

छ—तिल्लर=चटकाविशेषः (देश.)।

+√तीम् (तीम) ४/१६ मै-श-च-जै-काकृ-कात-शा ×   आर्द्रीभावे (प) क्षी-सा । आर्द्रभावे—हे । क्लेदने—वो ।   द्रष्ट. √तिम् ४/१५ । √तेम् १/२६३ d रुजायाम् (प) काकृ ।

ङ—तीमिअ (<तीमितम्)=आर्द्रम्-कुप्र. ३७३ ।

ङ—तीमन=कढ्वरी (>कढ़ी-हि.)-सण.; दे. २,३५ ।

√तिज् (तिज) १/९५६ श (?)	निशाने क्षमायां च (आ) क्षी-मै । निशाने—सा-च । क्षमायाम्—सा । क्षमानिशानयोः—जै-शा-हे । निशातने—काकृ । शातने क्षमायां च—कात । शीते क्षान्तौ च—वो । शातने क्षमायां च—काकृ ।	√तिज् (तिज) १०/ निशाने (प) । √तेज् (तेज) १/ पालने (प) ।
√तितिक्ष् ...		

ग—तेजते-ऋ. १०,१३८,५ । तेजमानः-शब्रा. ३,६,४,१४ । तितिक्षते-शब्रा. ३,१,२,१५ ।

ङ—√तिइक्ख (सक) = मर्षणे । तिइक्खए-आचा. ।

छ—√टेना (<तेजनम्)-निशाने—"कपट छुरी उर पाहन टेई"-तुलसी. ।

+√तिप् (तिपृ) १/३५७ श×	क्षरणार्थः (आ) क्षी-मै-सा-च-कात । स्रुतौ—जै । श्च्युतौ—वो । क्षरणे—काकृ-शा-हे ।	√स्तिप् (ष्टिप) १/ क्षरणार्थः (आ) । √तेप् (तेपृ) १/ क्षरणार्थः (आ) । √स्तेप् (ष्टेपृ) १/ क्षरणार्थः (आ) ।

ङ—√तिप्प (अक) = (१) क्षरणे, (२) पश्चात्तापे, (३) रोदने, (४) [सक] सुखच्युतौ । तिप्पामि-सूअ. २,१; २; २,५५ । तिप्पणया = अश्रुविमोचनम्-ठा. ४,१; औप. ।

√तिम् (तिम) ४/१५ श	आर्द्रीभावे (प) क्षी-मै-सा । आर्द्रभावे—च-जै-काकृ-कात-शा-हे । क्लेदने—वो ।	√तीम् (तीम) ४/ आर्द्रीभावे (प) । √स्तीम् (ष्टीम) ४/ आर्द्रीभावे (प) । √स्तिम् (ष्टिम) ४/ आर्द्रीभावे (प) ।

ग—तिमिताश्चाभवन् सर्वे-वा. रा. ५,१,२६ । वृष्टिर्बभूव, वानरांस्तिम्यतोऽवलोक्य-हितो. ७९,५ ।

ङ—√तिम्म (सक)=(१) आर्द्रीभावे, (२) [अक] आर्द्रत्वे। संक्ष-तिम्मेउं-पिंड. ३५०।

छ—√तिमाना †=आर्द्रीभावे।

+√तिल् (तिल) १/५३४ श-च-जै-शा×
गतौ (प) इत्यपि दुर्गः क्षी-मै-सा-काकृ-कात-हे-वो।
<√तिल्ल् (तिल्ल) गतौ(प)।

छ—√ठिलना=प्रवेशे-"ठिले दीह दल पुहुमि हिलाई"-लाल.।
छ—ठेलना (प्रे.)=प्रवेशे।
ज—टेला=मुष्टिप्रसारणे (कस्यचन वस्तुन आदानाय)।

+√तिल् (तिल) ६/७५ श
स्नेहने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। स्निहि—वो।
√तिल् (तिल) १०/ स्नेहने (प)।

ग—प्रतिलामि-वा.सं. २३,२४=स्निह्यामि[महीध.]। भ्रमात्मकमध्ययनम्-ह्वि.। तिलम्-साब्रा. १,८,१०। तिलाः-तांब्रा. १६,१,१०; शब्रा. ९,११,३। तिलस्य-गोब्रा. २,१,१७।

+√तिल्ल् (तिल्ल) १/५३४ मै-श-च-कात×
गतौ (प) क्षी-सा-जै-काकृ-शा-हे-वो।
>√तिल् (तिल) गतौ (प)।

ङ—थिल्लि=यानविशेषः-(१) अश्वद्वयवाह्यम्, (२) अश्वतरादिवाह्यम्-सूअ. २,२,६२; णाया. १,१ टी.-पत्र. ४३; औप.।

छ—तिल्लर=चटकाविशेषः (देश.)।

+√तीम् (तीम) ४/१६ मै-श-च-जै-काकृ-कात-शा×
आर्द्रीभावे (प) क्षी-सा। आर्द्रभावे—हे। क्लेदने—वो।
द्रष्ट. √तिम् ४/१५। √तेम् १/२६३ d रुजायाम् (प) काकृ।

ङ—तीमिअ (<तीमितम्)=आर्द्रम्-कुप्र. ३७३।
ङ—तीमन=कढ्वरी (>कढ़ी-हि.)-सण.; दे. २,३५।

+√तीव् (तीव) १/५६५ शX	स्थौल्ये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√नीव् (नीव) १/ स्थौल्ये (प) । धीव् १/२६० e स्थौल्ये (प) काकृ । तीव् १/२६३ b रुजायाम् (प) काकृ ।

छ—टीबा=मृत्तिकाचयः, वल्मीकम्, राशिः, चयः। गुर्जरभा.—टींबो ।

+√तीव् (तीवृ) १/८८३ क्षी-सा-श-च-जै-काकृ-कात-शा-हे-वोX	आदानसंवरणयोः (प) इति केचित्—मै ।	<√चीव् (चीवृ) आदानसंवरणयोः (उ) ।

√तु २/२४ क्षी-मै-श-च-काकृX	गतिवृद्धिहिंसासु (प) ७/३/९५ सौत्रः । बोधिन्यासे त्रिष्वपीति—सा । वृत्तिहिंसापूरणेषु—जै-कात-शा-हे । वृत्तिहिंसापूर्तिषु—वो ।	√तव् गत्याम्—सौ. धा.—वो । तविषीति बलनाम तवतेर्वा वृद्धिकर्मणः—निरु. ९,२५,१ । संतवीत्वत्-ऋ. ४,४०,४—तनोतेः पूर्वया प्रकृत्या निगमः—निरु. २,२८,१ ।

ग—तवीति-ऋ.—ह्विट्नीः । मया नोपलब्धम् । तूताव-ऋ. १,९४,२; पै. १२,१,२ । तवतेर्वृद्धिकर्मणो लिटि णलि "तुजादीनां दीर्घोऽभ्यासस्य" ६/१/७ ।

+√तुज् (तुज) १/२४० शX	हिंसायाम् (प) क्षी-मै-सा-च-काकृ-कात-शा-हे । हिंसने—जै । हिंसे—वो ।	√तु २/२४ गतिवृद्धिहिंसासु (प) । √तुञ्ज् (तुजि) १/ पालने, च = हिंसायाम् (प) । मर्म तुजन्नीशानः—ऋ. १,६१,६; तुजसे ४,२३,७ ।

छ—तुजीह=धनुः—(डिंग.) ।

√तुञ्ज् (तुजि) १/२४१ शX	हिंसायाम् (प) क्षी-मै-सा-च-काकृ-कात-शा-हे । हिंसने पालने च—जै । हिंसायां चलने च—काकृ ।	√तुञ्ज् (तुजि) १०/ हिंसाबलादाननिकेतनेषु (प) । तूतुजिः—निघ. २/१५=क्षिप्रनाम ।

हिंसायां बलने च—कात-शा। तुञ्जति—निघ. ३/२०
हिंसे—वो। दानकर्मा।
उत्तेजने, पीडने—ह्वि.।

ग—एवा त इन्दो रसानि तुञ्जन्ति-ऋ. ९,७९,५; तुञ्जते-१,१३१,२।

+√तुञ्ज् (तुजि) १/२४२, पालने, च=हिंसायाम् (प) √तुञ्ज् १/४० १वर्जने
श× क्षी-मै। (प) काक्र।
हिंसने पालने च—जै। पूर्ववत्।
हिंसायां चलने च—काक्र।
हिंसायां बलने च—कात-शा
हिंसायां बलने च—हे।
प्राणेऽवने—वो।
पूर्वसूत्रादभिन्नः क्षीरेण पृथक् संख्यायते।

ग—तुञ्जीन=कश्मीरदेशीयानामनेकेषां राज्ञां प्राचीननामानि-राजत.२,११;
३,९७=पालने।

+√तुट् (तुट) ६/९६ कलहकर्मणि (प) √त्रुट् (त्रुट) ६/ छेदने (प)।
क्षी-मै-सा-जै-काक्र- √तुड् (तुड) १/३४७ तोडने
कात-शा-हे। (प)।
कलहे—च-वो। √त्रुट् (त्रुट) १०/ छेदने (आ)।

ग—[तोटयति (प्रे.)-राजत. ६,२४८ (त्रोटयति)] तुटिः=····तन्त्रशास्त्रे ?

+√तुड् (तुड्) १/३४७ तोडने (प) इति दुर्गः-क्षी <√तूड् (तूड्) तोडने (प)।
श-जै-काक्र× क्षी-मै-सा-च-कात-शा-हे। √तुण्ड् (तुडि) १/ तोडने
वधे—वो। (आ)।
तोडनम्=द्रावणम्-क्षी। शेषः पूर्ववत्।

ङ—√तोड (सक)=तोडने। वक्र-तोडंत-भवि.। संक्र-तोडित्ता-ती. ७।
छ—√तोड़ना
छ—√तोरना† } =तोडने।

+√तुड् (तुड) ६/१०४ तोडने (प) पूर्ववत्।
श× क्षी-मै-सा-च-जै-काक्र- √तोड् १/ अनादरे (प) वो।
कात-शा-हे। √तोड् १/४२० b तोडने (प)
भेदे—वो। शा, २४६ हे।

√त्रुड् १/४४५ b त्रोडने (आ) काक्र ।
√त्रुण्ड् १/४४५ a त्रोडने (आ) काक्र ।

तोडनम् = भेदः, पृथक्करणं वा-क्षी ।

ग—सरस्वतीतुडगेन-यशस्ति. च., ३ आ., ४५२ पृ.=महाकविना । (तुडगः =मुखम्) ।

+√तुण् (तुण) ६/५२ कौटिल्ये (प)
श क्षी-मै-सा-च-जै-कात-शा-हे ।
जैह्मये—वो ।
(काक्र√तूण्)···· कौटिल्ये—काक्र ।

√तुण् १/४४ गतौ (प) काक्र ।
√द्रुण् (द्रुण) ६/ हिंसा-गतिकौटिल्येषु (प) ।
√तुल (तुल) १०/ उन्माने (प) ।
शेषः पूर्ववत् ।

ङ—तुणय = वाद्यविशेषः-दे. ५,१६ ।

+√तुण्ड् (तुडि) १/२७३ तोडने (आ)
श क्षी-मै-सा-च-जै-कात-शा-हे ।
संवरणे—च ।
काक्र ?
वधे—वो ।

शेषः पूर्ववत् ।
√तुण्ड् (तुडि) १०/१२४ छेदने (प) सा ।
आद्येषु व्याख्यानेषु न दृश्यतेऽतोऽप्रामाणिकः पाठोऽस्य—सा ।

वधः = निष्पीडनम् इति रमानाथः ।

ग—उत्तुण्डित०-सुश्रु. १,१००,१२; १,१०१,९ ।
ज—√टुण्डु = अन्ते, समाप्तौ ।

√तुद् (तुद) ६/१ व्यथने (उ)
श क्षी-मै-सा-च-जै-काक्र-कात-शा-हे ।
व्यथे—वो ।

तुन्दाना-शौ. ६,२२,३; पै. १९,२२,१२ ।

ग—कशया वा तुतोद-ऋ. १,१६२,१७; तै. ४,६,९,३ । तुदन्-शौ. २०,३०,४० ।
ङ—√तुअ (सक) = व्यथायाम् । प्रयो. संक्र.-तुयावइत्ता-ठा. ३,२ ।

+√तुप् (तुप) १/४०२ शX हिंसार्थः (प) क्षी-मै-सा-च-कात। हिंसायाम्—जै-शा-हे। भर्त्सनहिंसयोः—काक्रु। क्लिशि वधे—वो।

√तुप् (तुप) ६/ हिंसायाम् (प)।
√तुफ् (तुफ) १/ हिंसार्थः (प)।
√तुफ् (तुफ) ६/ हिंसायाम् (प)।
त्रुफ् (त्रुफ) १/ हिंसार्थः (प) इति चन्द्रः-क्षी।

छ—तोप (तुर्क.) = शतघ्नी (हिंसायाम्)।

+√तुप् (तुप) ६/३२ श-च-जै-शा-हेX हिंसायाम् (प) क्षी-मै-सा-कात। भर्त्सनहिंसयोः—काक्रु। क्लिशि वधे—वो।

√तु २/२४ गतिवृद्धिहिंसासु (प)। पूर्ववत्।

क—(स्) तॉइ-प् = आघाते। लैति.-स्तुर्पुम् = दुष्टः। पु. उ. ज. स्तॉबरोन्; आइस्. स्तौप। म. उ. ज. स्तोउफ्। लेट्टि.-स्तौंपे। सं.—प्र-स्तुम्पति-(लक्ष्यहीनम्)-वा. पॉकर्नीः।

ग—तुपति-काठ. १४,५। (तुपेजतु-पै. ७,८,४)।

+√तुफ् (तुफ) ६/३४ च-जै-शा-हे-वोX,श हिंसायाम् (प) क्षी-मै-सा-कात। भर्त्सनहिंसयोः—काक्रु।

पूर्ववत्।
√तुभ् (तुभ) ४/ हिंसायाम् (प)।
√तुह् १/३१६ k हिंसायाम् (प) काक्रु।

+√तुभ् (तुभ) १/७४४ श-जैX हिंसायाम् (आ) क्षी-मै-सा-च-काक्रु-कात-शा-हे। हिंसे—वो।

पूर्ववत्

क—(स्) तॉइ-प् (ब्-, भ्—विच्छिन्नता) = आघाते-वा. पॉकर्नीः।

+√तुभ् (तुभ) ४/१२८ श हिंसायाम् (प) क्षी-मै-सा-च-जै-काक्रु-कात-शा-हे। हिंसे—वो। (हिंसने—जै)।

पूर्ववत्।

+√तुभ् (तुभ) ९/४९	हिंसायाम् (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे । (हिंसने—जै) । हिंसे—वो ।	पूर्ववत् ।
+√तुम्प् (तुन्प्) १/४०३ श×	हिंसार्थः (प) । क्षी-मै-सा-च-कात । हिंसायाम्—जै-शा-हे । भर्त्सनहिंसयोः—काकृ । क्लिशि वधे—वो ।	√तु २/२४ गतिवृद्धिहिंसासु (प) सा । √तुप् (तुप) १/ हिंसार्थः (प) । √तुफ् (तुफ) १/ हिंसार्थः (प) । √तुभ् (तुभ) १/ हिंसार्थः (प) । √त्रुम्प् (त्रुन्प) १/ हिंसार्थः (प) । √त्रुम्फ् (त्रुम्फ) १/ हिंसार्थः (प) ।
+√तुम्प् (तुम्प) ६/३३ श-च-जै-शा-हे×	हिंसायाम् (प) । क्षी-मै-सा-कात । भर्त्सनहिंसयोः—काकृ । क्लिशि वधे—वो ।	पूर्ववत् ।
+√तुम्फ् (तुन्फ) १/४०७ श×	हिंसार्थः (प) । क्षी-मै-सा-च-कात । हिंसायाम्—जै-शा-हे । भर्त्सनहिंसयोः—काकृ । वधे—वो ।	√तुम्ब् (तुबि) १०/ अर्दने (प) । पूर्ववत् ।
+√तुम्फ् (तुन्फ) ६/३५ च-जै-शा-हे×	हिंसायाम् (प) । क्षी-मै-सा-कात । भर्त्सनहिंसयोः—काकृ । वधे—वो ।	पूर्ववत् ।

+√तुम्ब् (तुबि) १/४२८ अर्दने (प) मै ।
क्षी-श-च-जै-शा ×
मै-सा-काकृ-कात-हे ।
अर्दे—वो ।
√तुम्ब् १०/९७ मदने (प)
काकृ ।

ग—तुम्बुरुः-वा. रा. ३,४,१६ (गी. प्रे. सं.) ।

√तुर् (तुर) ३/२१
श-जै-शा ×
त्वरणे (प) ।
क्षी-मै-सा-च-काकृ-
कात-हे ।
वेगे—वो ।
√तूर् (तूरी) ४/ गतित्व-
रणहिंसनयोः (आ) ।
√त्वर् (ञित्वरा) १/
सम्भ्रमे (आ) ।
√तॄ १/ प्लवनतरणयोः
(प) ।

ग—तुतुर्यात्-ऋ. ५,१५,३; मै. ३,८,३; (तुर्याम-ऋ. ५,९,६) ।

ङ—√तुर (अक)=त्वरायाम् । वकृ-तुरंत, तुरेंत, तुरमाण, तुरेमाण-प्रासू. ५८ ।

√तुर्व् (तुर्वी) १/५६८
श ×
हिंसार्थः (प) ।
क्षी-मै-सा-च-कात ।
हिंसने—जै ।
हिंसायाम्—काकृ-शा-हे ।
हिंसे—वो ।
√तु २/२४ गतिवृद्धिहिंसासु
(प) सा ।
√थुर्व् (थुर्वी) १/ हिंसार्थः
(प) ।
√दुर्व् (दुर्वी) १/ हिंसार्थः
(प) ।
√धुर्व् (धुर्वी) १/ हिंसार्थः
(प) ।

ग—तूर्वसि-ऋ. ८,९९,६; शौ. २०,१०५,२ । तूर्वन्-तै. ४,६,१,२; मै. २,१०,१ ।

√तुष् (तुष) ४/७१
श
प्रीतौ (प) ।
क्षी-मै-सा-च-शा ।
तोषणे—जै ।
पुष्टौ—काकृ ।
तुष्टौ—शा-हे-वो ।
√तुष् १/२४० a शब्दे (प)-
च ।
√तूष् (तूष) १/ तुष्टौ (प) ।
नितोशते-निघ. २/१९=
वधकर्मा ।
तोशते-ऋ. ९,२७,१ ।
तोशमाना(=संतोषे)-मा.
१२,६९ ।

ग—तुष्यति–महोपनि. ५,७४; योशि. ३,१४; रुजा. २.३; गी. ६,२० ।
ङ—√तुस्स (अक)=प्रसादे । तुस्सइ–विसे. ९३० ।

+√तुस् (तुस) १/७०३	शब्दार्थः (प) ।
श×, (च√तुप्)	क्षी ।
(जै√त्रुस्)	शब्दे—मै-सा-जै-काकृ- कात-शा-हे ।
	ध्वाने—वो ।

ज—तोसा=अङ्गुलित्रोटने (तच्छब्दे) ।

+√तुह् (तुहिर्) १/७२९	अर्दने (प) ।
श×	क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो ।

ग—तुहुण्डः–मभार. १,६५,२५; १,६७,१९-२०=दानवः । नीता तुहिनेन दूर्वेव–आर्यासप्तश. ६३२=हिमेन ।

ङ—थोह=बलम् , पराक्रमः–दे. ५,३० ।
ङ—थोहर (>थूहर—हि.)=सीहुण्डः–सुपा. २०३ ।

+√तूड् (तूडृ) १/३४७	तोडने (प) ।	>√तुड् (तुडृ) तोडने (प)
मै-श-च-काकृ-कात×	क्षी-सा-जै-शा-हे ।	इति दुर्गः—क्षी ।
	वधे—वो ।	द्रष्ट.√तुड् ६/१०४ ।

+√तूर् (तूरी) ४/४२	गतित्वरणहिंसनयोः (आ) ।	√तु २/ गतिवृद्धिहिंसासु
श	क्षी-सा ।	(प) सा ।
	त्वरणहिंसयोः—मै-काकृ- कात ।	√तुर् (तुर) ३/ त्वरणे (प) ।
	हिंसागतित्वरणयोः— जै-शा ।	√त्वर् (ञित्वरा) १/ सम्भ्रमे (आ) ।
	त्वरायाम्—च ।	√तुर्व् (तुर्वी)१/ हिंसार्थः
	स्यदे हिंसे—वो ।	(प) ।

क—तुर्̑एर्̑–ः तुर् तथा–तूर्̑–वा. पॉकर्नीः ।

ग—मयेन विहिताभिरदृश्य-तूर्भिः–भा. पु. २,७,३७ । √तुर् इत्यनेनापि साध्यम् ।

ङ—√तूर । वक्र-तूरंत, तूरेंत, तूरमाण, तूरेमाण—सुपा. २९१ ।

+√तूल् (तूल) १/५२७ श×	निष्कर्षे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√तूल् (तूल) १०/ पूरणे (आ) इति चन्द्रः—क्षी। √तूल् (तूल) १०/ निष्कर्षे (प) वो।
निष्कर्षः =	वस्तुनिस्सारणम्—क्षी।	
निष्कर्षः =	इह इयत्तापरिच्छेदः—दुर्गादासः।	

क—तॉइ-,तेउ-,तू-, =वृद्धौ । ल-विस्तारः—तु-ऐल=निस्सरणे, प्रकाशने-वा. पॉकर्नीः ।

ग—कुलिशं तूलवत् तदा—दे. भा. ५,१०,३६ ।

छ—√तूलना=धुरि तैलदानाय चक्रं निस्सार्य स्थूणाद्याश्रित्य तत्स्थापने । वस्तुतो निस्सारणे, तोलने च तात्पर्यम् । दुर्गादासमतेन—इयत्तापरिच्छेदस्तोलने घटते, निस्सारणं च क्षीरमतेन ।

+√तूष् (तूष) १/६६७ श×,(काकृ√तुष्-तूषति)	तुष्टौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√तुष् (तुष) ४/ प्रीतौ (प)।

ग—कृष्णं वासः कृष्णतूषं दक्षिणा—तै. १,८,११; २४,९,१. दामतूष०—पञ्चविं, ब्रा. १७,१; कात्या. श्रौ. २२,४,२०; लाट्या. श्रौ. ८,६,२१ ।

ङ—√तूस (अक)=प्रसादे । तूसइ, तूसए—संक्षि. ३६; कृ—तूसियव्व—पण्ह. २,५ ।

छ—√तूसना *=सन्तुष्टौ, तृप्तौ, (२) प्रसादे ।

+√तृंह् (तृन्हू) ६/६९ श×	हिंसायाम् (प) क्षी-च-काकृ-हे। हिंसार्थः—मै-सा-जै-कात-शा। हिंसे—वो।	√तृंह (तृहि) ७/ हिंसायाम् (प)। √स्तृंह् (स्तृन्हू) ६/ हिंसायाम् (प)। √स्तृह् (स्तृहू) ६/ हिंसायाम् (प)।

ग—तृंहत्-ऋ. १०,१०२,४ । देवचक्रे यजमानस्य तृंहती परिप्लवेते—शब्रा. १२,२,२,२ । तृंहति—मै. ३,३,९ ।

√तृंहू (तृहि) ७/१८ मै-सा-श-च-जै-काकृ-शा-हे-वो ×	हिंसायाम् (प) क्षी । हिंसार्थः—कात ।	√तृंहू (तृन्हू) ६/ हिंसायाम् (प)।
√तृहू (तृह-) ७/१८ क्षी-कात ×,श	हिंसायाम् (प) मै । मै-सा-च-काकृ-शा-हे । हिंसने—जै । हिंसे—वो ।	

ग—तृणेढि–जैब्रा. १५१ । तृणेढु–शौ. ८,८,११ ।

+√तृक्ष् (तृक्ष) १/६५१ श ×	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।	

ग—तृक्षः=कश्यपर्षिः-(छ); तृक्षाकः=एक ऋषिः-(छ)।

ङ—तुक्खार=उत्तमजात्यश्वः–सुर. ११,४९; भवि. । (ऋ>उर्>उ । यथा अमृतम्>अमरूद–इति)।

+√तृण् (तृणु) ८/५ श	अदने (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । अदने—हे । भक्षे—वो ।	>√चृन् (चृनु) अदने (उ) इति नन्दी—क्षी ।
√तृन् (तृनु)........	अदने (उ)—मै-सा ।	

अन्येषां तु—अनुस्वारीभूतो णत्वमतिक्रामति—सा ।

ग—अकृणोतना तृणम् –ऋ. १,१६१,११ ।

ङ—तिण=घासः–सुपा. २३३; अभि. १७५; स. १७९ ।

√तृद् (उत्तृदिर्) ७/९ श	हिंसानादरयोः (उ) क्षी-मै-सा-जै-काकृ-कात-शा-हे । हिंसायाम्—च । हिंसे नादरे च—वो ।	√तर्द् (तर्द) १/ हिंसायाम् (प)।

ग—अतृणत्– ऋ. २,१५,३ । तृणद्मि–अ. वे. १९,३२,४ । परि तृन्दन्ति–शब्रा. ३,८,५,८ । (तदार्पते—शौ. ६,५०,३ ।); तर्दः–ऐब्रा. ५,१८; ऐआ. ६,५,३ ।

√तृप् (तृप) ४/८२ श	प्रीतौ (प) क्षी-हे प्रीणने—मै-सा-च-जै-काक्ट-कात-शा-वो ।	√तृप् (तृप) ६/ तृप्तौ (प) इत्येके—क्षी । √तृप् (तृप) ५/ प्रीणने (प) √तृफ् (तृफ) ६/ तृप्तौ (प) ।

ग—नात्मना तृप्यति नान्यस्मै ददाति—तै. २,५,४,३ ।

ङ—√तिप्प (अक)=तृप्तौ—पिंड. ६४७ ।

√तृप् (तृप) ५/२७ श-जै-शा × (क्षी ४/८२ स्थले स्मरति)	प्रीणने (प)—मै । क्षी-मै-सा-च-काक्ट-कात-हे-वो ।	पूर्ववत् ।

ग—तृप्णुहि—ऋ. ३,१६,६; तैब्रा. २,४,८,२ । तृप्णुत—ऋ. १,११०,१ । तृप्नुयात्—भा. पु. ३,५,११ ।

+√तृप् (तृप) ६/३० श-जै-शा ×	तृप्तौ (प) इत्येके—क्षी क्षी-मै-सा-च-काक्ट-कात-हे । प्रीणने—वो	>√तृफ् (तृफ) तृप्तौ (प) । पूर्ववत् ।

ग—तृपत्सोमं पाहि दृह्यदिन्द्रः—ऋ. २,११,५ । तर्पन्त्यथ जुह्वति—मभार. १४,१०,४० इति भौवादिकोऽपि ।

ङ—√तिप्प (सक) = तृप्तौ । हेकु.—तिप्पेउं—पञ्च. ५,५ । कु.—तिप्पियव्व—पउम. ११,७३ ।

+√तृफ् (तृफ) ६/३० च-काक्ट-कात ×	तृप्तौ (प) क्षी-मै-सा-जै-शा-हे । प्रीणने—वो ।	>√तृप् (तृप) ६/ तृप्तौ (प) इत्येके—क्षी । √तृम्प् (तृन्प) ६/ तृप्तौ (प) इत्येके—क्षी । √तृम्फ् (तृन्फ) ६/ तृप्तौ (प) ।

√तृम्प् (तृन्प) ६/३१ मै-सा-श-जै-शा ×	तृप्तौ (प) इत्येके—क्षी । क्षी-च-काक्ट-कात-हे । प्रीणने—वो ।	<√तृम्फ् (तृन्फ) ६/तृप्तौ (प) ।

ग—तृम्पसि-ऋ. ८,४,१२; खि. ३,५,४; जै. ४,१८,८; तृम्पन्तु-शत्रा. ४,२,१,३३।

+√तृम्फ् (तृन्फ) ६/३१ तृप्तौ (प) क्षी-मै-सा-जै-शा-हे।
च-काकृ-कात × प्रीणने—वो।
>√तृम्प् (तृन्प) तृप्तौ (प)। √तृप् (तृप) ६/ तृप्तौ (प) इत्येके-क्षी। √तृफ् (तृफ) ६/ तृप्तौ (प)।

√तृष् (ञितृष) ४/११५ पिपासायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा हे।
√तृष् (ञितृषा)-सि. कौ. तृषि—वो।
ग—तृष्यन्ति-पै. १२,३,१०; तौदादिकोऽपि—तृषत्-शौ. २,२९,४।
छ—√तरसना (<तर्षणम्)=पिपासायाम्, आकुलतायाम्।

[+]√तृह् (तृहू) ६/६८ हिंसायाम् (प) क्षी-च-काकृ-हे।
वो ×, श
√तृह् ७/ हिंसे (प) वो।
ग—ततर्ह-शौ. ११,७,७ (११,५,७)। अतृहम्-अ. वे. २,३१, २।

√तॄ १/९५४ प्लवनतरणयोः (प)
श
क्षी-मै-सा-जै-काकृ-कात-शा-हे।
प्लवने—च।
तारेऽभिभवे प्लुत्याम्—वो।
ग—तरति-ऋ. ६,२,४; तै. १,५,९,६। अप....तिर-शौ. ६,६, ३।
ङ—√तर (अक)=नीरोगतायाम्—तरइ-पिंड. ४१७।
छ—√तरना, √तिरना, √तैरना =प्लवनतरणयोः।

+√तेप् (तेपृ) १/३५८ क्षरणार्थः (आ)
श-काकृ×
क्षी-मै-सा-च-कात।
क्षरणे—शा-हे।
स्रुतौ कम्पे च—जै।
श्च्युतौ कम्पे च—वो।
√तिप् (तिपृ) १/ क्षरणार्थः (आ)। √स्तिप् (ष्टिपृ) १/ क्षरणार्थः √स्तेप् (ष्टेपृ) १/ क्षरणार्थः (आ)।

ङ—√ थेप्प = क्षरणे, गलने—थेप्पइ–पि. २०७; संक्षि. ३४।

+√ तेप् (तेपृ) १/३६१ कम्पने, च = क्षरणार्थः (आ) पूर्ववत्।
क्षी-सा।
क्षरणे कम्पने च—शा-हे।
कम्पे—जै-वो।

पूर्वधातोरभिन्नोऽयं क्षीरेण पृथक् संख्यायते।

+√ तेव् (तेवृ) १/४९५ देवने (आ) √ तेव् १/२६३ रुजायाम् (प)।
श× क्षी-मै-सा-च-जै-काक्र- √ देव् (देवृ) १/ देवने (आ)।
कात-शा-हे-वो।

देवनम् = क्रीडा–इति हलायुधः।
देवनम् = रोदनम्–इति भट्टमल्लः १/३/८३।

ग—तेवनम् = केलिकाननम्, क्रीडा। यथा शब्दार्थचिन्तामणिधृतरामायण-वचनम्—"तेवनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः"–श. क. द्रु.।

छ—तेवन† * = केलिकाननम्।

√ त्यज् (त्यज) १/९७१ हानौ (प)
श× क्षी-मै-सा-च-काक्र-कात-
शा-हे-वो।
त्यागे—जै।

ग—तित्याज–ऋ. १०,७१,६। त्यजति–ब्रह्मोपनि. १; आत्रो. १७; नाप. ५,१; अक्षि. १३; कुण्डिको. ८; गी. ८,६।

ङ—√ चय (सक) = त्यागे। वक्र–चयंत–सुपा. ३८८। संक्र–चइअ–महा.; उवा.।

च—√ तेज्ज (सक) = त्यागे। तेज्जइ–पिंग.।

छ—√ तजना, √ त्यागना } (<त्यजनम्) = त्यागे।

+√ त्रख् (त्रख) १/१३९ गत्यर्थः (प) सम्मतायां <√ रख् (रख) गत्यर्थः (प)।
क्षी-मै-श च-जै-काक्र- तु–सा १३९।
कात-शा-हे-वो× सा।

+√त्रङ्क् (त्रकि) १/९३ शX	गत्यर्थः (आ) क्षी-मै-सा-च-कात। गतौ--जै-काकृ-शा-हे-वो।	√त्रङ्ख् (त्रखि) १/ गत्यर्थः (प)। √त्रङ्ग् (त्रगि) १/ गत्यर्थः (प) इति चन्द्रः--क्षी।

छ—{ √तिरकाना=शिथिलगतौ (लश.); (२) रज्जुशैथिल्ये (लश.)। तिरकट=अग्र-नौवातपटः (लश.)। √तिरकना=स्फाटे।

+√त्रङ्ख् (त्रखि) १/१३९	गत्यर्थः (प) सम्मतायां तु—सा। सा।	<√रङ्ख् (रखि) गत्यर्थः (प) √त्रख् (त्रख) गत्यर्थः (प)
+√त्रङ्ग् (त्रगि) १/१४९ सा-श-जै-काकृ-कात-शा-हेX	गत्यर्थः (प) इति च चन्द्रः—क्षी। क्षी-मै-च। गते—वो।	<√तङ्ग् (तगि) गत्यर्थः (प)। √त्रङ्क् (त्रकि) १/ गत्यर्थः (प)। √त्रख् (त्रख) १/ गत्यर्थः (प)। √त्रङ्ख् (त्रखि) १/ गत्यर्थः (प)।

ग—त्रङ्गः, त्रङ्गा=हरिश्चन्द्रपुरम्–ब्योथ.–रॉथ.। (त्रङ्गति=शोभादिकं गच्छति)।
छ—त्रङ्ग=राजनगरम् (हरिश्चन्द्रस्य)।

+√त्रन्द् (त्रदि) १/६६ शX	चेष्टायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। चेष्टे—वो।	तुन्दाना–शौ. ६,२२,३; पै. १९,२२,१२।

क—तेर् (ऐ) द्=छेदने, प्रवेशे। लिथु. त्रेन्दु–ऐति, त्रन्दे–वा. पॉकर्नीः।

√त्रप् (त्रपूष्) १/३७१ शX	लज्जायाम् (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। ह्रियि—वो।

'त्रपि' भोजसूत्रम्–क्षी
१/८०३ घटादिः।

मै-श-च-जै-काकृ-कात-शा-(हे)×

ग—सा व्यपत्रपमाणेव-ऋ. २,३७,१० ; व्यपत्रपसि-२,५७,२८ ।

√त्रस् (त्रसी) ४/९ जै×,श	उद्वेगे (प) क्षी-मै-सा-काकृ-कात । उद्वेजने—शा । भये—च-हे-वो ।	√त्रस् (त्रसी) १/ भये (प) वो । √त्रस् (त्रस) वारणे (प) इति दुर्गः-क्षी । √त्रंस् (त्रसि) १०/ भासार्थः (प) ।

ग—त्रसन्ति-ऋ. ६,१४,४ ; मै. ४,२,१ । भयात् त्रस्यति-मभार. ३,३०८० । त्रस्यन्ति-वा. रा. ५,४५,१८ ।

ङ—√तस (अक)=त्रासे । कृ-तसियव्व-उप. ३३९ टी. ।

छ—√त्रसना * † (<त्रसनम्)=त्रासे ।

√त्रुट् (त्रुट) ६/९५ श×	छेदने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । छिदि--वो ।	विरुजेयुर्वित्रुड्येयुः-कात्या.श्रौ. २२,३,२२ ।

ग—त्रुटत्तन्तुकं मुक्ताजालम्-भर्तृ. १,९५ । दैवादिकोऽपि-त्रुट्यदट्टालमेखलाः-राजत. १,३०१ । यावन्मे दन्ता न त्रुट्यन्ति-हितोप. १५,१० ।

ङ— { √तुट्ट (अक)-तुट्टइ-महा. । √टुट्ट (अक)-टुट्टइ-पिंग. । √तिउट्ट (अक)-तिउट्टइ-सूअ. १,१५,५ ।

छ— { √तूटना, √टूटना } =छेदने ।

+√त्रुप् (त्रुप) १/४०४ श×	हिंसार्थः (प) क्षी-मै-सा-च-कात । हिंसायाम्—जै-शा-हे । वधे—वो । भर्त्सनहिंसयोः—काकृ ।	द्रष्ट.√तुप् १/४०२ ।

छ—√तुरपना=वर्तिकाकारेण सीवने ।

+√त्रुफ् (त्रुफ) १/४०४ श×	हिंसार्थः (प) इति चन्द्रः—क्षी क्षी-मै-सा-च-कात। हिंसायाम्—जै-शा-हे। भर्त्सनहिंसयोः—जै-काकृ। वधे—वो।	<√त्रुप् (त्रुप) हिंसार्थः (प) √त्रुप्>√त्रुफ्।
+√त्रुम्प् (त्रुन्प) १/४०५ श×	हिंसार्थः (प) क्षी-मै-सा-च-कात। हिंसायाम्—जै-शा-हे। भर्त्सनहिंसयोः—काकृ। वधे—वो।	√तुप् (तुप) १/ हिंसार्थः (प)। √तुफ् (तुफ) १/ हिंसार्थः (प)। √त्रुफ् (त्रुफ) १/ हिंसार्थः (प)। √तुम्फ् (तुन्फ) १/ हिंसार्थः (प)। √त्रुम्फ् (त्रुन्फ) १/ हिंसार्थः (प)।
+√त्रुम्फ् (त्रुम्फ १/४०५ श×	हिंसार्थः (प) इति चन्द्रः —क्षी। क्षी-मै-सा-च-कात। हिंसायाम्—जै-शा-हे। भर्त्सनहिंसयोः—काकृ वधे—वो।	पूर्ववत्। तत्क्रमेण च विकाससम्भवः।
√त्रै (त्रैङ्) १/९५० श×	पालने (आ) क्षी-मै-सा-च-जै-काकृ-कात- शा-हे-वो।	
√त्रा ४/, २/	ह्वि.।	

'त्राहि'–त्रैङ् पालने इत्यत्र कैश्चिददादौ √त्रा पठ्यते–दुर्गादा.।

ग—त्रायसे–ऋ. २,३४,४। त्राहि–ख्रि. २,१,८। त्रासि—एकाक्षरो. १२। त्रास्व–कौ. २,८०८। त्राति–गोन्ना. १,१,२।

+√त्रौक् (त्रौकृ) १/९६ श	गत्यर्थः (आ) क्षी-मै-सा-च-कात। गतौ—जै-काकृ-शा-हे-वो। गत्याम्—वो।	√टौक् (टौकृ) १/ गत्यर्थः (आ) इति दुर्गः—क्षी। √ढौक् (ढौकृ) १/गत्यर्थः (आ)।

छ—तौक (अर.) = आभूषणभेदः, (२) (पट्टः) सारसनम् ।

छ—तौचा (देश.) = आभूषणभेदः । यत् क्वचिद् ग्रामवधूटीभिः शिरसि धार्यते ।

+√त्वक्ष् (त्वक्षू) १/६४७	तनूकरणे (प)	त्वष्टा । त्वक्षतेर्वा स्यात् करोति-
श ×	क्षी-मै-सा-च-जै-काकृ-	कर्मणः-निरु. ८,१४,१ ।
	कात-शा-हे ।	=क्रियासामान्यवाचिनः,
	कार्श्ये—वो ।	उत्सृष्टतनूकरणस्वार्थस्य—
√त्वक्ष् २/	निर्माणे, विधाने-ह्वि. ।	दुर्गाचा. ।

ग—त्वक्षाणो अति विश्वा—ऋ. १०,४४,१ ; त्वक्षसा—१,१००,१५ ।

+√त्वक्ष् (त्वक्ष) १/६५६	त्वचने (प)	√त्वच् (त्वच) ६/ संवरणे
मै-सा-श-जै-काकृ-	क्षी-च-शा-हे ।	(प) ।
कात ×	त्वचो ग्राहे—वो ।	√तक्ष् (तक्ष) १/६६७
		त्वचने (प) मै ।

त्वचनम् = संवरणम्—क्षी ।

√त्वङ्ग् (त्वगि) १/१४९	गत्यर्थः (प)	√तङ्ग् (तगि) १/ गत्यर्थः
श ×	क्षी-मै-सा-च ।	(प) ।
	गतौ कम्पने च—जै-शा-हे ।	
	कम्पे गते—वो ।	
	कम्पने—काकृ-कात ।	

ग—त्वङ्गत्तुरङ्गसंघातखुराग्राङ्कनखक्षता—कथासरि. १८,७ । त्वङ्गदग्र०—दशकु. १३२,४ ।

√त्वङ्ग् (त्वगि) १/१५३	कम्पने, च = गत्यर्थः
श ×	(प) सा ।
	क्षी-मै-शा-हे ।
	गत्यर्थः—च ।
	गतौ कम्पने च—जै-शा-हे ।
	कम्पने—काकृ-कात ।
	कम्पे गतौ (गते)—वो ।

सायणेन पूर्वधातोः पृथक् संख्यायते । यु. मी. संस्करणेऽपि ।

ग—पूर्ववत् ।

√त्वच् (त्वच) ६/२२ संवरणे (प)
श ×
क्षी-मै-सा-च-जै-काक्-
कात-शा-हे ।
वृतौ—वो ।

ग—त्वक्—ऋ. ९,७०,७ । त्वचस्यम्—अ. वे. २,३,७ ।

छ—√दवोचना (<दवचना <तवचना <त्वचनम्)=समावृत्य पीडने, (२) संवरणे ।

√त्वञ्च् (त्वन्चु) १/१८९ गत्यर्थः (प)
श ×
क्षी-मै-सा-च ।
गतौ—जै-काक्-कात-शा-हे ।
इतौ—वो ।

√त्वञ्च् (त्वन्चु) ७/ सङ्कोचे (प) इति दुर्गादा. । तु+√अञ्च् (अन्चु) १/ गतौ (प) ।

छ—√दबकना }
छ—√दुकना† } =(<तवकना <तवंचना <त्वञ्चनम्) = गूहने, संकोच-गतौ ।

√त्वर् (ञित्वरा) १/७६८ सम्भ्रमे (आ)
श ×
क्षी-मै-सा-च-जै-काक्-
कात-शा-हे ।
त्वरे—वो

√तुर् (तुर) ३/ त्वरणे (प) । √तूर् (तूरी) ४/ गतित्वरण-हिंसनयोः (आ) ।

सम्भ्रमः=अत्राशुकारिता—क्षी ।

ग—त्वरेत—काठ. ६,६ ; क. ४,५ ; गोब्रा. १,५,८ । अभित्वरमाणः—मै. ४,५,५ । ममापि त्वरते मनः—वा. रा. ३,७८,२० ।

छ—√तुअर (अक)=त्वरायाम् । तुअर—गा. ६०१ ।
छ—√तर (अक)=त्वरायाम् । तर—विसे. २६०१ ।

+√त्विष् (त्विषा) १/९८५ दीप्तौ (उ)
जै×, श (सा√त्विष् [त्विष])
क्षी-मै-सा-च-काक्-
कात-शा-हे ।
भासे—वो ।
दाननिरसनयोः
(अवोपसर्गे)—
क्षी-मै-सा-शा-हे ।
दाने—वो ।

√त्विष् २/, ४/, ६/····
ह्वि. ।

ग—तित्विषे—ऋ. १,१०२,७; मै. १,३,३२ ।

+√त्सञ्च् (त्सञ्च) १/५५३ गतौ (प) इति कौशिकः— <√त्सर् (त्सर) छद्म-
मै-सा-श-च-जै-काकृ- क्षी
कात-शा-वो × क्षी-हे ।
गतौ (प) ।
√त्सर् + छद्म =
√त्सञ्च् इति वागीशः ।

√त्सर् (त्सर) १/५५३ छद्मगतौ (प)
श ×
क्षी-मै-सा-च-जै-काकृ-कात-
शा-हे ।
छद्मगत्याम्—वो ।
√त्सृ १/ गतौ (प) ।
त्सरति—निघ. २/१४=
गतिकर्मा ।

ग—तत्सार—ऋ. १,१४५,४ । अवत्सरत्—१,७१,५ । त्सरति—शौ. ८,६,८;
शत्रा. ११,१,६,१२ ।

+√थुड् (थुड) ६/१०६ संवरणे (प)
श ×
क्षी-मै-सा-च-जै-काकृ-कात-
शा-हे ।
संवृतौ—वो ।
√स्फुड् (स्फुड) ६/ संवरणे
(प) ।
√छुड् (छुड) ६/ संवरणे
(प) इत्येके—मै ।

?+√थुर्व् (थुर्वी) १/५७० हिंसार्थः (प) इति
श × (काकृ-√घुर्व् चन्द्रः—क्षी ।
[घुर्वी]
क्षी-मै-सा-च-कात ।
हिंसने—जै ।
हिंसायाम्—काकृ-शा-हे ।
वधे—वो ।
<√घुर्व् (घुर्वी) हिंसार्थः
(प) ।
√तुर्व् (तुर्वी) १/
हिंसार्थः (प) ।
√थर्व् १/२०५८ हिंसा-
याम् (प) ।
थर्वतिश्चरतिकर्मा—
निरु. ११,१९,१ ।
√दुर्व् (दुर्वी) १/
हिंसार्थः (प) ।

मैत्रायण्यां संहितायां 'थूर्वन्त' इत्यत्र स्याल्लैपिकी त्रुटिः । तत्संस्करणे 'तूर्वन्त'
इति पाठोऽस्ति—ह्वि. ।

छ—√थुरना
छ—√थरना
} (<थूर्वणम्=वधे)=(१) कुट्टने, (२) आघाते, ताडने ।

छ—√थूरना (<थूर्वणम्)=(१) दलने, (२) ताडने, (३) बलात्प्रवेशने, (४) बलात्पूरणे।

√दंश् (दन्श) १/९७४ दशने (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
दंशने—वो।

√दंस् (दसि) १०/ दर्शन-दंशनयोः (आ)।
√दंश् (दशि) १०/ भासार्थः (प)।

ग—दंदशानाः-ऋ. १०,९५,९। दशन्ति-मै. ३,६,७; शब्रा. ७,४,१,२९।

ङ—√दंस=दशने। दंसइ-नाट.-साहि. ७३। दंसंतु-आचा.।

ङ—√डस=दशने। डसइ-पि. २२२।

छ—√डँसना, √डसना }=दशने।

+√दक्ष् (दक्ष) १/६०३ वृद्धौ शीघ्रार्थे च (आ)
श×
क्षी-मै-सा-कात।
वृद्धौ—च।
वृद्धौ शैघ्र्ये च—जै-शा-हे।
वृद्धौ शीघ्रे च—काकृ।
स्यदे वृद्धौ—वो।

दक्षतेः समर्द्धयतिकर्मणः—निरु. १,७,१।
दक्षतेरुत्साहकर्मणः—निरु. १,७,१।

ग—दक्षते-ऋ. ७,१६,६; जै. ४,२९,६।

ङ—दक्ख=चतुरः-कप्प.; सुपा. २८९; श्रा. २८।

√दक्ष् (दक्ष) १/७६३ गतिहिंसनयोः (आ)
श×
क्षी।
गतिहिंसयोः—मै-शा।
गतिशासनयोः—सा।
गतौ—च।
गतिहिंसायाम्—जै।
गतौ। हिंसायाम्—कात।
गतौ हिंसायां च—काकृ।
हन्त्यर्थे (=गतौ वधे) —वो।
सामर्थ्ये—ह्वि.।

√धक्क् (धक्क) १०/ नाशने (प)।

ग—दक्षसे-ऋ. २,१,११=समर्था भवसि-सायणः। वस्तुतो द्वावेव धातू अभिन्नौ।

√दघ् (दघ) ५/२७ शा-च-जै-काकृ-कात-शा×	घातने (प) क्षी-मै-हे-वो। घातने पालने च—सा	दघ्नं दघ्यतेः स्रवतिकर्मणः—निरु. १,९,१। दघ्यति (दघ्नोति) निघ. २/१४=गतिकर्मा। √दघ् पालने। व्यत्ययेन शप्—देवराजयज्वा। √दह् (दह्) १/ भस्मीकरणे (प)। √दघ्<दग्ध (म्)

ग—दघ्म-ऋ. ७,५६,२१। दघ्नुयात्-काठ. ८,१२; क. ७,७। दघ-पै. १९.३७,८।

छ—√दगना (<दघनम्)=भुशुण्ड्याश्चलने, (२) दाहे। स्याद् दाहार्थस्य 'दग्धम्' इति शब्देन सम्बन्धः।

+√दङ्घ् (दघि) १/१५७ सा-श×	पालने च=वर्जने (प) क्षी। पालने—मै-च-जै-कात-शा-हे।	पूर्ववत्। √दघ्>√दङ्घ्।
(काकृ√ङ्घ् [ङ्घि]	पालने—काकृ। त्यागनेऽवने—वो।	

ङ—धंग (दे.)=भ्रमरः-दे. ५,५७।
ङ—डंगा (दे.)=यष्टिः—सुपा. २३८; ३८८; ५४६।
छ—धंगा† (देश.)=कासः।
छ—धंगर (देश.)=वाहीकः, गोपः।

छ—धाँगड़ (देश.)=वन्यानार्यजातिविशेषः, (२) कूपतडागखननव्यापारो जातिविशेषः।

छ—डंग (देश.)=अर्धपक्वं शुष्कपिण्डखर्जूरफलम्।

√दद् (दद) १/१७ श×	दाने (आ) क्षी-मै-सा-च-जै-काक्- कात-शा-हे । 'धारणे' कौशिकस्तु— क्षी १/८ । धारणे—हे । दाने धृतौ—वो ।	√दा (डुदाञ्) ३/ दाने (उ) । √दङ्ग् १/१६३ धारणे (प) काक् । दण्डो ददतेर्धारयतिकर्मणः "अक्रूरो ददते मणिम्" इत्यभिभाषन्ते—निरु. २,२, ११ । दद्धि—निघ. ३/३९ =याच्ञाकर्मा ।

ग—ददते-ऋ. १,२४,७; शौ. १०,८,३६ । धारणे—पुष्करे त्वा ददन्त-ऋ. सं ५,३,२४,१ ।

√दध् (दध) १/८ श	धारणे (आ) क्षी-मै-सा-च-जै-काक्- कात-शा-हे । 'दाने' इति कौशिकः—क्षी । दाने—हे । ददे—वो ।	√धा (डुधाञ्) ३/ धारण- पोषणयोः (उ) । दध्यति—निघ. २,१४— गतिकर्मा ।

ग—दधते-ऋ. ६,१,९; तै. २,२,१२,४ ।

+√दन्व् (दवि) १/५९२ मै-सा-श-च-जै-काक्- कात-शा-हे×	गत्यर्थः (प) क्षी । व्रजे—वो ।	√धन्व् (धवि) १/ गत्यर्थः (प) । √धिन्व् १/१९० f गत्यर्थः (प) कात ।

√दम् (दमु) ४/९० श×	उपशमे (प) क्षी-मै-सा-च-काक्-कात । उपशमने—जै-शा-हे । शमे—वो ।	√तम् (तमु) ४/ काङ्क्षा- याम् (प) ।

ग—दाम्यतु-पै. १३,१,३ । दाम्यत्-शब्रा. १४,८,२,२ ।
ङ—√दम=निग्रहे । दमेइ-स. २८९ ।
छ—√दवना (<दमनम्)=भारादधः पतने । शान्तौ ।

√दम्भ् (दन्भु) ५/२४ श	दम्भे (प) क्षी-मै-च-जै-काकृ-कात-शा-हे। दम्भने—सा।	√दम्भ् १०/ संघाते (आ) वो। √दम्भ् (दभि) १०/ क्षेपे (प) इति नन्दी—क्षी। दभ्नोति-निघ. २/१४= गतिकर्मा।

दभिरिति सौत्रो धातुः—सा।

ग—दभन्ति-ऋ. ७,३२,१२। आ दभ्नुवन्ति-ऋ. १,५५,७; शौ. २०,५९,३। दभ्नोति-तै. ५,७,४,१; मै. ३,३,९। स्तेनो वा यो दिप्सति नो वृको वा-ऋ. २,२८,१०।

√दय् (दय) १/४७८ श×	दानगतिरक्षणहिंसादानेषु (आ) क्षी-मै-सा-कात। दानगतिहिंसादानेषु—काकृ। रक्षणे—च। दानगतिहिंसादहनरक्षणेषु-जै-शा-हे। ग्रहणे गतौ वधे दानेऽवने—वो।	√दे (देङ्) १/ रक्षणे (आ) दयतिरनेककर्मा। उपदयाकर्मा। दानकर्मा वा विभागकर्मा वा। दहतिकर्मा। हिंसाकर्मा-निरु. ४,१७,२।

ग—दयते-ऋ. ८,१०३,६; कौ. १,४४; जै. १,४,१०।

ङ—√दय (सक)=रक्षणे, (२) कृपायाम्, (३) काङ्क्षायाम्, (४) दाने। दयइ-आचा.।

√दरिद्रा २/६२ श	दुर्गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। दुर्गत्याम्—वो।	√द्रा २/ कुत्सितायां गतौ (प)। कुत्सिता गतिः=पलायनं निद्रा च—क्षी।

ग—दरिद्रति वियद्द्रुमे-विक्रमाङ्कदेव. ११,७४। सर्वे एव दरिद्रति-हितोप. २,२…

ङ—√दलिद्दा (अक)=दौर्गत्ये। भूका-दलिद्दाईअ-संक्षि. ३२।

ङ—दरिद्द=(१) निर्धनः, (२) दीनः-प्रासू. २३; कप्पू.

√दल् (दल) १/५४७ श× विशरणे (प) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे। भेदे—वो। √दॄ ९/ विदारणे (प)। √दल् (दल) १०/ विदारणे (प)।

ग—दलन्ति-सुश्रु. १,३०५,८। दलति-शिशु. ९,१५।
ङ—√दल=विकसने, (२) दीर्णे। दलइ—गा. ४९५। वक्र-दलंत-से. १,५८।
छ—√दलना=दीर्णे।

√दस् (दसु) ४/१०० श च=उपक्षये (प) क्षी-मै-सा-कात-शा-हे-वो। उपक्षेपे—च-काक्ट। क्षये—जै। √तस् (तसु) ४/ उपक्षये (प)। दस्यतेर्वा स्यात्—निरु. १,९,१ = क्षयार्थस्य—दुर्गाचार्यः। दस्युर्दस्यतेः क्षयार्थादुपदस्यन्त्यस्मिन् रसाः—निरु. ७,२३,१।

ग—अपदस्यन्ति-ऋ. १,१३५,८। नोपदस्यन्ति-ऋ. १,६२,१२। पशुभिरुपदस्यति-अ. वे. १२,४,२। अदस्यन्-तै. १,६,११,३।

√दह् (दह) १/९७६ श भस्मीकरणे (प) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे। दाहे—वो। √दघ् (दघ) ५/ घातने (प)।

ग—अनु....दहन्ति-ऋ. १०,२८,८। दहति-तै. १,५,९१; मै. १,८,९।
ङ—√दह=दाहे। दहइ—महा.।
ङ—√डह=दाहे। डहइ—महा.।

+√दा (दाण्) १/९१४ श दाने (प) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे-वो। √दा (डुदाञ्) ३/ दाने (उ)। √दद् (दद) १/ दाने (आ)। दाति—निघ. ३/२०= दानकर्मा।

ग—प्रयच्छति-गी. ९,२६।

√दा (दाप्) २/४८ श	लवने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। लूनौ—वो।	√दो ४/ अवखण्डने (प)। √दान १/ अवखण्डने (प)। √दी (दीङ्) ४/ क्षये (आ)।

ग—दान्ति-ऋ. १०,१३१,२; तै. १,८,२१,१। दाति-ऋ. १,६३,८। दात्रम्-शब्रा. ५३,४,१८।

√दा (डुदाञ्) ३/९ श	दाने (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√दा १/९१४ वत्।

ग—ददाति-ऋ. २,१२,१०; तै. १,५,१,२। दाति-ऋ. ६,२४,२; मै. ४,१०,१ इत्यादादिकोऽप्ययम्।

ङ—√दा (सक)=दाने। दाइ, देइ-भवि.।

+√दाय् (दाय) १/८६७ मै-सा-श-च-जै-काकृ-कात-शा-हे×	दाने (उ) इति कौशिकः-क्षी। क्षी-वो।	<√दाश् (दाशृ) दाने (उ)।
+√दान् (दान) १/९७९ श×	अवखण्डने (उ) क्षी-मै-च-काकृ-कात-शा-हे। खण्डने—सा-जै। आर्जवे छिदि—वो।	द्र.√दा (दाप्) २/४८।
√दाश् (दाशृ) १/८६७; ८७९ श× (जै-√दास् [दासृञ्] जै।	दाने (उ) क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।	>√दाय् (दायृ) दाने(उ) इति कौशिकः-क्षी। √दास् (दासृ) १/ दाने (उ)। दाशति—निघ. ३/२०= दानकर्मा।

ग—दाशसि—ऋ. ८,२४,२; शौ. १८,१,३८। दाश्नोति-ऋ. ८,४,६।

+√दाश् (दाश) ५/३२ श-च-जै-काकृ-कात-शा× (हे—√दास्)	हिंसायाम् (प) क्षी-मै-सा । हिंसने—वो । हिंसायाम्—हे ।	√दास् ५/१७६ h वधे (प) काकृ-कात । √दास् ५/२६ h वधे (प) हे, वो । दाश्नोति–ऋ. ८,४,६= दाने ।
√दास् (दासृ) १/८७९ श×	दाने (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । उपक्षये—ह्वि. ।	>√दाश् (दाशृ) दाने (उ) इत्येके—क्षी । दासति–निघ. ३/२०= दानकर्मा ।

ग—अभिदासति–ऋ. १,७९,११; तै. १,६,१२,४; शौ. १,१९,३ । दासम्–वन-दुर्गोप. ४,५९,२६;–[ऋ. १०,८३,१ ।]

+√दिन्व् (दिवि) १/५८८ श×	प्रीणनार्थः (प) । क्षी-मै-सा-च-कात । प्रीणने—जै-काकृ-शा-हे । प्रीतौ—वो ।	√इन्व् (इवि) १/ प्रीणनार्थः (प) । √धिन्व् (धिवि) १/ प्रीणनार्थः (प) ।
+√दिप् (दिपृ) १/३५८ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	क्षरणार्थः (आ) इति च काश्यपः—सा । सा ।	<√तिप् (तिपृ) क्षरणार्थः (आ) । √तेप् (तेपृ) १/ क्षरणार्थः (आ) । √देप् (देपृ) १/ क्षरणार्थः (आ) इति च काश्यपः—सा ।
√दिव् (दिवु) ४/१	क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिगतिषु (प) । क्षी-शा । क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु—मै-सा-काकृ । क्रीडायाम्—च ।	√देव् (देवृ) १/ देवने (आ) । √दीप् (दीपी) ४/ दीप्तौ (आ) । √द्युत् (द्युत) १/ दीप्तौ (आ) ।

क्रीडाजयेच्छापणिद्युति-
गतिषु—जै ।
क्रीडाविजिगीषाव्यवहार-
द्युतिस्तुतिकान्तिगतिषु—
कात ।
क्रीडाजयेच्छापणिद्युतिस्तुति-
गतिषु—हे ।
जिगीषेच्छापणिद्युतौ क्रीडा-
गत्योः—वो ।

ग—अक्षैर्मा दीव्यः–ऋ. १०,३४,१३ । दीव्येयुः–मै. १,६,११ ।

√दिश् (दिश) ६/३ अतिसर्जने (उ)
श
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
ओचे—वो ।
ओचे=दाने, आज्ञापने
वा—दुर्गादासः ।

√दा (डुदाञ्) ३/ दाने (उ)—दित्सति, दित्सते ।

ग—दिदिष्टन–ऋ. १०,९२,९ । दिशन्तु–तैब्रा. १,४,८,५ । अव देदिशम् – ऋ. ८,७४,१५ ।

ङ—√दिस (सक)=(१) कथने, (२) दाने । दिसइ–भवि. ।

√दिह् (दिह) २/५ उपचये (उ) ।
श
क्षी-मै-सा-च-काकृ-कात ।
लेपे—जै-हे ।
उपदेहे—शा ।
लिपि—वो ।

ग—अशनिभिर्दिहाना–ऋ. १०,८७,४ । अदिहन्–अ. वे. ४,६,७ । मृदा दिग्धा–शब्रा. ६,७,१,१५ ।

√दी (दीङ्) ४/२६ [१/९५२] क्षये (आ) ।
श×
क्षी-मै-शा-च-जै-काकृ-
कात-शा-हे-वो ।
उड्डयने—ह्वि. ।
ब्योथ-रॉथ ।

दीयति–निघ. २/१४= गतिकर्मा ।
√डी (डीङ्) ४/ गतौ (आ) ।

ग—विभिः श्येनेव दीयतम्-ऋ. ५,७४,१ । दीयति-ऋ. ९,३,१ । दीयते-कौ. २,६०६; जै. ३,४९,४ । दीनाः-ऋ. ४,२४,९ ।

√दीक्ष् (दीक्ष) १/६०४ श×	मौण्ड्येज्योपनयन-नियमव्रतादेशेषु (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे । 'मौण्ड्ये' अन्ये-क्षी । मौण्ड्ये—च । मौण्ड्येज्या-ज्योर्थे(= नियमव्रतादेशोपनीतिषु —वो ।	√दिश् (दिश) ६/ अतिसर्जने (उ) । धीक्षते-शब्रा. ३,२,२,३० । धीक्षितम्-गोब्रा. १,३,१ । √दक्ष् (दक्ष) १/ वृद्धौ शीघ्रार्थे च (आ) । √ईष् (ईष) १/ गतिहिंसा-दर्शनेषु (आ) ।

ग—दीक्षते-तै. ६,१,१,३; मै. ३,६,१; काठ. २,३,१; शब्रा. ३,६,३, १ ।

√दीधी (दीधीङ्) २/६५ जै-शा×,श	दीप्तिदेवनयोः (आ) क्षी-मै-सा-काकृ-कात-हे-वो । दीप्तौ—च । चिन्तने—ह्वि. ।	√ध्यै १/ चिन्तायाम् (प) । दीदयति-निघ. १/१७ ज्वलतिकर्मा । दीधितयः-निघ.२/५=अङ्गुलि-नाम ।

देवनम्=क्रीडा-क्षी ।

ग—दीध्यानः-ऋ. १०,१०,१ । अवदीधेत्-ऋ.१०,१४४,३ । अनु···आ दीधीथाम्-शौ. २,१२,५ । अनु··· आदीध्याथाम्-पै. २,५,५ । दीधितिम्-ऋ.सं.३,४,१९,१ = दीप्तौ । दीधितयः-निघ. १/५=रश्मिनाम ।

√दीप् (दीपी) ४/४० श	दीप्तौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । दीपने—वो ।	दीदयति-निघ. १/१७= ज्वलतिकर्मा; ऋ. ५,६,४ । दीद्यति-ऐब्रा. १,८ ।

ग—दीप्यते-तै. ५,६,४,४; काठ. १९,१० ; शौ. १०,७,२ ।

ङ—√दीव् (सक)=(१) दीप्तौ, (२) ज्वलने, ~~(३)~~ प्रकोशे, (४) निवेदने । दीवइ-ओघ. ४३४ ।

छ—√दीपना*=प्रकाशने ।

+√द्रु १/९२९ गतौ (प) √द्रु १/ गतौ (प)।
श क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे-वो।
(काक्र-√द्रू) काक्र।

ख—दवूँ इथ्या <सं. दवन्त्याः=धावन्त्याः-अवे., यस्न. ९/१८।

ङ—√दव (सक)=गतौ, (२) त्यागे। दवए-विसे. २८।

√दु (टुदु) ५/१० उपतापे (प) √दू (दूङ्) ४/ परितापे
श क्षी-मै-सा-च-जै-कात- (आ)।
शा-हे-वो। √दिव् (दिवु) १०/अर्दने (प)।
परितापे (उ)—काक्र।
दाहे—ह्वि.।
सा-√दु (दुङ्) ५/३४ हिंसायाम् (आ)केचित्तु—सा।

ग—विदुनोति सर्वम्-अ. वे. ५,१८,४। नैनं दुन्वन्ति (अग्नयः)-शौ. ९,४,१८। दुनोति चित्तं यदि तं न पश्ये—मभार. ३,१००६९। दुनोति माम्-रघु. ८,५४।

छ—√दवना=दाह। "ग्रीषम दवत दवरिया कुंज कुटीर"-रहीम०।

+√दुड् (दुड) ६/१०७ निमज्जने (प) √हुड् (हुड)६/ निमज्जने (प)।
मै-सा-च-जै-काक्र-कात- क्षी।
शा-हे × मज्जने—वो।

+√दुर्व् (दुर्वी) १/५६९ हिंसार्थः (प) √तुर्व् (तुर्वी) १/हिंसार्थः (प)।
श-जै × क्षी-मै-सा-च-कात। √थुर्व् (थुर्वी) १/हिंसार्थः (प)।
हिंसायाम्—काक्र-कात। √धुर्व् (धुर्वी) १/हिंसार्थः (प)।
वधे—वो। छ-√धुरना*† = आहतौ।

क-*देर् (ऐ) उआ = दूर्वा। मुंदार्त. तर्वे, तेर्वे। हॉले. तर्वे-वा. पॉकर्नीः।
ग—दूर्वाया इव-ऋ. १०,१३४,५; दूर्वा रोहन्तु-१०,१४२,८।

√दुष् (दुष) ४/७२ वैकृत्ये (प)
श क्षी-मै-सा-च-काक्र-कात-
शा-हे।
वैकृते—वो।
(जै√द्रुष् [द्रुषौ]) वितत्ये !—जै।
३३

ग—दुष्यति–शाङ्खा. आ. १२,५; छान्दो. ८,१०,१। दूषयन्ति–ऋ.७,१०४,९; शौ. ८,४,९।

+√ दुहृ (दुहिर्) १/७२९ श-जै×	अर्दने (प) इति चन्द्रदुर्गौ–क्षी क्षी-मै-सा-च-काकृ- कात-शा-हे-वो।	<√ तुहृ (तुहिर्) १/ अर्दने (प)। दोधतः–कौ. २,१००२ (उपतापेऽपि वृत्तिः)। √ उहृ (उहिर्) १/ अर्दने (प)। √ दुहृ (दुह) २/ प्रपूरणे (प)। दोधति–निघ.२/ १२=क्रुध्यतिकर्मा।

अर्दनम्=पीडनम्।

ग—दोहन्–तैत्रा. २,१,१,३=निष्पीडने। दोहने निष्पीडनं भवत्येव।

√ दुहृ (दुह) २/४ श	प्रपूरणे (उ) क्षी-मै-सा-च-काकृ- कात-शा। क्षरणे—जै-हे। दुहि—वो।	पूर्ववत्।

ग—दोहते–ऋ. १,१३४,४। दुहन्ति–ऋ. १,६४[६;] तै. ३,१,११,७। दोग्धि–शत्रा. १,७,१,१७। दुह्यति–इतिहासो. १८,१२। दुह्यन्ति–भा. पु. ९,१९,१३ इति भ्वाद्यदादिदिवादिषु विद्यतेऽयं धातुः।

+√ दू (दूङ्) ४/२५ श	परितापे (आ) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे। खेदे—वो। कर्मणि दाहे—ह्वि.।

ग—दूयामि भरतश्रेष्ठ ?–मभार. ४,५९१। मां कथं पश्यन् न दूयसे–रघु. ७·६।

ङ—√ दू (सक)=उपतापे, (२) कर्तने। कर्म.–दुज्जंतु–पण्ह. १,२।

√ दृंह (दृहि) १/७२६ श×	वृद्धौ (प)। क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो। दार्ढ्ये—ह्वि.।	√ दृहृ (दृह) १/ वृद्धौ (प)।

ग—दृंहति–मै. १,६,३; शब्रा. १,१,२,२२।

√दृ १/७९६ क्षी-मै-श-जै-काकृ-हे-वो ×	भये (प) मित्। सा-च-कात-शा। विदारणे—ह्वि.।	√दॄ १/८०१ भये (प) मित्।

ग—दरयन्तः–शौ. २०,२१,४।

+√दृ ५/३३ श-च-जै-काकृ-कात-शा-हे ×	हिंसायाम् (प)। क्षी-मै-सा।	√दृह् ४/३७ जिघांसायाम् (प) काकृ। √दॄ ९/२२ विदारणे (प)।
√दृ (दृङ्) ६/१३० श (काकृ √द्री)	आदरे (आ)। क्षी-मै-सा-च-शा-हे-वो। अनादरे—जै-कात। आदरणे—काकृ।	

ग—द्रियेत–शाङ्ख्या. ब्रा. २५,१३। न संयतमाद्रियते–शब्रा. २,३,३,८।

√दृप् (दृप) ४/८३ श	हर्षमोहनयोः (प)। क्षी-मै-सा-हे। हर्षे—च। मोहने—जै। प्रहर्षणे विमोचने च—काकृ। हर्षगर्वयोः—वो।	√दृप् (दृप) १०/ संदीपने (प)।

ग—दृप्यति–ऐब्रा. २,७। दृप्यसि–जैउ. ३,६,१,४। अदृपत्–शौ. २०,१३६,५। अद्राप्सीत्–काठ. २८,४; क. ४४,४।

+√दृप् (दृप) ६/३३ क्षी-श-जै-काकृ-कात-शा-हे ×	उत्क्लेशे (प) वामनस्तु मै मै-सा-च। बाधने—वो।	<√दृफ् (दृफ) उत्क्लेशे (प)। √तृप् (तृप) ६/ उत्क्लेशे (प)। √दृम्फ् (दृन्फ) ६/ उत्क्लेशे (प)। √दृम्प् (दृन्प) ६/ उत्क्लेशे (प) च।

अदृपत्—शौ. २०,१३६,५ इत्यस्मिन् प्रयोगे व्याकरणदृष्टिं विना विचारेण श्यनोऽभावात् तौदादिकता स्पष्टैव। एकस्मिन्नेव लकारे प्रयोगस्योपलम्भादयं दिवादौ पुषादिनियमान्तः पाणिनिना विलीनीकृतः।

छ—√तड़पना (<तरपना<दरपना<दर्पणम्)=उत्क्लेशे।

+√दृफ् (दृफ) ६/३६ श-च×	उत्क्लेशे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। क्लेशे—वो।	पूर्ववत्।

छ—√तड़फना
छ—√तड़पना } (<तरफना<दरफना<दृर्फणम्)=व्याकुलतायाम्, उत्क्लेशे।

छ—√डीफना (<डीफ<डिफ<दृफः)=उत्क्लेशे [बुं. ख.]।

√दृभ् (दृभी) ६/४४ श	ग्रन्थे (प) क्षी-मै-सा-च-जै-काकृ-कात-हे। ग्रन्थने—शा। गुम्फने—वो।	√दृभ् (दृभ) १०/ सन्दर्भे (प)। √दृभ् (दृभी) १०/ भये (प)।

ग—दृभति—इति ह्विट्नीरुदाहृतवान्। मया नाधिगतोऽयं प्रयोगः। दृभीकम्—ऋ. २,१४,३।

+√दृम्फ् (दृन्फ) ६/३७ श-च ×	उत्क्लेशे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। क्लेशे—वो।	द्र. √दृप् ६/३३।

द्र. √दृप् ६/३३।

√दृश् (दृशिर्) १/९७३ श	प्रेक्षणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। प्रेक्षे—वो।	√दृप् १/२९७ धारणे (प) काकृ।

ग—पश्यन्ति—ऋ. १,२२,२०; तै. १,३,६,२। दृश्यन्ति—मभार. ५,१४२,४=पश्यन्ति।

स्वार्थयगन्तोऽयं कण्ड्वादेराकृतिगणत्वादिति तट्टीकायां नीलकण्ठः। वस्तुतो लस्यपि √ दृश् धातोर्महाभारतकाले प्रयोग आसीदिति स्पष्टम्। दृश्येत्—मभार. ५,४३,२८ = पश्येत्।

ङ—√ दक्ख (सक)=प्रेक्षणे। दक्खामि, दक्खिमो--अभि. ११६; विक्र. २७।

ङ--√ दिक्ख (सक)=प्रेक्षणे। दिक्खइ—पि. ६६।
ङ--√ देह (सक)=प्रेक्षणे। देहइ, देहए--उत्त. १९,६; पि. ६६।
च—√ देख-(सक)=प्रेक्षणे। देखइ—भवि.।
छ—√ देखना (सक)=प्रेक्षणे।

√ दृह् (दृह) १/७२५ श-काकृ-कात ×	वृद्धौ (प) क्षी-मै-सा-च-जै-शा-हे-वो। दार्ढ्ये—ह्वि.।	√ दृह् ४/३७ जिघांसायाम् (प) काकृ। √ दृढ् १/१८७ धारणे (प)। काकृ।

ग—इन्द्र द्रुह्यस्व पूरसि—ऋ. ८,६९,७—दैवादिकः। दृळ्हानि–ऐब्रा. ३,३१। दृढम्—१ योत. १५; योशि. १,१४; गी. ६,३४।

√ दॄ १/८०१ श-च-कात-शा ×	भये (प) मित् क्षी-मै-सा-जै-काकृ-हे। भियि—वो।	√ दृ १/७९६ भये (प) सा। √ दॄ ९/ [२२] भये (प)। √ दॄ १०, २८८ भये (प) काकृ।

√ दृ····विदारणे—ह्वि.।

ग—दरयन्नदीदेः–ऋ. ७,५,३।
ङ—डर = भयम्–सण.।

+√ दॄ ४/(१/८०१) मै-सा-श-च-जै-काकृ-कात-शा ×	विदारणे (प) इति पञ्जिका–क्षी क्षी (हे)। विदारे—वो।	√ दॄ ९/२२ विदारणे (प)। √ दल् (दल) १/ विशरणे (प)।

ग—पर्वता अपि दीर्येयुः–वा. रा. ५,५८,११। दीर्यतीव वसुन्धरा–मभार. ६,६७७; हृदयं दीर्यतीव च–१,२०६२।

√दॄ ९/२२	विदारणे (प)	इन्द्र इरां दृणातीति वा—निरु.
शं	क्षी-मै-सा-च-काकृ-हे ।	१०,८,२।
	विदारे—वो ।	√दल् (दल) १/ विशरणे
(कात √दृ)...	विदारणे—कात ।	(प)।
	जै-शा ?	

अवदृणीयात्—शत्रा. ५,२,१,१८ । दर्षि-ऋ. १०,६९,३ इत्यादादिकोऽपि ।

+√दे (देङ्) १/९४७	रक्षणे (आ)	√दय् (दय) १/ दानगति-
श×	क्षी-मै-सा-च-जै-शा ।	रक्षणहिंसादानेषु (आ)।
	पालने—कात-हे-वो ।	
(काकृ—√दै)	काकृ ।	

ग—एको देवत्रा दयते मर्तान्-ऋ. ७,२३,५। त्वां मृत्युर्दयताम्-अ. वे. ८,१,५। अस्याशीर्लिङि रूपे दृष्टे √दय् १/ धातुतो भेदः शक्यः कर्तुम्, उभयत्र रूपसादृश्यात् ।

+√देप् (देपृ) १/३५९	क्षरणार्थः (आ) इति च	<√तेप् (तेपृ) क्षरणार्थः
क्षी-मै-श-च-जै-काकृ-	काश्यपः—सा ।	(आ)।
कात-शा-हे-वो×	सा ।	

√देव् (देवृ) १/४९६	देवने (आ)।	√दिव् (दिवु) ४/ क्रीडा-
श	क्षी-मै-सा-च-जै-काकृ-	विजिगीषा० (प)।
	कात-शा-हे-वो ।	√दिव् (दिवु) १०/ अर्दने
	रोदने—ह्वि. ।	(प)।

ग—'देवते' इति ह्विट्नीः । मया नोपालम्भि रूपमिदम् । परिदेवन०-वा. रा. २,३९,४१—परिदेवनम्=रोदनम् (तिल.)।

√दै (दैप्) १/९०८	शोधने (प)।	√दा (दाण्) १/ दाने
श	क्षी-मै-सा-च-जै-कात-	(प)।
	शा-हे-वो ।	√दा (डुदाञ्) ३/ दाने
(काकृ√दे [देप्])	काकृ ।	(उ)।
		√दे (देङ्) १/ रक्षणे (आ)।
		√दो ४/ अवखण्डने (प)।

ग—प्रभ्राजमाना व्यवदाताः-तैआ. १,९,४। सुधावदात०-वा. रा. ४,३३,१०; मभार. ५,१,१९४। दानधर्मः-मभार. १२,२०,९=शुद्धिधर्मः (नील.)।

ङ—अवदाय (<अवदातम्)=(१) पवित्रम्-सुपा. ४९१, (२) श्वेतम्-पण्ह. १,४।

√दो ४/३९ (=३८) अवखण्डने (प)।
श क्षी-मै-सा-च-काक्र-कात-शा।
छेदने—हे।
छेदे—जै-वो।

ग—अव द्यति-तै. २,३,२,२; मै. १,१०,१८। आ द्यति-अ. वे. १२,५,१५।

+√द्यु २/२९ अभिगमने (प) √द्युत् (द्युत) १/ दीप्तौ (आ)।
श× क्षी-मै-सा-च-जै-काक्र-कात-शा।
अभिगमे—हे।
अभिसर्पणे—वो।

√द्युत् (द्युत) १/७३२ दीप्तौ (आ) √दिव् (दिवु) ४/ क्रीडा-विजिगीषाव्यवहार० (प)
श× क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
द्युत्याम्—वो।

ग—द्योतमाना-ऋ. १०,१७७,२। द्योतताम्-शब्रा. ८,६,३,२१। द्योतते-गायत्रीरहस्यो. ४५०:१९।

+√द्यै १/८९० न्यङ्गविधाने (प)
श× क्षी।
न्यक्करणे—मै-सा-च-जै-काक्र-कात-वो।
न्यङ्गकरणे—शा-हे।

√द्रम् (द्रम) १/४६० गतौ (प) द्रमति-निघ. २/१४=गतिकर्मा।
श-जै× क्षी-मै-सा-च-काक्र-कात-शा-हे-वो।

ग—दन्द्रम्यमाणाः-कठोप. १,२,५; मैत्र्यु. ७,९।

√द्रा २/४३ श×	कुत्सितायां गतौ (प) क्षी । कुत्सायां गतौ—मै-सा-जै-काक्र-कात-शा । कुत्सितगतौ—हे । पलायने—च-हे । स्वप्ने पलायने—वो ।	√द्रै १/ स्वप्ने (प) । द्राति–निघ.–२,१४–गतिकर्मा ।

कुत्सिता गतिः = पलायनं निद्रा च–क्षी ।

ग—अप द्रान्तु–ऋ. १०,८५,३२; शौ. ६,१२९,१–३ । द्रातु–शौ. ६,६६,१ । दद्रुः–ऋ. १,६२,११ ।

+√द्राख् (द्राखृ) १/१२४ श×	शोषणालमर्थयोः (प) क्षी-मै-सा-जै-काक्र-कात-शा-हे । शोषणे—च । ओखार्थे(=शोषालमर्थयोः)—वो ।	√ध्राख् (ध्राखृ) १/ शोषणालमर्थयोः (प) । √राख् (राखृ) १/ शोषणालमर्थयोः (प) । √लाख् (लाखृ) १/ शोषणालमर्थयोः (प) ।

+√द्राघ् (द्राघृ) १/१११ श×	सामर्थ्ये (आ) क्षी ।	द्र. उत्तरधातुः ।

उत्तरधातोरभिन्नोऽयं स्वामिना पृथक् संख्यायते । द्र. उत्तरधातुः ।

+√द्राघ् (द्राघृ) १/११३ श×	आयासे, च = सामर्थ्ये (आ) क्षी-च-जै-कात-शा-हे । आयामे, च = सामर्थ्ये—मै-सा । आयासे—काक्र । कौशिकस्तु—'आयामे'—क्षी । क्षी-हे । श्रमायामशक्तिषु—वो ।	√राघ् (राघृ) १/१०९ सामर्थ्ये (आ) । √लाघ् (लाघृ) १/११० सामर्थ्ये (आ) । शेषः √द्राख् (द्राखृ) १/१२४ वत् ।

आयासः = कदर्थनम्–क्षी । कौशिकस्तु–आयामे = दैर्घ्यविशिष्टायां क्रियायामित्याख्यन्–क्षी ।

ग—द्राघ्मन् [घ्मा]-ऋ. १०,७०,४; मै. २,११,२। द्राघिष्ठभिः-कौ. २,१४; जै. ३,२,५। काल्पनिके हि प्रकृतिप्रत्ययविभागे द्राघिमादयः कस्मिंश्चिद् व्याकरणे धातोरेव साधिताः। एवं नेदिष्ठादयो नेदत्यादेः--क्षीरस्वामी।

+√द्राङ्क्ष् (द्राक्षि) १/६६१ काङ्क्षायाम् (प)
क्षी।

उत्तरधातोरभिन्नोऽयं क्षीरेण पृथक् संख्यायते।

+√द्राङ्क्ष् (द्राक्षि) १/६६४ शX
घोरवाशिते, च=काङ्क्षायाम् (प)
क्षी-मै-च-हे।
घोरवासिते, च=काङ्क्षायाम् —
सा-जै-काक्ट-कात।
काङ्क्षे घोररुते—वो।

√ध्राङ्क्ष् (ध्राक्षि) १/ घोरवाशिते, च = काङ्क्षायाम् (प)।
√ध्वाङ्क्ष् (ध्वाक्षि) १/ घोरवाशिते, च = काङ्क्षायाम् (प) इति दुर्गः—क्षी।
√जाङ्क्ष् १/२८३ ० काङ्क्षायाम् (प) काक्ट।

घोररुतमिह तिरश्चामेव घोरशब्दः—दुर्गादा.।
छ—दलाँकना (<दराँकना<दराँखना<द्राङ्क्षगम्)=वृषभगर्जने-(बुं.ख.)।

√द्राड् (द्राडृ) १/२८५ शX
विशरणे (आ)
क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे।
शीर्णौ—वो।

√ध्राड् (ध्राडृ) १/ विशरणे (आ)।
√दल् (दल) १/ विशरणे (प)।

ग—उन्मूलयन् द्रुमान् गण्डशैलान् उद्द्राडयन् बलात्-शत्रुञ्जयमा. १४,४४।

+√द्राह् (द्राहृ) १/६३८ शX
निक्षेपे (आ)
क्षी-सा-जै-शा-हे।
निद्राक्षये—मै-सा-च-काक्ट-कात।
निद्राक्षेपे—हे।
जागरे निक्षेपे—वो।

ग—द्राह्यायणः=सामगानां कल्पसूत्रकारक ऋषिभेदः (छ)।

√द्रु १/९३० श	गतौ (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। स्रुतौ गतौ—वो।	√द्रु १/ गतौ। द्रवति-निघ. २/१४= गतिकर्मा।

ग—दुद्रवत्-ऋ. ७,१६,२; तै. ४,४,४,४। द्रवन्ति-काठ. २८,१; क. ४४,१।

+√द्रु ५/३३ मै-सा-श-च-जै-काकृ-कात-शा×	हिंसायाम् (प) इति दुर्गः—क्षी। क्षी-हे। उपतापे—वो।	√द्रु १/ गतौ (प)। √द्रुह् (द्रुह) ४/ जिघांसायाम् (प)। √द्रू (द्रूञ्) ९/ हिंसायाम् (उ)।

+√द्रुण् (द्रुण) ६/५७ श	हिंसागतिकौटिल्येषु (प) क्षी-मै-सा-जै-शा-हे। हिंसायाम्—च। गतौ—काकृ। हिंसायां गतौ—कात। जैह्म्ये वक्रे गतौ च—वो।	द्रूळति-निघ. १,१४-गतिकर्मा। √द्रु १/ गतौ (प)। √द्रु ५/३३ हिंसायाम् (प)।

क—दे॑रॅडू (ऑ)-वा. पॉकर्नीः।

ग—द्रोणमेघ इवोदितः-मृच्छकटिक. १०,२६। बृहद्द्रोणीशैलकान्तारम्-मालतीमा. ९।

√द्रुह् (द्रुह) ४/८४ श	जिघांसायाम् (प)। क्षी-मै-सा-जै-कात-शा-हे। द्रोहे—च। जिघांसे—वो।	√द्रुहि ५/१७ जिघांसायाम् (प) काकृ—द्रुहिणोति। द्रुह्यत्-ऋ. २,११,१५। पूर्ववत्।

(काकृ-√द्रुह् [द्रुह]) जिघांसायाम्—काकृ।

जिघांसः = इहानिष्टाचरणम्-दुर्गादासः।

ग—अभिदुद्रोह-ऋ. १,२३,२२। द्रुह्यति-तैआ. १,६,३; गोब्रा. २,२,२।

ङ—√द्रोह (सक)=द्रोहे-संबोध. ४।

ङ—√दुह (सक)=द्रोहे। दुहइ-विचार. ६४७।

√दृ (दृञ्) ९/९ हिंसायाम् (उ)। दृणाति-निघ. २/१९=
च-कात × (जै √दृ), श क्षी-मै-सा-काकृ-शा-हे। वधकर्मा।
५/, ९/ वधे गतौ—वो। √दृ ५/३३ हिंसायाम् (प)।

ग—दृणानः-ऋ. ४,४,१। दृणाति-मै. ३,७,३। दृतः-काठ. १६,१५; क. २५,६।

+√द्रेक् (द्रेकृ) १/७५ शब्दोत्साहे (आ)। √द्राङ्क् (द्राक्षि) १/ घोर-
श × क्षी-जै-शा-हे। वाशिते (प)।
शब्दोत्साहयोः—मै-सा-
काकृ-कात।
वृद्धौ—च।
स्वनोत्साहे—वो।

ग—द्रेक्कः }
ग—द्रेक्काणः } =लग्नतृतीयभागैकभागः। यथा ज्योतिस्तत्त्वे-
स्वपञ्चनवमानां ये राशीनामधिपा ग्रहाः।
ते द्रेक्काणाधिपा ज्ञेया द्रेक्काणास्त्रय एव हि॥ -श. क. द्रु.।

√द्रै १/८९१ स्वप्ने (प)। √द्रा २/ कुत्सितायां गतौ
श × क्षी-मै-सा-च-जै-काकृ- (प)।
कात-शा-हे-वो। कुत्सिता गतिः=पलायनं
√द्रा ४/ ह्विट्नीः। निद्रा च—क्षी।

ग—नाद्रासीदेषः-काठ. २८,४। यदि निद्रायात्-शब्रा. ३,९,३,१। निद्रायते-मभार. १३,७४१८। निदद्रौ-नैष. १,१२१।

√द्विष् (द्विष) २/३ अप्रीतौ (उ)।
श × क्षी-सा-च-जै-काकृ-कात-
शा-हे।
वैरे—वो।

ग—द्वेष्टि-ऋ. ३,५३,२१; खि. ४,५,१८। द्वेषते-तै. ४,१,१०,३। न त्यागोऽस्ति द्विषन्त्याश्च-मनु. ९,७९=परिचरन्त्याः (मन्वर्थ.)।

√द्वृ १/९१८ वरणे (प)। √वृ १/९३४ संवरणे (प)
श × क्षी-मै-सा-च-जै-काकृ- सि. कौ.।
कात-शा-हे।
अनादरे—मै।
स्थगने—वो।
√द्वर् ? ह्वि.।

क—घुऐर्-, घुएर्-, घुऑर्-, घुर्-, घुऋ-वा. पॉकर्नी: ।

ग—स हि द्वरो द्वरिषु वव्र ऊधनि-ऋ. १,५२,३; दुर् (=द्वार्)—दुरो घृतान्यक्षरन्-१,१८८,५ ।

+√धण् (धण) १/४५३ मै-सा-श-च-काकृ-कात×	शब्दे (प) । क्षी-जै-शा-हे । ध्वाने—वो ।	>√धन् (धन) शब्दे (प) इति कौशिकः—क्षी । √ध्रण् (ध्रण) १/ शब्दे (प) । √ध्वण् (ध्वण) १/ शब्दे (प) ।
+√धन् (धन) १/४५३ मै-सा-श-च-जै-कात-शा-हे×	शब्दे (प) इति कौशिकः—क्षी । क्षी-काकृ । रवे—वो ।	ध्वनयः पूर्ववत् ।
√धन् (धन) ३/२३ श-जै-शा×	धान्ये (प) । क्षी-मै-सा-च-काकृ-कात-हे-वो । द्रुतगत्याम्—ह्वि. ।	√धन्व् (धवि) १/ गत्यर्थः (प) । पूर्ववत् ।

ग—दधन्युः-ऋ. ४,३,१२ । दधनत्-तैब्रा. २,८,३,५ । दधन्वान्-कौ. २,६७४; जै. ३,५६,२ ।

√धन्व (धवि) १/५९३ श-काकृ-कात×	गत्यर्थः (प) क्षी-मै-सा-च । गतौ—जै-शा-हे । व्रजे—वो ।	धन्वति-निघ. २/१४= गतिकर्मा । √दन्व् (दवि) १/ गत्यर्थः (प) । √धव् १/२५६ f गतौ (प) काकृ । √धाव (धावु) १/ गतिशुद्ध्योः (उ) ।

ग—धन्वन्ति-ऋ. ९,९७,२० । वाजाय धन्याय धन्वसि-ऋ. १,८६,३४ ।

√धम् (धम) १/९११ मै·सा-श-च-जै-काकृ-कात-शा-हे	शब्दाग्निसंयोगयोः (प) प्रकृत्यन्तरमित्येके—क्षी। क्षी। ध्वाने—सौ.धा.—वो।	धमति–निघ.२/१४=गतिकर्मा। धमति–निघ.२/१९=वधकर्मा। धमति–निघ. ३/१४=अर्चतिकर्मा।

ग—इयमस्य धम्यते नाळीः–ऋ. १०,१३५,७। ते बाहुभ्यां धमितमग्निम्… जहुः–२,२४,७। शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः–वा. रा. ३,६२,७। वायुना धम्यमानोऽत्र–मभार. ३,१६८२५।

छ—धमना = संधुक्षणे, (व्यजनवायौ, मुखवायौ च)।

√धा (डुधाञ्) ३/१०	दानधारणयोः (उ) दाने धारणे च—जै-शा-हे। धारणपोषणयोः—मै-सा-काकृ-कात। धारणे—च। धारणे पुष्टौ दाने—वो।	√दध् (दध) १/ दाने (आ)। √धन् (धन) ३/ धान्ये (प)। √धी (धीङ्) ४/ आधारे (आ)। होतारं रत्नधातमम्–निरु. ७,१५,१=धनानां दातृतमम्।

ग—इमं जीवेभ्यः परिधिं दधामि–ऋ. १०,१८,४; धत्ते–३,१०,३; दधाति–६,१०,३।

√धाव् (धावु) १/५९७ श-जै×	शुद्धौ (उ) क्षी। वेगितायां गतौ—इत्याहुः—क्षी। गतिशुद्धयोः—मै-सा-च-काकृ-कात-शा-हे। जवे मृजि—वो।	√सर्तेर्वेगितायां गतौ धावादेशमिच्छन्ति—काशिका ७/३/७८। √धव् १/२५६ f गतौ (प) काकृ। √धन्व् (धवि) १/ गत्यर्थः (प)।

ग—धावति–ऋ. ९,३,७; धावते–६,४८,६। शुद्धौ—धावते–तै. २,५,१,७।
ङ—√धोअ (सक)=प्रक्षालने, शुद्धौ। धोएज्जा–आचा.।
ङ—√धुव (सक)=प्रक्षालने, शुद्धौ। धुवइ, धुवंति–गा. ४३३।
छ—√धावना * † (<धावनम्=गतौ)=द्रुतगमने।
छ—√धोना (<धावनम्=शुद्धौ)=प्रक्षालने, शुद्धौ।

+√धि ६/१२५ श	धारणे (प) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे। धृतौ—वो।	√धा (डुधाञ्) ३/ दान-धारणयोः (उ)। √धा >√धि इति क्रम-सङ्केतः।

ग—अनु…धिषीय-तै. ३,५,६,३; काठ. ३,९; क. २,१६।

+√धिक्ष् (धिक्ष)१/५९९ श×	सन्दीपनक्लेशनजीवनेषु (आ)। क्षी-मै-सा-काक्ृ-कात-शा-हे। संदीपनजीवनक्लेशेषु—जै। संदीपने—च। संदीपे क्लेशे जीवे—वो।	√दह् (दह) १/ भस्मी-करणे (प)। √धुक्ष् (धुक्ष) १/ संदीप-नक्लेशनजीवनेषु (आ)।

छ—धिकना † (<धिक्षणम्)=संदीपने, तपने, अग्न्यौष्ण्येन रक्ताभत्वे।
छ—धिकाना † (प्रयोज.)=संदीपने, तपने, अग्न्यौष्ण्येन रक्ताभत्वे।

√धिन्व् (धिवि) १/५८९ श-काक्ृ-कात-शा-हे-वो×	प्रीणनार्थः (प) क्षी-मै-सा-च। प्रीणने—जै।	√धिन्व् ५/२१ प्रीणने (प) काक्ृ-कात। √धिन्व् ५/२२ प्रीणने (प) शा २६, गतौ—हे। √धिन्व् ५/ प्रीतौ गतौ—वो। √हिन्व् (हिवि) १/ प्रीणनार्थः (प) इति च चान्द्राः-क्षी।

ग—अभिधिनोति-तै. ६,६,१०,२। धिनोति-ऐब्रा. ५,३; शब्रा. १,६,४,४; कुमारसं. ७,९४।

+√धिष् (धिष) ३/२२ श-जै-शा×	शब्दे (प) क्षी-मै-सा-च-काक्ृ-कात-हे। रवे—वो।	√धा (डुधाञ्) ३/ दान-धारणे च (उ)।

ग—मिमाति मायुं धिषणावधिश्रिता-ऋ. सं. २,६,१९,३।

+√धी (धीङ्) ४/२८ श	आधारे (आ) क्षी-हे। आदाने—सा।	√धि ६/धारणे (प)। √धा (डुधाञ्) ३/दान-धारणयोः (उ)।

	अनादरे—मै-च-जै-काक्र-कात-शा-हे । आधारेऽनादरे--वो ।	√दृ ६/अनादरे (आ) जै । √दृ १/अनादरे (प) मै ।

ग—अभिधीतः-मा. ८,५४; का. ९,७,१ ।

छ—धीजना (<धीय [ते])=ग्रहणे, स्वीकारे, (२) धैर्याधारे, (३) अतिप्रसादे, सन्तुष्टौ ।

√धु (धुञ्) ५/९ च-शा ×	कम्पने (उ) इति चन्द्रः-क्षी क्षी-मै-सा-जै-काक्र-कात हे । कम्पे--वो ।	√धू १/कम्पे (उ) वो । √धव् २/२५६f गतौ (प) काक्र । √धाव् (धावु) १/ शुद्धौ (उ)

ग—धुनोति-पारमात्मिकोप. २, ८ । धुनोति शमलं कृष्णः-भा. पु. २, ८, ५ ।

√धुक्ष् (धुक्ष) १/ ५९८ श×	संदीपनक्लेशनजीवनेषु (आ) क्षी-मै-सा-काक्र-कात-शा-हे । संदीपने--च । संदीपनजीवनक्लेशेषु--जै । संदीपे क्लेशे जीवे--वो ।	√दुह् (दुहिर्) १/ अर्दने (प) । √धिक्ष् (धिक्ष)१/संदीपन-क्लेशनजीवनेषु (आ) ।

ग—धुक्षामि-पै. ८, १६, ६ [धुक्षसि इति BKA. शोधप्रस्तावः] । संधुक्ष-ध्वम्-मभार. १३, ३६७७ ।

√धुर्व् (धुर्वी) १/५७० श×	हिंसार्थः (प) क्षी-मै-सा-च-कात । हिंसने—जै । हिंसायाम्—काक्र-शा-हे । हिंसे—वो ।	धूर्वति-निघ. २/१९=वधकर्मा

ग—धूर्वन्तु-ऋ. ६,७५,१९; शौ. १,१९,४ । धूर्वति-तै. १,१,४,१; शत्रा. ५,२,४,२० ।

√धू (धूञ्) ५/९ श-काकृ×	कम्पने (उ)। क्षी-मै-सा-च-जै-कात-शा-हे। कम्पे—वो।	√धु (धुञ्) ५/९ कम्पने (उ)। अव····धवन्ते–ऋ. ६,४७,१४। √धू १/ कम्पने (उ) वो।

ग—अधूनुतम्–ऋ. ३,१२,६; तै. १,१,१४,१। अव····धूनुहि–ऋ. १०,६६,१४। धूनोति–शौ. ९,४,१३।

√धू ६/११७ श	विधूनने (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। कम्पे—वो।	पूर्ववत्।

ग—धुवते–तैब्रा. १,४,६,७[२]। धुवन्ति–१,४,६,७। जरायै निधुवामि त्वा–अ. वे. ३,११,७।

√धू (धूञ्) ९/१५ श	कम्पने (उ)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। कम्पे—वो।	पूर्ववत्।

ग—स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया–शाकु. १८३। धुनीयाद् वा करौ—सुश्रु. १,१०९,१०।

+√धूप् (धूप) १/३९४ श	सन्तापे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। तापे—वो।	√धू ६/११७ विधूनने (प)। शेषः पूर्ववत्। √धूप् (धूप) १०/ भासार्थः (प)।

ग—ततो विधूपायत्प्रत्यक्कर्तारम्–अ. वे. ४,१९,६। धूपायन्–तैब्रा. २,१,१०,१।
ङ—√धूव (सक)=सन्तापे। धूवेज्ज–आचा. २,१३।
छ—√धूप *† = सौगन्ध्ये, व्रजने, सन्तापे।

+√धूङ् (धूरी) ४/४६ श	हिंसागत्योः (आ)। क्षी-मै-सा। हिंसायाम्—च-काकृ-कात।	√तूङ् (तूरी) ४/ गतित्वरणहिंसनयोः (आ)। √धुर्व् (धुर्वी) १/ हिंसार्थः (प)।

गतिहिंसयोः—जै-शा।
हिंसायां गतौ च—हे।
गतौ वधे—वो।

√धृ (धृञ्) १/९०४ क्षी-श×	धारणे (उ) मै। मै-सा-व-जै-काकृ-कात-शा-हे। धृत्याम्—वो।	ध्रति-निघ. २/१४= गतिकर्मा। √धृ (धृङ्) १/९४५ अव-ध्वंसने (आ)। √धृ (धृङ्) ६/१३१ अव-स्थाने (आ)। √धृ प्रीतौ इति मल्लिनाथः-रघु. १६,८२।

ग—धरते-पारमात्मिकोप. १,५। धरन्ति [अवस्थाने गतौ वा]-वरा. ५,३१। ['चरन्ति' इति अड्या]।

√धृ (धृङ्) १/९४५	अवध्वंसने (आ)। क्षी-मै-सा-च-काकृ-कात। 'अविध्वंसने' इति क्षीर-स्वामी-इति पुरुषकारे ३७ पृ०। अविध्वंसने—जै-शा-हे। अविध्वंसे—वो।	पूर्ववत्।

ग—धरते-पारमात्मिकोप. १,५।

+√धृ (धृङ्) ६/१३१ श ? (काकृ-√ध्री)	अवस्थाने (आ) क्षी-मै-सा-च-काकृ-कात। स्थाने—जै-शा-हे। स्थितौ—वो।	पूर्ववत्।
कर्मणि—	ह्वि.।	

ग—ध्रियते-ऋ. ५,३४,७; मै. ४,६,५; काब्रा. १,२,४,७। ध्रियेत्-मभार. २,१११,१२ = जीवेत् (नील.)। इन्द्राय ध्रियस्व-तैब्रा. २,६,३,२।

+√धृज् (धृज) १/२१६ श-च-कात× क्षी√वृज् [वृजी]	गतौ (प) मै मै-सा-जै-काकृ-शा-हे-वो।	√वृज् (वृजी) १/ गतौ (प)। √धृञ्ज् (धृजि) १/२१७ गतौ (प) मै।

√ध्रुज् १/६४b गतौ (प) काक्व। ध्रजति—निघ. २/१४=गतिकर्मा।

द्रष्ट. √ध्रज् १/२१६।

+√धृञ्ज् (धृजि) १/२१७ गतौ (प) मै। क्षी-श-काक्व× मै-सा-च-जै-कात-शा-हे-वो। — √धृज् (धृज) १/२१६ गतौ (प) मै।

√धृष् (ञिधृषा) ५/२३ प्रागल्भ्ये (प) श क्षी-मै-सा-च-जै-काक्व-कात-शा-हे-वो। — √धृष् १/ संहतौ हिंसे (प) वो।

ग—धृष्णुहि—ऋ. १,८०,३; कौ. १,४१३; जै. १,४०,५। धृष्णोति—शब्रा. ३,७,४,२।

√धॄ९/२३ वयोहानौ (प) इति त्वेके इति मैत्रेयः—सा क्षी-मै-श-च-जै-काक्व-कात-शा-हे-वो× सा। — <√जॄ वयोहानौ (प)।

√धे (धेट्) १/८८७ पाने (प) श क्षी-मै-सा-च-जै-काक्व-कात-शा-हे-वो। — √धा (डुधाञ्) ३/ धारण-पोषणयोः (उ) मै।

ग—धयति—ऋ. १,१७९,४; मै. १,६,४; काठ. २७,२; क. ४२,२; शब्रा. १२,९,२,११।

+√धेप् (धेपृ) १/३७० गतौ (आ) इति च क्वचित् पठ्यते—सा। क्षी-मै-श-च-जै-काक्व-कात-शा-हे-वो× — <√रेप् (रेपृ) गतौ (आ)। √हेप् (हेपृ) गतौ (आ) इति च क्वचित् पठ्यते—सा।

+√धोर् (धोर्ऋ) १/५५२ गतिचातुर्ये (प) श×(काक्व-कात×) क्षी-मै-सा-च-जै-शा-हे-वो। — √धोल् १/२५३ b गतिचातुर्ये (प) काक्व। √धौड् १/१८७ गतिचातुर्ये (प) कात। √दोल् १/२५३ a गतिचातुर्ये (प) काक्व।

√डोल्ट १/२५३ c गतिचातुर्ये (प) काक्र।
√ढोल्ट १/२५३ d गतिचातुर्ये (प) काक्र।

क—थेउ्रऐर-(धुऐर-,धॉड्डर)-=जलावर्तः-जू. पॉकर्नीः।
छ—दौड़ना
छ—दौरना } (<दोलनम् <धौडनम् <धोल्टनम् <धोरणम्) = द्रुतगत्याम्।

√ध्मा १/९११ शब्दाग्निसंयोगयोः (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। अग्नियुतौ ध्वनौ—वो।
श
√धम् (धम) १/ शब्दाग्निसंयोगयोः (प)।

ग—धमन्ति-ऋ. ९,१,८; जै. ४,४,८। शङ्खस्य ध्मायमानस्य-शत्रा. १४,५,४,९।

√ध्यै १/८९३ चिन्तायाम् (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। चिन्तने—वो।
श
√धी (धीङ्) ४/ आधारे (आ)। दीध्यानः-मा. २९, २३; का. ३१,३,२२।

ग—ध्यायति-तै. ५,१,५,८; शत्रा. १२,९,१,१३। धीमहि-तैआ. १,११,२।
ङ—√धा = चिन्तने। धाअंति-संक्षि. ७६।
ङ—√झिया = चिन्तने। झियाइ, झियायइ-उवा.; भग.; कस.; पि. ४७९।
छ—√धिआना, √ध्याना, √ध्यावना = ध्याने।

√ध्रज् (ध्रज) १/२१६ गतौ (प) क्षी-मै-सा-काक्र-कात-हे-वो।
श-च-जै-शा ×
√धज् १/६४d गतौ (प)। ध्रजति—निघ. २/१४=गतिकर्मा। ध्रयति—निघ. २/१४=गतिकर्मा।
√धृज् (धृज) १/ २१६ गतौ (प) मै।

ग—वातमिव ध्रजन्तम्-ऋ. ४,३८,३; ७,३६,३। ध्रजतः-तै. १,७,८,३।'

+√ध्रञ्ज् (ध्रजि) १/२१५ श-जै-काकृ-शा×	गतौ (प) क्षी-मै-सा-च-कात-हे-वो।	पूर्ववत्। √धृञ्ज् (धृजि) १/२१७ गतौ (प) मै।
+√ध्रण् (ध्रण) १/४५८ क्षी-सा-श-काकृ-कात×	शब्दे (प) मै-च-जै-शा-हे। ध्वाने—वो।	√धण् (धण) १/४५३ शब्दे (प)। √ध्वण् (ध्वण) १/४४५ शब्दार्थः (प)।
√ध्रन् (ध्रन) १/४५८	शब्दे—मै-सा।	√ढण् १/२०७hh शब्दे (प) काकृ। √ढुण् १/२०७ii शब्दे (प) काकृ। √ध्वन् (ध्वन) १/४५६ शब्दे (प)।

क—धेर्-, धेरॉङ्-, ध्रेन् = शब्दे, कलकलशब्दे, गर्जने। पु. सैक्सॉ. ड्रेनॉ = मधुमक्षिका; वाद्यविशेषस्य नलिका। पु. उ. ज.-त्रेनॉ = मधुमक्षिका; वाद्यविशेषस्य नलिका-वा. पॉकर्नीः।

+√ध्रस् (उध्रस्) ९/५२ कात ?, श	उञ्छे (प) क्षी-मै-सा-च-जै, कात ? शा-हे। उत्क्षेपे उञ्छे च—वो।	√ध्रस् (उध्रस) १०/ उञ्छे (प)। √उद्ध्रस् (उद्ध्रस) १०/ उञ्छे (प)।
काकृ-√ध्रश् [ध्रश]	उञ्छे—काकृ। उत्क्षेपे—काकृ-कात-हे।	
+√ध्राख् (ध्राखृ) १/१२५ श-शा×	शोषणालमर्थयोः (प) क्षी-मै-सा-जै-काकृ-कात-हे। शोषणे—च। ओखार्थे (=शोषालमर्थयोः)—वो।	√द्राख् (द्राखृ) १/ शोषणालमर्थयोः (प)। √राख् (राखृ) १/ शोषणालमर्थयोः (प)। √लाख् (लाखृ) १/ शोषणालमर्थयोः (प)।
+√ध्राघ् (ध्राघृ) १/११२ मै-श-च-जै-काकृ-कात-शा-हे×	सामर्थ्ये (आ) क्षी-सा। शक्तौ—वो।	√द्राघ् (द्राघृ) १/ सामर्थ्ये (आ)। √राघ् (राघृ) १/ सामर्थ्ये (आ)।

		√लाघ् (लाघृ) १/ सामर्थ्ये (आ)। √ध्राख् (ध्राखृ) १/ शोषणालमर्थयोः (प)।
+√ध्राङ्क्ष् (ध्राक्षि) १/६६२ श×	काङ्क्षायाम् (प) क्षी।	√ध्राङ्क्ष् (ध्राक्षि) १/ घोरनिवाशिते च (प)। √द्राङ्क्ष् (द्राक्षि) १/ काङ्क्षायाम् (प)।

उत्तरसूत्रादभिन्नः क्षीरस्वामिना पृथक् संख्यायते।

+√ध्राङ्क्ष् (ध्राक्षि) १/६६५ श-जै×	घोरनिवाशिते, च= काङ्क्षायाम् (प) क्षी। घोरवाशिते, च= काङ्क्षायाम्— मै-च-शा-हे। घोरवासिते, च= काङ्क्षायाम्—सा-काकृ-कात। काङ्क्षे घोररुते—वो।	द्रष्ट. √द्राङ्क्ष् १/६६४।
+√ध्राड् (ध्राडृ) १/२८५ श×, (जै√धाड्)—संभवतो मुद्रणदोषदूषितः।	विशरणे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। शीर्णौ—वो।	√द्राड् (द्राडृ) १/ विशरणे (आ)।

ङ—√धाड (सक)=(१) प्रेरणायाम्, (२) नाशे। धाडेंति-सूअ. १,४,२।
छ—√धाड़ना=मलिम्लुचानामाक्रमणे।

+√ध्रु १/९२८ श-च-काकृ-कात×	स्थैर्ये (प) क्षी-मै-सा-जै-शा-हे-वो।	√ध्रुव् (ध्रुव) १/स्थैर्ये (प)।

ग—उत्तरसूत्रं विलोकनीयम्।

+√ध्रु ६/११९ श-च-कात×	गतिस्थैर्ययोः (प) क्षी-मै-सा-जै-काकृ-शा-हे। स्थैर्ये सर्पणे—वो।	

ग—ध्रुवो अस्तु–ऋ. ४,२,७। ध्रुवा गावो मयि गोपतौ–अ. वे. २,२६,४। तिङन्तप्रयोगमन्तरा भ्वादेस्तुदादेर्वा निश्चयोऽशक्यः कर्तुम्।

+√ध्रुव् (ध्रुव) ६/११६ क्षी-मै-जै-काकृ-शा-हे वो×,श	गतिस्थैर्ययोः (प) इति स्वाम्यादयः—सा। सा-च-कात।	√ध्रु ६/११९ गतिस्थैर्ययोः (प)।

उक्तं च 'ध्रुवमपाये' इति सूत्रे हरदत्तेन—"ये 'ध्रुव'गतिस्थैर्ययोरिति पठन्ति, तेषामिगुपधलक्षणः कप्रत्ययः"—सा ११६।

+√ध्रेक् (ध्रेकृ) १/७६ श×	शब्दोत्साहे (आ) क्षी-जै-शा-हे। शब्दोत्साहयोः--मै- सा-काकृ-कात। वृद्धौ—च। स्वनोत्साहे—वो।	√द्रेक् (द्रेकृ) १/ शब्दो- त्साहे (आ)। √ध्रेक् (ध्रेकृ) १९१५ दर्शने (प) इत्येके— सि. कौ.।
+√ध्रै १/८९२ श×	तृप्तौ (प) क्षी-मै-सा-जै-काकृ- कात-शा-हे-वो। दीप्तौ—च	√त्रै १/२७५ a तृप्तौ (प) शा।
√ध्वंस् (ध्वन्सु) १/७४६ श	अवस्रंसने (आ) क्षी-सा।	

उत्तरधातोरभिन्नः क्षीरेण पृथक् संख्यातः।
ग—ध्वंसताम्–वा. रा. २,३५,२३।

√ध्वंस् (ध्वन्सु) १/७४८ श×	गतौ,च=अवस्रंसने (आ) क्षी-मै-सा-कात-शा-हे। गतौ—च-काकृ। अवस्रंसे गतौ च—जै। गतौ भ्रंशे—वो।	√ध्वंसति–निघ. २/१४= गतिकर्मा।

ग—यत्र सर्वत्र आपः प्रध्वंसेरन्–आश्व. गृह्य. ४,१।

+√ध्वज् (ध्वज) १/२१७ श-च×	गतौ (प) इत्येके–क्षी। क्षी-मै-सा-जै-काकृ- कात-शा-हे-वो।	<√ध्वञ्ज् (ध्वजि) गतौ (प)। √धुज् (धुज) १/६४ b गतौ (प) काकृ।

क—ध्रुऐज्=कम्पने ?–वा. पॉकर्नीः ।

ग—येषु ध्वजेषु पतन्ति–ऋ. ७,८२,२ ।

छ—धज, धजा (<ध्वजः) ।

+√ध्वञ्ज् (ध्वजि) १/२१७ गतौ (प)		>√ध्वज् (ध्वज) गतौ (प) ।
श-काक्र-कात×	क्षी-मै-सा-च-जै-शा-हे-वो ।	√ध्रुज् (ध्रुज) १/६४ d गतौ (प) काक्र ।

छ—धौंजना=द्रुतगत्याम्, व्याकुलतायाम्, (२) पादाभ्यां मर्दने, (३) पादाभ्यां सम्मर्द्य विरूपणे ।

+√ध्वण् (ध्वण) १/४४९	शब्दार्थः (प)	√धण् (धण १/ शब्दे (प) ।
मै-श-च-काक्र-कात×	क्षी-सा ।	√ध्वन् (ध्वन) १/ शब्दे (प) ।
	शब्दे—जै-शा-हे ।	√वन् (वन) १/ शब्दे (प) ।
	ध्वाने—वो ।	

√ध्वन् (ध्वन) १/४९६	शब्दे (प)	√द्रष्ट. √ध्रण् १/४५८ ।
मै-सा-श-जै-शा-हे-वो×	क्षी-च-काक्र-कात ।	√ध्वन् (ध्वन) १०/ शब्दे (प) ।

ग—अध्वनत्–काठ. २७,३; क. ४२,३ ।

√ध्वन् (ध्वन) १/८०३	शब्दे (प)	पूर्ववत् ।
श-च×	क्षी-मै-सा-जै-काक्र-कात-शा-हे ।	
	रवे—वो ।	

ग—ध्वनयन्–तैआ. ४,२४,१ ।

√ध्वन् (ध्वन) १/८१२	शब्दे (प) घटादिः फणादिश्च ।	पूर्ववत् ।
श-जै-शा×	क्षी-मै-सा-च-काक्र-कात-हे ।	
	रवे—वो ।	

ग—उदाहरणं पूर्ववत्

+√ध्वाङ्क्ष् (ध्वाङ्क्षि) १/६६३	घोरनिवाशिते, च=काङ्क्षायाम् (प) इति दुर्गः–क्षी ।	<√ध्राङ्क्ष् (ध्राङ्क्षि) घोरनिवाशिते च (प) ।
	घोरवाशिते, च=काङ्क्षायाम्—मै-च-शा-हे ।	√वाङ्क्ष् (वाङ्क्षि) १/ काङ्क्षायाम् (प) ।

घोरवासिते च=काङ्क्षायाम्-
सा-जै-काक्र-कात।
काङ्क्षे घोररुते—वो।

ग—हविर्ध्वाङ्क्षा इवाध्वरात्-ब्राह्मणविला. २,१७।

√ध्वृ १.९२३ हूर्च्छने (प) √ह्वृ १/ कौटिल्ये (प)।
श× क्षी-मै-सा-च-कात। ध्वरति-निघ. २/१९=
कौटिल्ये—शा-हे-वो। वधकर्मा।
(जै-काक्र-√धृ) हूर्च्छने—काक्र। √धुर्व् (धुर्वी) १/ हिंसार्थः
कौटिल्ये—जै। (प)।

ग—ध्वरति-तै. २,५,८,६। अध्रूर्षत-ऋ. ५,१२,५।ध्वराम-मै. १,१,४।

√नक्ष् (णक्ष) १/६५३ गतौ (प) नक्षति-निघ. २/१४=गतिकर्मा।
श× क्षी-मै-सा-च-जै-काक्र- नक्षति-निघ. २/१८=व्याप्तिकर्मा।
कात-शा-हे। नंशे-ऋ. १,१२२,५।
व्रजे—वो।

ग—अभिनक्षति-ऋ. १,९५,१०; पै. ८,१४,१०। नक्षति-शौ. २,२७,३; मै. २,१६,६। नक्षते-तैब्रा. १,५,२,५।

छ—√नकना* † =चलने।
छ—√नाकना† * =वर्धने, प्रस्थाने।

+√नख् (णख) १/१३४ गत्यर्थः (प) √नक्ष् (णक्ष) १/६५३ गतौ (प)।
मै-श-शा× क्षी-सा-च-कात। √नंख (णखि) १/ गत्यर्थः (प)।
गतौ—जै-काक्र-हे-वो। शेषः पूर्ववत्।

छ—√नखना=पारगमने।
छ—√नाकना † *=पारगमने, (२) प्रस्थाने, लङ्घने-"परिमान नखे" केशव.।
छ—√नाखना* †=(१) क्षेपणे, पातने, (२) लङ्घने-"नीरनिधि नाख्यो ई"—केशवदासः।

+√नख् (नख) १/१३४ गत्यर्थः (प) पूर्ववत्।
श-च-जै-काक्र- क्षी-मै-सा-च।
कात× गतौ—शा-हे-वो।
सर्पणे—वो।

छ—√नाखना * †=लङ्घने।
छ—√नाकना † *=लङ्घने।

+√नङ्ख्(णखि) १/१३५ मै-श-च-जै-काकृ-कात-शा-हे-वो×	गत्यर्थः (प) क्षी-सा।	पूर्ववत्।

छ—पूर्ववत्।

+√नज्(ओनजी) ६/१० मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	व्रीडे (आ) इति चन्द्रः-क्षी क्षी।	<√लज्ज् (ओलस्जी) व्रीडे (आ)। √नज्(ओनजी) १/ह्रियि (आ) वो। √नञ्ज् १/३१३ b हिंसा-गत्योः (प) काकृ।

ग—अभ्यूर्णोति यन्नग्नम्-ऋ. ८, ६८,२।

√नट्(नट) १/३०६ मै-श×	नृतौ (प) क्षी-सा-च-कात-शा-हे। नृत्तौ—सा-जै-काकृ। नृत्ये हिंसे—वो। 'नतौ' इत्येके—क्षी। 'नृत्तौ' इत्युचितः पाठः द्र. पुरुषकारे ६६ पृ.।	√नट् (नट) १०/अवस्य-न्दने (प)। √नट्(नट) १०/भासार्थः (प)। √नथ् (णथ) १०/१९ अवस्कन्दने (प) काकृ। शेष उत्तरधातुवत्।

ग—नटः-दे. भा. १,७,४२। नटति-पञ्चत. १,४,३३। नटते-राजत. ३,२१८।
छ—नटना=(१) नाट्ये, (२) नर्तने, (३) निषेधे।

+√नट्(णट) १/३०८ क्षी-च-जै-काकृ-कात-शा×,श	नृतौ (प) मै मै-सा-हे। नृत्यहिंसयोः—वो।	√नम् (णम्) १/९६६ प्रह्वत्वे (प)। √नृत्(नृती) ४/८ गात्र-विक्षेपे (प)। शेषः पूर्वधातुवत्।

नृत्यम्=साभिनयनर्तनम्-दुर्गादासः।

ग—पूर्ववत्।

+√नट् (नट) १/७७४ नतौ (प) मित् ।
मै-सा-श-हे× क्षी-वो । पूर्वद्वयधातुवत् ।
नृतौ—च-कात-शा ।
नृत्तौ—जै-काकृ ।
ग—√नट् (नट) १/३०६ वत् ।

+√नट् (णट) १/७८५ नृत्तौ (प) मित्—मै ।
क्षी-श-च-जै-काकृ- मै-सा ।
कात-शा× 'गतौ' इत्येके—मै । पूर्ववत् ।
'नतौ' इत्यन्ये—मै ।
हे-वो ।

√नद् (णद) १/५२ अव्यक्ते शब्दे (प) नदति—निघ. ३,१४=
श× क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । अर्चतिकर्मा ।
क्लिष्टोक्तौ—वो । √नन्द् (टुनदि) १/समृद्धौ (प) ।

ग—नानदति-ऋ. १,६४,८ । नदतो नभस्वतः-अ. वे. ४,१५,१ । ननाद-वा. रा. २,४१,२०=चक्रन्द (तिल.) ।

ङ—√णद =शब्दे । वकृ. णदंत-सम. ५० ।

छ—√नदना*†=शब्दे ।

√नन्द् (टुनदि) १/६४ समृद्धौ (प) √नन् ८/२ शङ्कायाम् (उ)
श× क्षी-मै-सा-च-जै-काकृ-कात- काकृ ।
शा-हे ।
संवृधि—वो ।

ग—नन्दन्ति-ऋ. १०,७१,१०; शौ. १९,५३,७; पै. १२,२,७ । नन्दते-कौलोप. ८ : ४ । नन्दति-वा. रा. ३,४५,३ ।

ङ—√णंद=प्रसादे, (२) समृद्धौ । कवकृ.-णंदिज्जमाण-औप. ।

छ—नादना (<नन्दनम्)=प्रफुल्लत्वे ।

√नभ् (णभ) १/७४३ हिंसायाम् (आ) √नभते-निघ. २/१९-वधकर्मा ।
श× क्षी-मै-सा-च-जै-काकृ- √नभ् (णभ) ४/ हिंसायाम् (आ) ।
कात-शा-हे ।
हिंसने—जै । √नभ् (णभ) ९/ हिंसायाम् (आ) ।
हिंसे—वो ।

ग—नभन्ताम्-ऋ. १०,१३३,१; तै. १,७,१३,५; शौ. २०,९५,२-४।

+√नभ् (णभ) ४/१२७ हिंसायाम् (आ) पूर्ववत्।
श शेषः पूर्ववत्।

+√नभ् (णभ) ९/४८ हिंसायाम् (आ) पूर्ववत्।
शेषः पूर्ववत्

√नम् (णम) १/९६६ प्रह्वत्वे (प)
श× क्षी-जै-हे।
प्रह्वत्वे शब्दे च—
क्षी-(यु. मी. सं.)-मै-सा-च।
प्रह्वत्वे शब्दे—काक्र-कात-शा।
शब्दनत्योः—वो।

√नम् (नम) १/८०३ अनुपसर्गाद्वा (उ)
श-जै-शा-हे-वो×

प्रह्वत्वम्=नम्रत्वम्-क्षी।

ग—नमन्ति-ऋ. ८,९७,१२; जै. ३,२३,१३; शौ. २०,५४,३।

ङ—√णम=नमने, प्रणामे। णमामि-भग.।

+√नम्ब् (नम्ब) १/४२२ गतौ (प) रेफस्थाने नकारं <√नर्ब् (नर्ब) गतौ (प)।
मै-सा-च-जै-काक्र- कौशिको मन्यते (प) क्षी। √नम्ब् १/२०६ k मर्दने (प)
कात-शा-(हे)× क्षी-वो। काक्र।

+√नय् (नय) १/४७६ गतौ (आ) √नी (णीञ्) १/ प्रापणे
मै-सा-श-च-काक्र- क्षी-जै-शा-हे-वो। (उ)।
कात×

छ—उत्तरसूत्रवत्।

+√नय् (णय) १/४७९ गतौ (आ) मै। √नाय् १०/७३ हेतौ (प)
क्षी-श-जै-शा-हे× मै-सा-च-काक्र-कात-वो। काक्र।
रक्षणे च—मै-सा।
गतिरक्षयोः—वो।

छ—नयना *=नम्रत्वे, (२) प्रलम्बने, (३) गतौ।

√नर्द् (नर्द) १/५४ शब्दे (प) √नर्द् (णर्द) १/१९ a शब्दे (प)
श-काक्र-शा× क्षी-मै-सा-च-जै-कात- काक्र; १/३०७ शब्दे—शा;
हे-वो। १/३०२ शब्दे—हे-वो।

ग—नर्देत्–ऐब्रा. ६,३२। दर्दुरः प्रतिनर्दति–मभार. ८,१८०६। निनर्दन्निव गायति—पब्रा. २,१; आश्व. श्रौ. ८, ३

+√नर्व् (नर्व) १/४२२ गतौ (प)
मै-सा-श-च-जै-काक्र- क्षी-हे-वो।
कात-शा ×

>√नम्ब् (नम्ब) गतौ (प)।

छ—नवारना=(१) चलने, पादविहारे, (२) यात्रायाम्।

√नल् (णल) २/८२२ गन्धे (प)
श-जै ×
क्षी-मै-सा-च-काक्र-कात-शा-हे-वो।
बन्धे—वो।
गन्धः=अर्दनम्—क्षी।

√नड् (नड) १०/२६२ भाषार्थः (प) सा।
√नल् (नल) १८०३ भाषार्थः (प) सि. कौ.।

क—नर्द् (हृ) ऑ—: (अथवा* नेर्धो–: नृधो ?)।
ख—* नर्द—: न. पर्सि. नाल=नलिका, वेत्रम्—वा. पॉकर्नीः।
ग—नलः–द्रौप. प्रमा. ५,९।
छ—√नलाना=बीजाकृतात् क्षेत्रात् तृणाद्यपनयने।

√नश् (णश) ४/८१ अदर्शने (प)
श
क्षी-मै-सा-च-जै-काक्र-कात।
नाशे—वो।
(शा-हे √नश् [नश] ४/७१ अदर्शने—शा-हे।

√नस् (णस) १/ कौटिल्ये (आ)।
नशते–ऋ. ५,४,११।
नशत्–निघ. २/१८=व्याप्तिकर्मा।

ग—अभिनशन्–ऋ. २,२७,१४। नश्यति–तै. २,३,२,५; शब्रा. १२,४,१,११।
ङ—√णस (अक)=पलायने। णसइ–पिंग.।
ङ—√णस्स (अक)=पलायने। णस्सइ–कुमा.।
छ—√नशना * } =नाशे।
√नसना *† }

√नस् (णस) १/६२० कौटिल्ये (आ)
श-काक्र ×
क्षी-मै-सा-च-जै-कात-शा-हे।
हृतौ—वो।

√क्नस् (क्नसु) ४/ ह्वरण-दीप्त्योः (प)।
नक्षते–निघ. २/१४=गतिकर्मा।
नसतिराप्नोतिकर्मा वा, नमतिकर्मा वा—निरु. ७,१७,१।

ग—नसते-ऋ. ९,७१,३ ।

छ—√नसना*† = विकृतौ ।

√नह् (णह्) ४/५५ श	बन्धने (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । वन्धे—वो ।	√नथ् (णथ) १०/ अवस्कन्दने (प) काकृ । √नाध् (नाधृ) १/ याच्ञोपतापैश्वर्याशीःषु (आ) ।

ग—अपि नह्यामि-ऋ. १०,१६६,३; शौ. १,१४,४ । नह्यते-तै. ३,१,७,१ । नह्यति-ऐब्रा. १,११ ।

√नाथ् (नाथृ) १/७ श×	याच्ञोपतापैश्वर्याशीःषु (आ) क्षी-मै-सा । याचने—च । याच्ञाशीरुपतापैश्वर्येषु—जै-शा । याचने उपतापाश्चर्याशीःषु—काकृ । 'आश्चर्य-' इत्यैश्वर्यस्थाने स्याल्लैपिकी त्रुटिः । याचने उपतापैश्वर्याशीषुः—कात-हे । द्वाशिषोरैश्वर्येऽर्थने—वो ।	√नह् (णह्) ४/५५ बन्धने (उ) । √नस् (णस) १/६२० कौटिल्ये (आ) + क्तः = नस्तम्-नस्तितम् । √नाध् (नाधृ) १/६ याच्ञोपतापैश्वर्याशीःषु (आ) ।

ग—अनाथत-मै. ४,५,८; काठ. १०,२; क. ४२,४ । इष्टदेवं नाथन्ति के नाम न लोकनाथम्-नैषध. ३,२५ ।

छ—√नाथना = उपतापे, नाथने, नासान्ता रज्जुप्रोतत्वे ।

√नाध् (नाधृ) १/६ मै-श-काकृ-शा×	याच्ञोपतापैश्वर्याशीःषु (आ) क्षी-सा । जै—पूर्ववत् । याचने—च । वो—उत्तरवत् । याचने उपतापैश्वर्याशीःषु—हे ।	√नह् (४/५५ + क्तः = नद्धम् (:) । शेषः पूर्ववत् ।
√नाध् [णाधृ] क्षी-श-च-जै-कात×	याच्ञोपतापैश्वर्याशीःषु (आ) मै-सा । याच्ञाशीरुपतापैश्वर्येषु—शा । याचने उपतापाश्चर्याशीःषु—काकृ । याचने उपतापैश्वर्याशीषुः—हे । नाथे—वो ।	

ग—नाधमानेव योषा–ऋ. ५,७८,४। नाधमानस्य कारोः ऋ. १, १७८, ३। नाधमानः—तैआ. ३,१५,२।

+√नास् (णास्) १/६१९ श-काकृ×	शब्दे (आ) क्षी-मै-सा-च-जै-कात-शा-हे। ध्वाने—वो।	√नास् १/५३५ शब्दे (आ) काकृ। √नस् (णस) १. कौटिल्ये (आ)।

ग—यो नासे परिसर्पति–अ. वे. ५,२३,३।

√निंस् (णिसि) २/१५ श	चुम्बने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। चुम्बे—वो।	√निक्ष् (णिक्ष) १/ चुम्बने (प)।

ग—निंसते–ऋ. १,१४४,१।

√निक्ष् (णिक्ष) १/६१९ श×	चुम्बने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। चुम्बे—वो।	√निंस् (णिसि) २/ चुम्बने (आ)।

ग—अनुनिक्षन्ति पृष्टीः–शौ. ९,८,१५; पै. १६,७५,५। निक्ष दर्भ सपत्नान् मे–शौ. १९,२९,१=छेदने।

√निज् (णिजिर्) ३/११ श	शौचपोषणयोः (उ) क्षी-मै-सा-जै-काकृ-कात-शा-हे। शुद्धौ—च। पोषे शुद्धौ च—वो।	√निञ्ज् (णिजि) १/ शुद्धौ (आ)।

ग—नेनिक्ते–ऋ. ९,७१,३। निजमहे–पै. १,१११,३ [पाठः ? नेनिज्महे इति शोधः]। नेनिज्यान्नेजकः शनैः–मनु. ८,३९६।

√निञ्ज् (णिजि) २/१६ (श)	शुद्धौ (आ) क्षी-मै-सा-च-जै-काकृ-कांत-शा-वो। विशुद्धौ—हे।	√निज् (णिजिर्) ३/ शौच-प्रोपणयोः (उ)।

छ—नींदना † (<निङ्क्ते)=अङ्कुरितात् क्षेत्रात् तृणशोधने, तदपनयने।

√निद् (णिद्) १/८५६ शX
कुत्सासन्निकर्षयोः (उ) क्षी-मै-सा-जै-शा-हे।
सन्निकर्षे—च।
कुत्सासन्निकर्षणयोः—काक्र-कात।
सन्निधौ कुत्सने च—वो।
>√निव् (णिव्) कुत्सासन्निकर्षयोः (उ)। इति प्राच्यो हेवाकिनः—क्षी।
नेदति—निघ. २/१४=गतिकर्मा।

ग—निद्यमान०-ऋ.६,५२,३। अत्यनेदत्-मै. ३,१०,४। अभिनिनित्ससि-खि. ५,१५,४।

√निन्द् (णिदि) १/६३ शX
कुत्सायाम् (प) क्षी-मै-सा-च-काक्र-कात-शा-हे।
कुत्सने—जै-वो।
√निन्द् (निदि) १.६६ कुत्सायाम् (प)। इति मैत्रेयाभरणसम्मताकाराः—सा।

ग—निन्दात्-ऋ. ५,४२,१०; तै. ४,१,१०,३। निन्दति-तांब्रा. ५,५,१३।

+√निन्व् (निवि) १/५८५ मै-सा-श-जै-काक्र-कात-वोX
सेचने (प) क्षी-च-शा-हे।
'सेवने' इत्येके—क्षी।
√मिन्व् (मिवि) १/ सेचने (प)।
√निन्व् (णिवि) १/ सेचने (प) वो।

√निन्व् (णिवि) १/५९०....
स्रंसने—मै।
सेचने—सा-काक्र-कात।

[छ—निवान = जलाशयः, (२) पङ्किला जलाप्लुता वा भूः। (<निम्नम् ?)]
छ—√निवाना (<निन्वनम्)=स्रंसने, प्रलम्बे, नमने।

+√निल् (णिल) ६.८१ श-जैX
गहने (प) क्षी-मै-सा-च-काक्र-कात-शा-हे-वो।
निल् १/२५० r अदने (प) काक्र।
गहनम्=दुर्बोधः—दुर्गादा.।

छ—√नीरना † (<नेलनम्)=विकिरणे, विक्षेपे।
ज—नेल्-आद्=प्रमाणवैफल्ये।

+√निव् (णिवृ) १/८२६ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो× | कुत्सासन्निकर्षयोः (उ) इति प्राच्यो हेवाकिनः— क्षी। | <√निद् (णिदृ) कुत्सा-सन्निकर्षयोः (उ)।

+√निश् (णिश) १/७१४ श×,(जै—√निस्) | समाधौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। शीले—वो। | √निस् (णिसु) b१/२९५ सेचने (प) काकृ। √निस् (णिसु) १/२९५ सेचने (प) कात। √निस् (णिषु) १/सेके (प)। वो।

ग—निशा–गी. २,६९। विनिक्षे–मभाष्ये. ६,१,४५.$\frac{३}{३}\frac{१}{६}$।

√नी (णीञ्) १/८८६ श | प्रापणे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

ग—नयति–ऋ. ५,३४,६; तै. २,५,११,७। नयते–शौ. ५,१९,१५।
ङ—√णी (सक) = प्रापणे, (२) ज्ञाने। णेइ,णयइ–विसे. ९१४।
ङ—√णीण (सक) = प्रापणे–उत्त. १९,२२।

√नील् (णील) १/५२२ श-च-जै-शा = च-जै-शा√नील्[नील] | वर्णे (प) क्षी-मै-सा-काकृ-कात-हे-वो च-जै-शा। | √नील् १/२५०t अदने (प) काकृ। √निड १/१८६ निवासे (प) काकृ। √नीन् ८/३ सम्बोधने (उ) काकृ।

वर्णे = वर्णोपलक्षितायां क्रियायाम्—क्षी।

क—नेइ (लू) = प्रभायाम्, द्युतौ–वा. पॉकर्नीः।
ग—बभूव जलदं नीलं भित्त्वा चन्द्र इवोदयः–वा. रा. ३,५२,१९।
ज—नेद्′ = वर्णे।

+√नीव् (नीव) १/५६४ श× √नीव् (णीव) १/५६७– | स्थौल्ये (प) क्षी-च-शा-हे। मै-सा-जै-काकृ-कात-वो। | √तीव् (तीव) १/ स्थौल्ये (प)। √मीव् (मीव) १/ स्थौल्ये (प)।

√नु (णु) २/२४	स्तुतौ (प)	√नु १/५५१q शब्दे (आ) काक्त।
श	क्षी-मै-सा-च-जै-काक्त-कात-शा-हे-वो।	नवन्ते-ऋ. ९,८६,२५
		√नू (णू) ६/ स्तवने (प)। नवते—निघ. २/१४=गति-कर्मा। नौति-निघ. ३/१४=अर्चतिकर्मा।

ग—नवीनोत्-ऋ. ६,३,७। ओमोमिति प्रणौति-ऐब्रा. ५,३२। प्रणुयात्-शाङ्खा. ब्रा. ६,३,११। नोनुमः-अशि. ४,२०।

+√नु (णु) ६/११३	स्तवने (प) सा	√नू (णू) ६/११६ स्तवे (प)।
क्षी-मै-श-च-जै-काक्त-शा-हे-वो×	सा। स्तुतौ—कात।	

ह्रस्वान्तोऽयमिति वररुचिः-दुर्गादासः।
ग—√नू ६/११६ वत्।

√नुद् (णुद) ६/२	प्रेरणे (उ)	√नुड् ६/ वधे (प) वो।
जै-काक्त-शा×, श	क्षी-मै-सा-च-कात-हे-वो।	√नुणुम्ब् १/२०६gg मर्दने (प) काक्त।
नुद् (णुद) ६/१४४	प्रेरणे (प)	
श-च-कात-वो×	क्षी-मै-सा-काक्त-हे। क्षोदे—जै। शा ?	

ग—नुदस्व-ऋ. ९,५३,१। नुदते-तै. ५,४,२,२; शब्रा. १,९,३,११। नुदतु-खि. ४,५,३५।

+√नू (णू) ६/११६	स्तवे (प)	√नु (णु) ६/११३ स्तवने (प) सा।
श, (कात-√नु)	क्षी। स्तवने—मै-सा-जै-काक्त-कात-शा-हे-वो। स्तुतौ—च।	नवते—निघ. २/१४=गतिकर्मा। नौति-निघ. ३/१४=अर्चतिकर्मा।
		√नून् ८/४ निश्चये (उ) काक्त।

ग—गर्दभं नुवन्तम्-ऋ. १०,२९,५। न्यनुवीत्-मभाष्ये १,१,३,२. ७६। अदादौ तु 'न्यनावीत्' इति रूपं भविष्यति।

√नृत् (नृती) ४/८ जै×,श	गात्रविक्षेपे (प) क्षी-मै-सा-काकृ-कात-शा। नाट्ये--च। नर्तने—हे। नर्ते--वो।	√नट् (नट) १/नृत्तौ (प)। √नॄ १/८०२ नये (प) मित्।

ग—अनर्तिषुः-ऋ. १०,९४,४; काठ. ३५,१४; क. ४८,१३। नृतमानः-ऋ. ५,३६,६ तौदादिकः। नृत्यन्ति-शौ. १२,१,४१। नृत्यति-शांब्रा. २०,४।

ङ—√णच्च (अक)=नर्तने। वक्र-णच्चंत, णच्चमाण-सुर. २,७५; ३,७७।

छ—√नचना
छ—√नाचना } =नर्तने।

√नॄ १/८०२ श-शा×काकृ-√नॄ [णॄ] (कात-√नृ [नॄ])	नये (प) मित् क्षी-मै-सा-च-जै-काकृ-कात-हे। नीतौ—वो। क्रीडने—ह्वि.।	√नृत् (नृती) ४/गात्रविक्षेपे (प)।

ग—नृभिर्नृवन्तः-ऋ. ७, ४१,३। आपो नारा इति प्रोक्ता आपो वै नरसूनवः-मनु. १, १०।

√नॄ ९/२४ श (कात-√नृ)	नये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे नीतौ—वो।	√नॄ १/८०२ नये (प) मित्। √न्वी ९/नये (प) मै।
गणरहितः-	क्रीडने—ह्वि.।	
√नेद् (णेदृ) १/८५७ श×	कुत्सासन्निकर्षयोः (उ) क्षी-मै-सा-जै-शा-हे। सन्निकर्षे—च। कुत्सासन्निकर्षयोः—काकृ-कात। सन्निधौ कुत्सने च—वो प्रवाहे--ह्वि.।	√निद् (णिदृ) १/कुत्सासन्निकर्षयोः (उ)। √निन्द् (णिदि) १/कुत्सायाम् (प)। √नेव् (णेवृ) १/ कुत्सासन्नि- √कर्षयोः (उ)। नेदति-निघ. २/१४= गतिकर्मा।

ग—अति नेदन्ति (०नेदन्ते–बृहदारण्य. ३,१,८), अधिशेरते–शब्रा. १४,६, १,१०; तै. १६,८,१। नेदिष्ठो अस्या उषसो व्युष्टौ–ऋ. १,४,१,५।

काल्पनिके हि प्रकृतिप्रत्ययविभागे द्राघिमादयः कस्मिंश्चिद् व्याकरणे धातोरेव साधिताः, एवं नेदिष्ठादयो नेदत्यादेः–द्रष्ट. √द्राघ् १/११३–क्षी। नेदिष्ठः सन्निकर्षणार्थे चरितार्थः।

+√नेप् (णेपृ) १/६१२ श×	गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। व्रजे—वो।	√एप् (एपृ) १/गतौ (आ)।

ग—नेपति–ऋ. ५,४६,१,=नयने, प्रापणे। स नो नेपन्नेपतमैरमूरः–ऋ. १,१४१,१२। नेपणि–ऋ. १०,१२६,३।

+√न्वी ९/२५ क्षी-सा-श-च-जै-काकृ-कात-शा-हे-वो×	नये (प) इत्येके–मै मै।	<√नॄ नये (प)।
+√पक्ष् (पक्ष) १/६५६ श-च-जै-काकृ-शा-हे-वो×	परिग्रहे (प) इत्येके—क्षी क्षी-मै-सा-कात।	√पक्ष् १/५१७ विभागे (आ) काकृ। √पच् (डुपचष्) १/पाके (उ)।

ग—पक्षो वयो यथोपरि–ऋ. १,४७,२; दिवि मे अन्यः पक्षः–१०,११९,११।

+√पच् (पच) १/१७१ मै-श-च-जै-शा×	व्यक्तीकरणे (आ) इति दुर्गः—क्षी। क्षी-सा-काकृ-कात-हे। व्यक्तीकारे—वो।	<√पञ्च् (पचि) व्यक्तीकरणे (आ)।
√पच् (डुपचष्) १/९८ जै×,श	पाके (उ) क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।	√पच् (पच) १/१७१ व्यक्तीकरणे (आ)।

ग—पचति–ऋ. १०,८८,१०। पचते–शौ. १२,४,३८; पै. १३,५,१।

ङ—√पच=पाके। पचइ, पचए–संक्षि. ३०; पि. ४३६; ४५५।

छ—√पचना, √पचाना, √पकना, √पकाना।

+√पञ्च् (पचि) १/१७१ शकात×
व्यक्तीकरणे (आ)
क्षी-मै-सा-च-जै-काकृ-शा-हे।
व्यक्तीकारे--चो।

√पच् (पच) १/व्यक्तीकरणे (आ)।
√पञ्ज् १/३१३g गतौ (प) काकृ।
√पञ्च् (पचि) १०/विस्तारवचने (प)।

क—पञ्चुएँ=पञ्च।

ख—अवे. पञ्च=पञ्च-वा. पॉकर्नी:।

ग—ये के च कुरुपञ्चालानां राजानः-ऐब्रा. ८,१४। पञ्चालानाचक्षते-शब्रा. १३,५,४,७। पङ्के गौरिव सीदति-मनु. ४,१९१। पञ्चिका=न्यासः। रागप्रायः प्रपञ्चः-कादम्ब. १५१।

छ—√पंजना (<पञ्चनम्)=धातुपात्राणां टङ्कनैर्योजने, सन्धाने (अञ्जने)।

√पट् (पट) १/२९३ श
गतौ (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
विदारे--ह्वि.।

√पत् (पत्लृ) १/गतौ (प)।
√पद् (पद) ४/गतौ (आ)।

ग—पटु०-तेजोबिन्दूप. ४,२४ [धा. गतौ वृत्तिः]।

√पठ् (पठ) १/३२८ श
व्यक्तायां वाचि (प)
क्षी-मै-सा-जै-काकृ-कात-शा-हे।
उच्चारणे—च।
वाचि—वो।

√प्रथ् (प्रथ) १/प्रख्याने (आ)।
√पत् (पत्लृ) १/गतौ (प)।

ग—पठन्ति-तैआ. १०,४८,१; खि. ३,१०,१८।

ङ—√पठ। पठदि-शौ.; नाट-मृच्छ. १४०।

√पण् (पण) १/४३२ श
व्यवहारे स्तुतौ च (आ)
क्षी-मै-सा-जै-काकृ-कात-शा-हे।
व्यवहारे—च।

√पण् १/२०७ r शब्दे (प) काकृ।
√फण् १/२०७ शब्दे (प) काकृ।

व्यवहृतौ स्तुतौ—वो। पणायति-निघ. ३/१४= अर्चतिकर्मा। पणते-निघ. ३/१४= अर्चतिकर्मा।

ग—पणयः-ऋ. ६,२०,४। पणते-शब्रा. ३,३,३,१। पणायन्ति-जैउ. ३,३,३,३।

+√पण्ड् (पडि) १/२७९ गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो। √पण्ड् १/१६८ धारणे (प) काकृ। √पड्ड् १/१६४ मदे (प) काकृ। √पन्थ् (पथि) १०/गतौ (प)।
श

क—पेल्=प्रेरणे-वा. पॉकर्नीः।

ग—पण्डितम्मन्यमान०-मुण्डकोप. १,२,८। पण्डिताः-गी. ५,१७; छान्दो. ६, १४,२। गतिः=ज्ञानम्।

√पत् (पत्लृ) १/८२९ गतौ (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे। गमने—जै। गत्याम्—वो। √पद् (पद) ४/गतौ (आ)। √पट् (पट) १/गतौ (प)। √पथ् (पथे) १/गतौ (प)। पण्डको वा—निरु. ६,३२, १=तृतीया प्रकृतिः—दुर्गाचार्यः।
श

ग—पतति-ऋ. ६,७५,११; तै. ४,६,६,४; शब्रा. १४,७,१,२०।

√पत् (पत) ४/३८ ऐश्वर्ये (आ) इति द्रविडाः-क्षी। क्षी-मै-सा-हे। ऐश्ये गत्यां च—वो। <√पत् (पत) ऐश्वर्ये (आ)। पत्यते-निघ. २/२१=ऐश्वर्यकर्मा।
श-च-जै-काकृ-कात-
शा×

ग—अग्निर्देवेषु पत्यते-ऋ. ८,८१,९; २,३७,२; १,८४,९।

√पथ् (पथे) १/८३१ गतौ (प) ज्वलादिः क्षी-मै-सा-च-काकृ-कात-शा-हे-वो। गमने—जै। √पत् (पत्लृ) १/ गतौ (प)। √पद् (पद) ४/ गतौ (प)।
श×

न वास्तविको धातुः— गमने—ह्वि.।

क—पेन्नू (थ्)=गमने–वा. पॉकर्नीः।

ग—(अग्निः) स एवैनं पुनर्यज्ञपथमपि पाथयति–शाङ्खा. ब्रा. ४,३; शाङ्खा. श्रौ. १६,१०,९।

+√पद् (पद) १/४९ स्थैर्ये (प) इति कण्ठः–क्षी <√बद् (बद) स्थैर्ये (प)।
मै-सा-च-जै-काकृ- क्षी-वो।
कात-शा-हे×

√पद् (पद) ४/५८ श	गतौ (आ) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो।	√पत् (पत्ल) १/ गतौ (प)। √पथ् (पथे) १/ गतौ (प)। √फण् (फण) १/ गतौ (प)।

ग—पपाद–ऋ. १०,३४,२१। पद्यते–शौ. २०,१३६,३; शब्रा. ११,१,६,३२।

√पन् (पन) १/४३३ श	च=स्तुतौ (आ) क्षी-मै-सा-च-जै-कात- शा-हे। व्यवहारे स्तुतौ च— काकृ। ईडे—वो।	पनायते—निघ. ३/१४= अर्चतिकर्मा। पणायति—निघ. ३/१४= अर्चतिकर्मा। पणते—निघ. ३/१४= अर्चतिकर्मा।

ग—महिमानं पनायत–ऋ. ६,७५,६। पनिष्ट–ऋ. ७,४५,२।

√पय् (पय) १/४७२ श-च×(मै-√यय्) √पि....	गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात- शा-हे-वो। ह्वि.।	√पि ६/गतौ (प)। √वय् (वय) १/गतौ (प)।

ग—पयते–ऋ. १,१६४,२५। अपयात्–मभार. ४,५५,१७=गत्यभावादित्यर्थः (नील.)।

√पर्द् (पर्द) १/२८ श×	कुत्सिते शब्दे (आ)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। अपानोत्सर्गे—वो।

क—पेर्द्=अपानोत्सर्गे–वा. पॉकर्नीः।
ख—अवे. पूर्-दैति=अपानोत्सर्गे–वा. पॉकर्नीः।
छ—√पादना=अपानोत्सर्गे।

+√पर्प् (पर्प) १.४१३ गतौ (प) मै। क्षी-श-च-काकृ-कात-हे× मै-सा-जै-शा। √पर्ब् (पर्ब) १.गतौ (प) वो।

क—पेल्पॉ-अथवा-पॉल्पॉ=पर्पः, खञ्जकुक्षियष्टिः-वा. पॉकर्नीः।

+√पर्ब् (पर्ब) १/४१७ गतौ (प) मै क्षी-श-जै-शा× मै-सा-च-काकृ-कात-हे-वो। √पर्प् (पर्प) १/४१३ गतौ (प)। √बर्ब् (बर्ब) १/गतौ(प)। √पर्व् (पर्व) गतौ (प) वो।

छ—√पबारना=प्रेरणे (प्रक्षेपणे)।

+√पर्व् (पर्व) १/५७४ पूरणे (प) श-जै× क्षी-मै-सा-च-काकृ-कात-शा-हे। पूर्तौ—वो। √पृ ३/पालनपूरणयोः (प)। शेषः पूर्ववत्।

क—पेर्-वा. पॉकर्नीः।
ग—पर्वतं गिरिम्-ऋ. ५,५६,४। पञ्चपर्वा नदी-श्वेताश्वतरोप. १,५।

+√पर्ष् (पर्ष) १/६०८ स्नेहने (आ) सा-श-च-जै-शा× क्षी-मै-काकृ-कात-हे। स्नेहे—वो। √पृष् (पृषु) १/ सेचने (प)। √वृष् (वृषु) १/ सेचने (प)।

क—पेर्स्=सेचने-वा. पॉकर्नीः।

ग—खले न पर्षान् प्रति हन्मि भूरि-ऋ. १०,४८,७। पर्षत्-याज्ञ. १,९;३,३०१। भूतपर्षद्भिः-भा. पु. ३,१४,२३।

+√पल (पल) १/८२३ गतौ (प) श×(जै-√फल्) क्षी-मै-सा-च-काकृ-कात-शा-हे-वो। गमने—जै। √पिपल १/२४८ i चलने (प) काकृ। √पिप्पल १/२४८ j चलने (प) काकृ। √पल्ल् १/ गतौ (प) वो। √पत् (पत्ल) १/ गतौ (प)। परा+√अय्=√पल् [आय्]।

ग—दधिमधुपललविमृदित०—सुश्रु. १,१५८,१६ । पालिन्दी०—यशस्तिल. च., ३ आ., १९९ पृ.=लहरी० ।

+√पव् (पव) १/५०८ गतौ (आ) इत्यन्ये—मै । क्षी-सा-श-च-काकृ- मै-जै-शा-हे-वो । कात×

<√प्लेव् (प्लेवृ) गतौ (आ) । <√प्लव् (प्लव) गतौ (आ) इत्येके ।

√पश् (पश) १/८७२ बाधनस्पर्शनयोः (उ) स्वामि- काश्यपादयः—सा
क्षी-मै-श-च-जै-काकृ- सा-हे ।
कात-शा× बाधे ग्रन्थे—वो ।

उत्तरधातुवत् ।

'पश' इति सौत्रो धातुः—काशिका—७/४/८६ ।

ग—पशून्—ऋ. १०,९०,८ ।

+√पष् (पष) १/८७३ बाधनस्पाशनयोः (उ) इत्येके—क्षी
मै-श-च-जै× क्षी ।
बाधनस्पर्शनयोः—सा-काकृ-कात-शा-हे ।
बाधे ग्रन्थे—वो ।

<√स्पश् (स्पश) बाधनस्पाशनयोः (उ) ।
√पष् १/२९७ a धारणे (प) काकृ ।

+√पस् (पस) १/८७२ बाधनस्पर्शनयोः (प) सौत्रो धातुः—सा ।
क्षी-मै-श-च-जै- सा-हे ।
काकृ-कात-शा× बाधे ग्रन्थे—वो ।

पूर्ववत् ।

√पा १/९०९ पाने (प)
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।

√पै १/ शोषणे (प) ।
√पा २/ रक्षणे (प) ।

ग—पिबन्ति—ऋ. १,८४,१० । पिबति—तै. २,३,३,३; शौ. ५,१८,४ ।
ङ—√पा=पाने । भवि—पाहिसि—कप्प.; पि. ३१५ । कर्मणि—पिज्जइ—उव. ।
ङ—√पिब=पाने । पिबामो—पि. ४८३ ।
ङ—√पिव=पाने । पिवइ—पिंग. ।
ङ—√पिअ=पाने । पिअइ—गा. १६१ ।

ङ—√पत्र = पाने । भग. ७,६–पत्र. ३०५ ।
छ—√पीना = पाने ।

√पा २/४५ रक्षणे (प)
श क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे-वो ।

ग—पाति–ऋ. ३,५,५; तै. २,३,१३,३ ।
ङ—√पा (सक) = रक्षणे । पाइ, पाअइ–विसे. ३०,२५ ।

+√पि ६/१२४ गतौ (प) पीयतिर्हिंसाकर्मा–निरु.
श क्षी-मै-सा-च-जै-काक्र- ४,२५,५—पियारुम् – ऋ. ३,
(काक्र-कात–√रिप् कात-शा-हे-वो । ३०,८ ।
[रिपि]) √प्यै (प्यैङ्) १/ वृद्धौ (आ) ।

ग—अभिपित्वम्–ऋ. ४,१६,१; शौ. २०,७७,१; अपपित्वम्–३,५३,२४ । पियानः–ऋ. १,७९,३ = वृद्धौ ।

+√पिछ् (पिछ) ६/१८ उत्क्लेशे (प) इति <√मिछ् (मिछ) उत्क्लेशे (प) ।
मै-सा-श-च-जै-काक्र- द्रमिडाः—क्षी √पिछ् (पिछ) १०/ कुट्टने
कात-शा× क्षी-हे । (प) ।
बाधे—वो ।

ग—पिच्छ०–कात्या. श्रौ. १३,३,१३ । पिच्छल०–छान्दोग्यो. ८,१४; मभार. १,२१४७ । मायूरं पिच्छमच्छिनत्–अनर्घरा. ६,६५ ।

ङ—पिच्छ = लाङ्गूलम्–गउड. ।

+√पिञ्ज् (पिजि) २/१७ अव्यक्ते शब्दे (आ) इति √पिष् (पिष्लृ) ७/ सञ्चूर्णने
श-च-जै-काक्र-कात- कौशिकः–क्षी (प) ।
शा-हे× क्षी ।
वर्णे—मै-सा-हे ।
'अव्यक्ते शब्दे' इति
काश्यपः—सा ।
'सम्पर्चने' इति शाकटायनः
—सा ।
वर्णपूजयोः सम्पर्के [च]
—वो ।

क—पाइज्-तथा पाइक्=परिचयचिह्नम्, रञ्जितम्, वर्णयुतम्। लैति. पिंजो, पिंक्सि-वा. पॉकर्नी:।

ग—सिंहकेसरपिञ्जराः-वा. रा. ४,१,७९; वृत्तपिङ्गलनेत्रा हि-वा. रा. ६,२७, ४४२ (गी. प्रे. सं.)।

ङ—√ पिंज (सक)=पिचुशोधने (सध्वनि) तद्धनुषा।
छ—√ पींजना (सक)=पिचुशोधने।
छ—पीजन=पिचुशोधनधनुः।

+√ पिञ्ज् (पिजि) २/२० सम्पर्चने (आ) पूर्ववत्।
क्षी-मै-श-च-काक्र- सा-जै-शा-हे।
कात-वो× अव्यक्तशब्दार्थे—हे।

पूर्वधातोरभिन्नोऽर्थभेदार्थं पार्थक्यं नीतोऽयम्।

+√ पिट् (पिट) १/३०७ शब्दसंघातयोः (प) क्षी-मै-सा-काक्र-कात। संघाते—च। संघाते शब्दे च—जै-शा-हे। संहतौ ध्वनौ—वो।
श

√ पिड् (पिड) १/३१२ शब्दे (प)। √ पिट्ट् १/१२२ चलने (प) काक्र। परितः कुट्टनेन पांसूनवटेऽधः प्रवेशयति पिट्टयतीत्यर्थः—कात्या. श्रौ. ६,३,११। √ पिट्ट् धातुः पाणिनीये सम्प्रदाये नास्ति।

ग—कुद्दालदात्रपिटकम्—मार्क. पु. ५०,८६।

ङ—√ पिट्ट (सक)=ताडने (शब्दे)। पिट्टइ, पिट्टेइ—आचा.; पिंग; गा. १७१; सिरि. ६५५।

छ—√ पीटना=आहतौ।

+√ पिट् (पिट) १/३१२ शब्दे (प) अर्थभेदाद् द्विपाठः—क्षी।
मै-सा-श-च-जै-काक्र-कात-शा-हे-वो×

>√ पिड् (पिड) शब्दे (प) इत्येके—क्षी। शेषः पूर्ववत्।

ग—पूर्ववत्।

+√पिट् (पिट) १/३१३ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	आक्रोशे (प) इति मल्लः —क्षी क्षी।	√बिट् (बिट) १/ आक्रोशे (प) मै। √विट् (विट) १/ आक्रोशे (प) मै। √विड् (विड) १/ आक्रोशे (प)।

भट्टमल्लस्तु नाक्रोशार्थे पठति धातुम्—"अथ पेटति शब्दसंघातयोः"—आ. च. ३,३,६३—६४।

+√पिठ् (पिठ) १/३३६ श× (जै—पिठि) स्यात् त्रुटिः।	हिंसासंक्लेशनयोः (प) क्षी-मै-जै-काकृ-कात-शा-हे। हिंसासंक्लेशनयोः—सा। क्लिशि वधे—वो।	√पिठ् १/१४३ स्थितौ (प) काकृ।

ग—पिठीनस्—ऋ. ६,२६,६। सूर्यतप्तपिठराम्बुपायिनः—बृह. सं. २४,३०। गृह्णीष्व पिठरम्—मभार. ३,३,७२। पिठर०—आर्यासप्त. ५५२=गृहभेदः। पीठं दत्त्वा—मभार. ५,१३९९।

ङ—पिढर (<पिठरः) =भाजनविशेषः, स्थाली—आचा.; कुमा.।

ङ—पीढ=इक्षुनिष्पीडनयन्त्रम्—दे. ६,५१।

+√पिड् (पिड) १/३१२ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	शब्दे (प) क्षी।	√पिण् १/२०७ bb शब्दे (प) काकृ। √पीण् १/२०७ aa शब्दे (प) काकृ। √पुण् १/२०७ x शब्दे (प) काकृ।

ग—पिडकिन्—सुश्रु. १,८८,११।

+√पिण्ड् (पिडि) १/२७१ श	संघाते (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। संहतौ—वो।	√पिट् (पिट) १/ शब्दसंघातयोः (प)। √पिण्ड् १/१६९ धारणे (प) काकृ। √पिण्ड् (पिडि) १०/ संघाते (प)।

संहतिः = राशीकरणम्—दुर्गादासः ।

ग—पिण्डानां प्रजुहोम्यग्निम्—ऋ. १,१६२,१९ ।

ङ—पिंड / पेंड } (<पिण्डम्)—प्राप्र.; कुमा. ।

छ—पींड़ (<पिण्डम्) = (१) शरीरम्, पिण्डम्, (२) कस्यचनार्द्रवस्तुनो गोलः, (३) खर्जूरफलविशेषः ।

√पिन्व् (पिवि) १/५८३ सेचने (प) √पीव् (पीव) १/५६२
श-जै× क्षी-मै-सा-च-काकृ-कात- स्थौल्ये (प) ।
शा-हे-वो ।
'सेवने'—इत्येके—क्षी ।
स्थौल्ये—ह्वि. ।

ग—पिन्वति—ऋ. ९,७४,५; पिन्वते—१,५४,७ । पिन्वन्ति—ऐआ. १,२,१ ।

+√पिश् (पिशृ) १/७११ गतौ (प) इति सभ्याः– √पिस् (पिसृ) गतौ (प) ।
मै-श-च-जै-काकृ-कात- क्षी ।
शा-हे-वो× क्षी-सा ।
ग—पेशलं स्मरः–रघु. ११,४५ ।

√पिश् (पिश) ६/१५४ अवयवे (प) √पिश् (पिशृ) १/७११ गतौ
श क्षी-मै-सा-च-जै,काकृ (प) ।
(उ), कात-शा-हे । √पिष् (पिष्लृ) ७/ सञ्चूर्णने
(प) ।

ग—पिंशते—ऋ. ८,१९,२२ । पिंशतु—शब्रा. १४,९,४,२०; शौ. ५,२५,५ ।

√पिष् (पिष्लृ) ७/१५४ सञ्चूर्णने (प)
श क्षी-मै-सा-च-जै-काकृ-कात-
शा-हे ।
चूर्णने—वो ।

ग—पिनष्टि—ऋ. १०,१३६,७; शब्रा. १,२,१,१९ । पिण्ढि—शौ. १९,२९,६ ।
ङ—√पीस = सञ्चूर्णने । पीसइ—पि. ७६ ।
छ—√पीसना = चूर्णने ।

+√पिस (पिसृ) १/७११ गतौ (प) >√पिश् (पिशृ) गतौ (प)
श ? क्षी-मै-सा-च-जै-काकृ- इति सभ्याः—क्षी ।
कात-शा-हे । पिस्यति-निघ. २/१४=

	गत्याम्—वो।	गतिकर्मा। पेसुकं… पिस्यति–
४/	विस्तारे ?—ह्वि.।	शत्रा. १,७,३,१८। पिपिसुः—शत्रा. ९,५,१,१७।

ग—पिस्यति—शत्रा. १,७,३,१८—व्यत्ययेन श्यन्, इति निघ. २/१४ टीकायां देवराजयज्वा।

+√पी (पीङ्) ४/३३ श	पाने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√पा १/ पाने (प)। पीयति—ऋ. १,१४७,२= वृद्धौ वृत्तिः ? पीयति—तै. ४,२,३,४= आक्रोशहिंसादौ वृत्तिः।

ग—तदाऽपीयत तत्तेजो राजा वारिमयम्-मभार. ३,१३६११।
ङ—√पी (सक)=पाने-रयण. ५१।
छ—√पीना=(<पयनम्) पाने।

+√पील् (पील) १/५२१ श×	प्रतिष्टम्भे (प)। क्षी-मै-सा-जै-काकृ-कात-शा-हे। प्रतिष्ठायाम्—च। रोधे—वो।	√पीड् (पीड) १०/ गहने (प)।

ग—पीलु=फलविशेषः, रागविशेषः········?
ङ—√पील (सक)=पीडने। पीलइ-पि. २४०; कवकृ-पीलिज्जंत-श्रा. ६।

+√पीव् (पीव) १/५६२ श×	स्थौल्ये (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√पिन्व् (पिवि) १/ सेचने (प)। √प्यै (प्यैङ्) १/ वृद्धौ (आ)। √प्याय् (ओप्यायी) १/ वृद्धौ (आ)। √मीव् (मीव) १/ स्थौल्ये (प)।

ग—पीवः-ऋ. १०,८६,१४; खि. १५,१२; शौ. २०,१३१,१०। पीवः-शौ. ९, १२, १८।

(ङ—√पीण (सक)=पुष्टौ। पीणंति-राय. १०१)।

√पुट् (पुट) ६/८७ श

संश्लेषणे (प)।
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
श्लिषि—वो।
उन्मानादौ—ह्वि.।

√पुट् (पुट) १०/ संसर्गे (प) मै।

'पुटति' इति ह्वि.। मया नावाप्तम्। ओष्ठौ परिपुट्यते-सुश्रु. १,३०२, १४। करपुट०-मभार. १४,१९२८। प्रतिगृह्य पुटेनैव-मनु. ६,२८।

छ—√पोटना=समाहरणे, (२) हस्तगतीकरणे।

+√पुड् (पुड) १/३२० क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×

प्रमर्दने (प) इति शाकटायनः-सा। सा।

+√पुड् (पुड) ६/१०४ क्षी-श-च-जै-काकृ-कात-शा-हे-वो

उत्सर्गे (प) मै। मै-सा।

√मुड् (मुड) ६/१०२ उत्सर्गे (प) इत्यात्रेयः-सा।
√वुड् ६/१०८ उत्सर्गे (प) शा।
√बुड् ६/१३७ उत्सर्गे (प) हे।

+√पुण् (पुण) ६/५३ श×

कर्मणि शुभे च (प)।
क्षी।
कर्मणि शुभे—मै-सा-जै-शा।
शुभे—च-हे।
शोभे—काकृ-कात।
धर्मे—वो।

ग—शकुने भद्रमा वद पुण्यमा वद-ऋ. २,४३,२। निपुणं शुद्धिमिच्छताम्-मनु. ५,६१।

+√पुण्ड् (पुडि) १/३२० मै-श-च-काकृ-कात× जै-√घुण्ड् [घुडि]

प्रमर्दने (प) इत्येके—क्षी।
क्षी-सा जै-शा-हे।
मर्दे—वो।

<√मुण्ड् (मुडि) प्रमर्दने।
√मुट् (मुट) १/ प्रमर्दने इति दुर्गः-क्षी।

ग—पुण्ड्र०-ऐब्रा. ७,१८; मभार. १,४२२१।

+√पुण्ड् (पुडि) १/३२७ क्षी-श-च-जै-काकृ-कात-शा-हे-वो× | खण्डने (प) चेत्येके—मै। मै-सा। | √पुण्ड् (पुडि) १/१८३ हिंसागत्योः (प)। शेषः पूर्ववत्।

ग— मागधपुण्ड्रैश्च-हरिवंश. १५८५१। पुण्ड्रेक्षु०-राजत. ४,५००।

√पुथ् (पुथ) ४/११ श-जै× | हिंसायाम् (प)। क्षी-मै-सा-च-काकृ-कात-शा-हे। हिंसे—वो। | √पुन्थ् (पुथि) १/ हिंसासंक्लेशनयोः (प)।

ग—कीचकस्याहं पोथयामि यदा शिरः-मभार. ४,६४३ (स्वार्थप्रयोज.)।

+√पुन्थ् (पुथि) १/४२ श-च× | हिंसासंक्लेशयोः (प)। क्षी-जै-कात-शा-हे। हिंसायाम्—काकृ। हिंसासंक्लेशनयोः—मै-सा। कुन्थे—वो। | √पुथ् (पुथ) ४/ हिंसायाम् (प)। √बुन्थ् १/७ e हिंसासंक्लेशयोः (प) काकृ। √बुन्ध् १०/७५b हिंसायाम् (प) काकृ।

[ग—भिक्षोर्नहि नखवृद्धेः फलमपरं पुन्दकण्डूतेः-यशस्ति. च., ३ आ., २५२ श्लो.=नितम्ब०।]

[छ—पोंद (<पुन्दम्) = नितम्बः-बुं. ख.। बं. पाँद ?।]

+√पुर् (पुर) ६/६६ श× | अग्रगमने (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। अग्रगत्याम्—वो। | √पुल् (पुल) १/ महत्त्वे (प)। √पॄ ३/ पालनपूरणयोः (प)।

ग—पुरा पुरं समिदम्-ऋ. १,५३,७।

+√पुर्व् (पुर्व) १/५७६० क्षी-श-च-जै-काकृ-कात-शा-हे-वो× | पूर्तौ (प) मै। मै। पूरणे—सा-कात। | √पूर्व् (पूर्व) १/ पूरणे (प)। √पॄ ३/ पालनपूरणयोः (प)।

ग—अधिगच्छ दिशं पूर्वाम्-वा. रा. ४,४०,१९ (गी. प्रे. सं.)।

(ङ—√पुव्व=गतौ। पुव्वंति-भग. १५-पत्र. ६७०; टी.-पत्र. ६७३. [<√प्लु?])

ङ—पुव्व (<पूर्वम्)-ठा. ४,४; जी. १।
ङ—पुरव (<पूर्वम्)-गउड.।

+√पुल (पुल) १/८२५ शX	महत्त्वे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√पुर् (पुर) ६/ अग्रगमने (प)। √पुल (पुल) १०/ समुच्छ्राये (प)।

ग—पुलस्त्यं पुलहम्-मनु. १,३५। पुलस्त्य०-अ. वे. प्राति. ९१,२। कोद्रवाः पुलकास्तथा-मभार. १३,४३६३। पुलोमा = दैत्यविशेषः—हरिवंश. २०,१३४। पुलिन्द० बृह. सं. ४,२२; वा. पु. ४३ अध्याये।

ङ—√पुल (अक)=उन्नतौ-दस. १०,१६।

ङ—पुलिण=तटम्-पउम. [१०,५४;] (अनवरतं) द्वाविंशतिवासरान् यावदुपवासः-संबोध. ५८।

√पुष् (पुष) १/६९१ शX	पुष्टौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√पुष् (पुष) ४/पुष्टौ (प)। √पुष् (पुष) ९/पुष्टौ (प)। √पूष् (पूष) १/वृद्धौ (प)।

ग—√पोषति प्रजा रसानुप्रदानेन-निरु. १०,३४,१। पोषस्व-खि. ४,९,४।
छ—√पोषना—,√पोखना,√पोसना।

√पुष् (पुष) ४/६९ श	पुष्टौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	पूर्ववत्

ग—पुष्यति-ऋ. १,८३,३; तै. २,१,९,४। अयं तौदादिकोऽपि—सहस्रपोषं पुषेयम्-मा. ४,२६; का. ४,९,२। पुषन्तः-पारमात्मिको. ९,५।

√पुष् (पुष) ९/५७ श	पुष्टौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	पूर्ववत्।

ग—पुष्णामि–गी. १५,१३ । पुष्णाति–मभार. ३,६५०; ३,२५०६; ३,२६०२ ।

+√पुष्प् (पुष्प) ४/१४ श	विकासे (प) क्षी । विकसने—मै-सा-च-जै-काकृ-कात-शा-हे । फुल्लने—वो ।	पूर्ववत् । √पुष्प् १/४९ k गतौ (प) काकृ । √पुष्क् १/४१२ k गतौ (प) काकृ ।

ग—कालेन पुष्प्यन्ति नगा वनेषु–मभार. १२,७३९ । पुष्प्यन्ति च फलन्ति च–हरिवं. १२७९९ ।

स्यात् कण्ड्वादिगणान्तर्गतं मत्वा ह्विट्नीमहाशयेनोपेक्षितः ।

+√पुस् (पुस) ४/१०२ मै-सा-श-च-जै-काकृ-कात×	विभागे (प) इत्येके–क्षी क्षी-शा-हे-वो ।	<√प्युस् (प्युस) ४/विभागे (प) । √प्युष् (प्युष) ४/विभागे (प) । √पुष् ४/५२ विभागे (प) काकृ, ५४ कात ।
√पू (पूङ्) १/९५१ श-काकृ–√पु	पवने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । शोधे—वो ।	पवते–निघ. २/१४= गतिकर्मा । √पू (पूञ्) ९/पवने (उ) ।

ग—पवते–ऋ. २,१६,५; तै. ४,६,१,४ ।

+√पू (पूञ्) ४ (९/१०) मै-सा-श-च-जै-काकृ-कात-शा-हे×	पवने (उ) क्षी । शोधे (आ)—वो	पूर्ववत् ।

ग—पूयते–ऋ. ९,८६,१२ । पूयन्ते सत्यसाक्षिणः–मनु. ८,२५७; पूयन्ते–८,३११ ।

√पू (पूञ्) ९/१० श	पवने (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । शोधे—वो ।	पूर्ववत् ।

ग—पुनाति-ऋ. १,१६०,३; मा. १,९,४। पुनीते-मै. १,५,६; काठ. २३,१।

ङ—√पुण=(१) पावित्र्ये, (२) धान्यस्य तुषराहित्ये (अवहनने)। पुणंति-णाया. १,७।

√पूय् (पूयी) १/४८१ विशरणे दुर्गन्धे च (आ)।
श× क्षी-मै-सा-काक्र-कात।
विशरणे—च।
दुर्गन्धविशरणयोः—शा-हे।
दुर्गन्धशीर्ण्योः—वो।
दुर्गन्धिविशरणयोः—जै।

ग—पूयति-तै. ५,३,१,१; शब्रा. ४,१,१,३। अपूयीत्-जैब्रा. १५७। ह्विट्नी-महाशय इमं भ्वादौ स्वीकृतवान्। दिवादौ कुतो नाङ्गीकृतवान् √प्यायादि-(१।४८५)-धातुवत्!

ङ—पूअ (<पूयः)-पण्ह. १,१; णाया. १,८।

ङ—पूअ=दधि-दे. ६,५६।

√पूर् (पूरी) ४/४१ आप्यायने (आ)
श क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
पूर्तौ—वो।

√पॄ ३/पालनपूरणयोः (प)।
√पूर्ण् (पूर्ण) १०/संघाते (प)।

ग—पूर्येथाम्-वा. सं. ५,२८। अभि नः पूर्यतां रयिः-पार. गृ. ३,४। कुम्भस्य पूर्यतः-वा. रा. २,६३,२१।

छ—पूजना (<पूर्य[ते])=आप्यायने, पूर्तौ।

+√पूर्व् (पूर्व) १/५७३ पूरणे (प)
मै-सा-श-जै-कात× क्षी-च-काक्र-शा-हे।
पूर्तौ—वो।
उदाहरणं √पुर्व् (पुर्व) १/५७६ वत्।

√पॄ ३/पालनपूरणयोः (प)।
√पर्व् (पर्व) १/पूरणे (प)।
√पुर्व् (पुर्व) १/पूरणे (प) मै।

+√पूल् (पूल) १/५७८ संघाते (प)
श× क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
संहतौ—वो।

√पुण् (पुण) १०/संघाते (प) सा।
√पूण् (पूण) १०/संघाते (प) जै।
√पूर्ण् (पूर्ण) १०/संघाते (प)।

ग—पूलक०–का. श्रौ. २२१,१ (=तृणसंहति०)। पूल्य०–अ.वे. १४,२,६३।
ङ—पूल=तृणसंहतिः–उप. ३२० टी; कुप्र. २१५।
छ—पूला पूरा } =तृणसंहतिः–वुं.ख.।

+√पूप् (पूष) १/६६८ वृद्धौ (प) द्र.√पुष् १/६९१।
श×(काक्रु–√पुप्) क्षी-मै-सा-च-जै-काक्रु-
काता-शा-हे-वो।

ग—पूषा–ऋ. ३,६२,९। पूषणस्य–ऋ. १०,५,५। पूषेम–शौ. १९,६७,५।

√पॄ ३/४ पालनपूरणयोः (प) <√पृ पालनपूरणयोः (प)।
श-च-जै-काक्रु-शा× ह्रस्वान्तोऽयमिति नन्दी–क्षी।
क्षी-मै-सा-कात-हे।
पालने पूर्तौ—वो।

ग—पिपर्तन–ऋ. १,१५६,३; पूर्धि–१,४२,९। पिपर्ति–ऐब्रा. ३,२५; गोब्रा. २,६,१४।

√पॄ ५/१२ प्रीतौ (प)
श क्षी-मै-सा-च-जै, काक्रु (उ),-
कात-शा-हे-वो।
व्यापृतौ—ह्वि.।

ग—यदिन्द्रियप्रीतय आपृणोति–भा. पु. ५,५,४; व्यापृण्वानं यतोऽबुधः–१,११,३७।

+√पृ (पृङ्) ६/१२१ व्यायामे (आ) √पॄ ३/ पालनपूरणयोः (प)।
श (काक्रु–√प्री) क्षी-मै-सा-च-जै-काक्रु-
(कात–√वृ [वृङ्]) कात-शा-हे।
व्यायामके—वो।
५/ ह्वि.।

ग—मा व्यापृतः परकार्येषु भूस्त्वम्—मभार. २,२१२६।
ङ—√वावर (अक)=व्यापृतौ। वावरइ–भवि.।
ङ—वावड (<व्यापृतः)—कस.; सुर. १,९। वावड—(<व्यापृतः) उपप्र. ८७।
ङ—शौरसे.–वापिद (<व्यापृतः)–नाट–वेणी. ६७।

+√पृच् (पृची) २/१९ शX	सम्पर्के (आ) क्षी-मै-च-काकृ-कात-वो । सम्पर्चने—सा-जै-शा-हे ।	>√पृञ्च् (पृचि) सम्पर्के (आ) इति कौशिकः-क्षी । √पृञ्ज् (पृजि) २/ सम्पर्चने (आ) शाकटायनोऽपि-सा । √पृज् (पृजी) २/ सम्पर्चने (आ) इत्यपरे-सा । √पृच् (पृची) ७/ सम्पर्के (प)।

ग—यं सीमकृण्वन्तमसे विपृचे-(चतुर्थी ?)-ऋ. ४,१३,३ ।

√पृच् (पृची) ७/२५ श	सम्पर्के (प) क्षी-मै-सा-च, काकृ (उ), कात-शा-हे-वो । सम्पर्चने—जै ।	पूर्ववत् पृणक्षि—निघ. ३/२०=दानकर्मा

ग—पृञ्चन्ति-ऋ. १०,१४,१३ । पृणक्ति-शब्रा. ७,३,१,३०; काठ २१,६ । काशकृत्स्नमतेनोभयपदित्वात्-सम्पृङ्क्ते-ऋ. ७,१०३,४ इत्यपि ।

+√पृज् (पृजी) २/२० क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वोX	सम्पर्चने (आ) सा । सा ।	द्रष्ट.√पृच् २/१९ ।

+√पृञ्च् (पृचि) २/१९ मै-च-जै-काकृ-कात-शा-हे-वोX, श	सम्पर्के (आ) इति कौशिकः—क्षी क्षी । सम्पर्चने—सा । दुर्गकाश्यपनन्दिधन-पालादयः—सा ।	पूर्ववत् ।

ग—क्रतुभिर्न पृङ्क्ते-ऋ. १०,९५,१; मध्वा पृञ्चे नद्यः—६,१२,३ । रुधादाव-स्योभयपदित्वेन तत्रैव गतार्थता ।

+√पृञ्ज् (पृजि) २/१९ क्षी-श-च-जै-काकृ-कात-शा-हे-वोX	वर्णे (आ) इत्येके-मै मै-सा ।	√पिञ्ज् (पिजि) २/ वर्णे (आ) मै । √पिञ्ज् (पिजि) २/ अव्यक्ते शब्दे (आ) ।

+√पृञ्ज् (पृजि) २/२० क्षी-मै-श-च-काक्र-कात-वो ×	सम्पर्चने (आ) शाकटायनोऽपि—सा सा-जै शा-हे।	√पिञ्ज् (पिजि) २/२० सम्पर्चने (आ) सा।
+√पृड् (पृड) ६/४९ श	सुखने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। मुदि—वो।	√पृण् (पृण) ६/ प्रीणने (प)। √मृड् (मृड) ६/ सुखने (प)।
√पृण् (पृण) ६/५० श (काक्र-√तृण्)	प्रीणने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। तृपि—वो।	√पृड् (पृड) ६/ सुखने (प)। √प्री (प्रीङ्) ४/ प्रीतौ (आ)। √प्री (प्रीञ्) ९/ तर्पणे कान्तौ च (उ)। √पृण् १/२०८ c अपनयने (प) काक्र।

ग—पृणति–ऋ. ३,३६,६। पृणस्व–मा. ५,१९; तै. १,७,१३,४; शौ. २,५,२।

+√पृथ् (पृथु) १/७५८ मै-श-जै-काक्र-कात-शा-हे-वो ×	विस्तारे (आ) क्षी-च। प्रख्याने—सा।	√प्रथ् (प्रथ) १/ प्रख्याने (आ)। √पृत् १/६६८ c व्याप्तौ (उ) काक्र। √पृथ् १/६६८ b व्याप्तौ (उ) काक्र।

"प्रथिम्रदिभ्रस्जां सम्प्रसारणम्"–उणा. १/२८ इति वचनादनार्षममुं मन्यन्ते–क्षी।

ग—द्यावा पृथिवी–ऋ. ४,५६,१।

√पृष् (पृष) १/६९६ श ×	सेचने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। हिंसासंक्लेशनदानेषु—इति काश्यपः—सा।	√वृष् (वृषु) १/ सेचने। √पृष् १/४०२० गतौ (प) काक्र। √मृष् (मृषु) १/ सेचने (प)। √स्पृश् (स्पृश) ६/ संस्पर्शे (प)।

ग–पर्षते–गोगृ. ३, ३, १५। इषुपर्षिन्–शत्रा. १३, ४, २, ५। दाता मे पृषती-नाम्–ऋ. ८, ५४, १०। पृषत् –अ.वे. १, २३, २। खले न पर्षान् प्रतिहन्मि भूरि–ऋ, १०, ४८, ७,–निरु. ३, १०, १=सञ्चितवान्—दुर्गाचार्यः।

√पॄ ३/४ शा-कात×	पालनपूरणयोः (प) क्षी-मै-सा-काकृ-कात-शा-हे। पालने—च। पालनपूरणे—जै। पालनपोषणयोः—काकृ। पालने पूर्तौ—वो।	>√पॄ पालनपूरणयोः (प) इति नन्दी—क्षी। √पॄ ९/ पालनपूरणयोः (प)। √पार् (पार) १०/ कर्मसमाप्तौ (प)। √पूरी (पूरी) ४/ आप्यायने (आ)।
√पॄ	ह्वि.।	

ग—पिपर्ति–खि. ५, २०, ३; मै. १, २, ८; काठ. २, ९।
च—√पुर (सक)=पूरणे। पुरह्–पिंग. (प्रयोज.)।

√पॄ ९/१७ कात×,श	पालनपूरणयोः (प) क्षी-मै-सा-शा-हे। पालने—च। पालनपूरणे—जै। पालनपोषणयोः–काकृ (उ)। पालने पूर्तौ—वो।	पूर्ववत्।

ग—पृणीतः–ऋ. १०, ११७, ९। पृणाति–शौ. ६, २२, ३।

√पेव् (पेवृ) १/३७२ क्षी-सा-श-जै-काकृ-कात-शा-हे-वो×	सेवने (आ) मै। मै। गतौ—च।

+√पेल् (पेलृ) १/५४० श×	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गतौ चाले च—वो।	पेलयति–निघ. २/१४=गतिकर्मा। पिपीलिका पेलतेर्गतिकर्मणः–निरु. ७, १३। √फेल् (फेलृ) १/गतौ (प)। √पेण् १/१५१ गतौ (प) च।

ग—पुष्पपेलव०-कथास. २१, ९७।

ङ—√उत्पेल (<उत्+√पेल्)=उच्चैः करणे, उन्नतौ। उप्पेलिअ-कुमा.।

छ—√पेलना (<पेलनम्)=प्रेरणे, प्रवेशे। √पीड्धातोर्व्युत्पादनापेक्षया प्रकृतधातोर्व्युत्पादने लाघवम्।

+√पेव् (पेवृ) १/५०४ श×	सेवने (आ) क्षी-च-जै-शा-हे। सेचने—मै-सा-काकृ-कात। सेवे—वो।	√प्लेव् (प्लेवृ) १/ सेवने (आ)। √मेव् (मेवृ) १/ सेवने (आ)।
+√पेश् (पेशृ) १/७१२ मै-श-च-जै-काकृ-कात-शा-हे-वो×	गतौ (प) इति सभ्याः-क्षी क्षी-सा।	<√पेस् (पेसृ) गतौ (प)। √पिस् (पिसृ) १/गतौ(प)। √पिश् (पिशृ) १/ गतौ (प)।

ग—एकोन्मीलनपेशलः-उत्तरराम. ६, ३४।

+√पेस् (पेसृ) १/७१२ श×	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।	>√पेश् (पेशृ) गतौ (प)। इति सभ्याः—क्षी। शेषः पूर्ववत्।

ग—पेसुकः-शब्रा. १,७,३,१८।

+√पै १/९०५ श×	शोषणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। शोषे—वो।	√पा १/ पाने (प)। √वै (ओवै) १/ शोषणे (प)।

ग—क्षरन्नापो न पायनाय राये सहस्राय-ऋ. १,११६,९।

+√पैण् (पैणृ) १/४५० श-च-काकृ-कात-वो×	गतिप्रेरणश्लेषणेषु (प) क्षी-मै-सा-जै-शा-हे।	√पेण् १/१५० गतिप्रेरण-श्लेषणेषु (प) कात। √पेण् १/१५१ गतौ—च। √प्रेण् १/२१३ a गतिप्रेरण-श्लेषणेषु (प) काकृ। √फ्रेण् १/२१३ b गति-प्रेरणश्लेषणेषु (प) काकृ।

ङ—√पेल्ल (सक)=प्रेरणे, क्षेपणे। कर्म-पेल्लिज्जइ-उव.।

छ—√पेंडना } (< पैणनम्)=प्रेरणे।
छ—√बेंड़ना }

छ—पैंणा, पैंड़ा=मार्गः, (२) सादी, (३) प्रणाली।

√प्याय् (ओप्यायी) १/४८५ वृद्धौ (आ)		√प्यै (प्यैङ्) १/ वृद्धौ (आ)।
श×	क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√स्फाय् (स्फायी) १/ वृद्धौ (आ)।
४/	ह्विट्नीः।	

ग—प्यायताम्-शब्रा. ३,४,३,१८। पिप्यताम्-ऋ. ६,५०,१२। प्यायन्ति-जैब्रा. ४८।

+√प्युष् (प्युष) ४/१०२ विभागे (प) इति दुर्गः—		<√प्युस् (प्युस) विभागे (प)।
मै-सा-श-जै-काकृ-कात-	क्षी।	√पुस् (पुस) ४/१०२ विभागे। (प) इत्येके-क्षी।
शा×	क्षी-च-हे।	√प्युष् (प्युष) १०/१४० उत्सर्गे (प) हे।
	दाहे भागे च—वो।	√व्युस् (व्युस) ४/ विभागे (प) सा।
		√व्युष् (व्युष) ४/ विभागे (प) मै-सा।
		√बुस् (बुस) ४/ विभागे (प) सा।

अपि +√उष् (उष) १/ दाहे (प)=अप्युष्। "वष्टिभागुरिरल्लोपम्" इत्यकारलोपे सति √प्युष् इति धातुर्निष्पद्यते। वोपदेवमतेन दाहार्थकोऽप्ययमिति वयम्।

+√प्युस् (प्युस) ४/६	विभागे (प)	
मै-सा-श-च-जै-काकृ-	क्षी।	
कात×	दाहे—शा-हे।	पूर्ववत्।
	दाहे विभागे च—वो।	

+√प्युस् (प्युस) ४/१०२ विभागे (प) पुषादिः >√प्युष् (प्युष)विभागे (प)।
मै-सा-श-च-जै-काकृ- क्षी।
कात-शा-हे× दाहे विभागे – वो।

√प्यै (प्यैङ्) १/९४९ वृद्धौ (आ) √प्याय् (ओप्यायी) १/
श× क्षी-मै-सा-च-जै-काकृ- वृद्धौ (आ)।
कात-शा-हे-वो।

ग—तत आप्यायसे पुनः-ऋ. १०,८५,५। आप्यायन्ते पुनः पुनः-मभार.
.१४,९८९।

√प्रच्छ् (प्रछ) ६/१३२ ज्ञीप्सायाम् (प) पृच्छति—निघ. ३/१४=
श क्षी-मै-सा-कात-शा-हे। अर्चतिकर्मा।
प्रश्ने—च।
ज्ञीप्सने—जै।
ईप्सायाम् (ज्ञीप्सायाम्)
—काकृ।
ज्ञीप्से—वो।

ग—पृच्छते-ऋ. ९,८९,३। पृच्छति-तै. ६,३,१०,१; शब्रा. १,७,१,१७।
ङ—√पुच्छ (सक)=प्रश्ने। भूका.-पुच्छे-पि. ५१६; कुमा.; भग.।

√प्रथ् (प्रथ) १/७५७ प्रख्याने (आ) √पृथ् (पृथ) १/ प्रख्याने
श× क्षी-मै-सा-काकृ-कात-शा-हे। (आ) सा।
विस्तारे—च।
प्रख्यातौ—जै।
प्रक्षेपे ख्यातौ च—वो।

ग—प्रथते वृषायते-ऋ. १०,९४,९। प्रथते-तैब्रा. १,४,१०,९।

+√प्रस् (प्रस) १/७५९ विस्तारे (आ) इति √प्रथ् (प्रथ) १/७५७
श-च× दुर्गः—क्षी। प्रख्याने (आ); विस्तारे—
क्षी-मै-सा-जै-काकृ- च।
कात-शा-हे।
प्रसवे—क्षी-हे।
सवे ततौ—वो।

√प्रा २/५० श	पूरणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । पूर्तौ—वो ।	√पॄ ३/ पालनपूरणयोः (प) ।

ग—प्रासि-ऋ. १,४२,९; पप्रतुः-८,४१,९; पप्रौ-१,८१,५; १,११५,१ ।

√प्री (प्रीङ्) ४/३५ श×	प्रीतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√प्री (प्रीञ्) ९/ तर्पणे कान्तौ च (उ) ।
४/ कर्मणिवा···	ह्वि. ।	

ग—त्वं तु निष्कारणादेव प्रीयसे-वा. रा. ६,१०,२३; मां प्रीयते कश्चित्—२,१७,३२ । प्रीयामो दर्शनेन वः-मभार. ३,१५०२५ ।

√प्री (प्रीञ्) ९/२ श	तर्पणे कान्तौ च (उ) क्षी-मै-सा-काकृ-कात-वो । तृप्तिदीप्त्योः—जै । तर्पणे—च । कान्तितर्पणयोः—शा । तृप्तिकान्त्योः—हे ।	√प्री (प्रीञ्) १०/ तर्पणे (उ) ।

ग—प्रीणीते-ऋ. ७,७,३ । प्रीणाति-तै. २,६,६,४ ।

√प्रु (प्रुङ्) १/९४२ श	गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । सर्पणे—वो ।	√प्लु (प्लुङ्) १/ गतौ (आ) । प्रवते-निघ. २/१४ ।

ग—अभिप्रवन्त समनेव योषाः-ऋ. ४,५८,८ । अत्यप्रवत-तै. ७,१,१,२ ।

+√प्रुष् (प्रुष) १/६९४ श×	दाहे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।	प्र+√उष् (उष) १/ दाहे (प) । √प्लुष् (प्लुष) १/ दाहे (प) ।

ग—प्रोष्ट० ?-खि. ४,५,२३ [सपा. खिसा. २९,२३ प्रोथ इति पाभे.]

√प्रुष् (प्रुष) ९/५५ श	स्नेहनसेचनपूरणेषु (प) क्षी-हे । स्नेहनमोचनपूरणेषु—मै । स्नेहनसेवनपूरणेषु—सा । स्नेहसेचनपूरणेषु—काकृ- कात-शा । स्नेहने—च । स्नेहनसेचनसेवनपूरणेषु—जै । स्नेहे सेकपूर्त्योश्च—वो ।	

ग—'प्रुष्णन्तु' इत्युदाहृतवान् ह्वि. । मया नावाप्तम् । प्रुष्णते–मा. २२, २६; तै. ७, ५, ११, २ । सौवादिकोऽपि—प्रुष्णुवन्ति–ऋ. १, १६८, ८ ।

अ+√प्रेण् (प्रेण) १/२१३a क्षी-मै-सा-श-च-जै- कात-शा-हे-वो×	गतिप्रेषणश्लेषणेषु (प) काकृ ।	द्र. √पैण् (पैणृ) १/४५० । √प्रैण् (प्रैणृ)१/ गति- प्रेरणश्लेषणेषु (प) सा ।

पा
णि
नी
यः

ग—प्रेणिम् आवतम्–ऋ. १,११२,१० ।

+√प्रेष् (प्रेषृ) १/६१४ मै-श-च-जै-काकृ-कात- शा-हे-वो×	गतौ (आ)	√एष् (एषृ) १/ गतौ (आ) ।
+√प्रैण् (प्रैणृ) १/४५४ क्षी-मै-श-च-जै-काकृ- कात-शा-हे-वो×	गतिप्रेरणश्लेषणेषु (प) इति क्वचित् पठ्यते–सा । सि. कौ. ४५८ ।	द्रष्ट.√ पैण्—१/४५० ।
+√प्रोथ् (प्रोथृ) १/८५२ श×	पर्याप्तौ (उ) क्षी-मै-सा-च-जै-कात- शा-हे । पर्यापणे—वो । काकृ ?	√प्रुथ् १/६६८ व्याप्तौ (उ) ।
√प्रुथ्……	नासाशब्दे—ह्वि. ।	

ग—प्रोथत्—ऋ. ७,३,२; तै. ४,४,३,३। प्रोथन्तम्–ऋ. १०,११५,३; पोप्रुथत्–१,३०,१६=शब्दे। नार्थसंवादः।

+√प्लक्ष् (प्लक्ष) १/८७८ मै-श-च-जै-काकृ-कात-शा-हे×	भक्षणे (उ) इति दुर्गः–क्षी क्षी-वो। अदने—सा।	√भ्लक्ष् (भ्लक्ष) १/ भक्षणे (उ)।

सायणस्तु धातुमिममनार्षमाह–'प्रक्षरतीति प्लक्षः' इति प्रपूर्वात् क्षरतेः प्लक्ष-शब्दस्य भाष्यकारेण व्युत्पादितत्वात् (अयं धातुः) अनार्ष एव–१/८७७ सा।

इत्थं तु बहवो धातवोऽनार्षाः सेत्स्यन्ति। तत्र तत्र सायणेन कुतो न विचारः कृतः?

ग—प्लक्षः–तैब्रा. ३,८,१९,२।

+√प्लव् (प्लव) १/५०८ क्षी-श-च-जै-काकृ-कात-शा-हे-वो×	गतौ (आ) इत्येके–मै। मै-सा।	<√प्लेव् (प्लेवृ) गतौ (आ)। √पव् (पव)१/गतौ (आ) इत्यन्ये–मै। √प्लु (प्लुङ्) १/ गतौ (आ)।

ग—प्लवते–ऐब्रा. ६,३०। क्ते 'प्लवित'-रूपं दृष्ट्वैव शक्यते स्वीकर्तुम्, 'प्लवते' इत्यस्य प्लुङ्धातुनापि सिद्धत्वात्।

√प्लिह् (प्लिह) १/६३४ श×, (च-शा√प्लीह्)	गतौ (आ)। क्षी-मै-सा-च-जै-कात-शा-हे। वक्रगतौ—काकृ। गत्याम्—वो।

क—(स्) प्लेइघ्=विस्तारे–वा. पॉकर्नीः।

ग—प्लिहा (प्लेहते=वृद्धिं गच्छतीति)=प्लीहरोगः। यथा याज्ञवल्क्ये ३,९४–"नाभिः क्लोम यकृत् प्लिहा"।

√प्ली ९/३४ क्षी-श-च-जै-काकृ-कात-शा-हे-वो×	गतौ (प) मै। मै-सा।	√व्ली ९/ वरणे (प)।

ग—'विप्लीयन्ते' इत्युदाहरति ह्वि.।

√प्लु (प्लुङ्) १/९४३ श	गतौ (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। सर्पणे—वो।	√प्रु (प्रुङ्) १/ गतौ (आ)।

ग—प्लवते-ऋ. १०,१५५,३; पै. ६,८,७।

√प्लुष् (प्लुषु) १/६९५ श×	दाहे (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। दहि—वो।	√प्रुष् (प्रुष) १/६९४ दाहे (प)।

ग—प्लोषति-इति ह्वि.। मया नाधिगतम्। विप्लुष्ट०—वा. रा. २,१२५,९। मदनप्लोषणम्—मालतीमा. १।

+√प्लुष् (प्लुष) ४/७ च-जै-काक्र-कात-शा-वो×, श	दाहे (प) क्षी-मै-सा-हे।	पूर्ववत्।

ग—उत्तरधातुवत्।

+√प्लुष् (प्लुष) ४/१०३ श-शा×	दाहे (प) पुषादिः क्षी-मै-सा-च-जै-काक्र-कात-हे। दहि—वो।	पूर्ववत्।

ग—प्लुष्यते (कर्मणि ?)-सुश्रु. १,३७,१; प्लुष्ट०—बृह. सं. ५,९४,३६।

+√प्लुष् (प्लुष) ९/५६ श	स्नेहसेचनपूरणेषु (प) क्षी-हे। स्नेहनमोचनपूरणेषु—मै स्नेहनसेवनपूरणेषु—सा। स्नेहने—च। स्नेहनसेचनसेवन-पूरणेषु—जै।	√प्रुष् (प्रुष) १/ स्नेह-सेचनपूरणेषु (प)

स्नेहनसेचनपूरणेषु—
काक्-कात-शा।
स्नेहे सेकपूर्त्योश्च—वो।

ग—प्लुष्टश्लिष्टायतभुज०–मभार. ९,३००। प्लुष्ट०–कथासरि. ४०,६८।

+√प्लेव् (प्लेवृ) १/५०२ शा-च-काक्-कात× — सेवने (आ) क्षी-जै-शा-हे। सेचने—मै-सा। सेवे—वो। — √पेव् (पेवृ) १ सेवने (आ)।

√प्सा २/४४ श — भक्षणे (प) क्षी-मै-सा-च-जै-काक्-कात-शा-हे-वो। — √भस् (भस) ३/ भर्त्सनदीप्त्योः (प)। भक्षणदीप्त्योः—ऋग्भाष्ये १,२८,७–सायणः। प्साति–निघ. २/१४ गतिकर्मा। यदप्स इत्यभक्षस्य–निरु. ५,१३।

ग—सपत्नान् प्साहि मे पूर्वान्–शौ. १०,३,१४। प्यायात्–शब्रा. ३,५,४,२४।

√फक्क् (फक्क) १/११५ श× — नीचैर्गतौ (प) क्षी-मै-सा-च-जै-काक्-कात-शा-हे। असद्व्यवहारे शनैर्गतौ—वो। — √ष्वक्क् (ष्वक्क) १/ गत्यर्थः (आ)।

नीचैर्गतिः=मन्दगमनम् असद्व्यवहारो वा—क्षी।

ग—भुजगराजफक्कत्फणाः–प्रतापरुद्रीय. ३३,b९।
ङ—फक्किया (<फक्किका)=ग्रन्थविषमस्थलम्–सुर. १६,२४७।
छ—फाँक=(<फक्किका)=खण्डम्।

√फण् (फण) १/८०४ श× — गतौ (प) क्षी-मै-सा-च-जै-काक्-कात-शा-हे-वो। — √फण् १/ निस्नेहने (प) वो। √फण् १/२०७ शब्दे (प) काक्। फणति—निघ. २,१४=गतिकर्मा।

ग—ऋष्या इव पम्फणतः–खि. ५,५,११ । फणः (फणति = विस्तृतिं गच्छति)–तैब्रा. ३,१०,१,४ । अफाणयत्–ऋ. ८,५८,१३; ऐब्रा. ४,४ ।

√फल् (ञिफला) १/५१७ विशरणे (प)
शX
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
भिदि—वो ।

√फुल्ल् (फुल्ल) १/५३२ विकसने (प) ।

ग—फलेन्मूर्धा स्म ते राजन्–वा. रा. २,६४,२२ (गी. प्रे. सं.) । शतधाऽस्य फलेन्मूर्धा–मभार. ३,१६५६४ ।

√फल् (फल) १/५३० निष्पत्तौ (प)
श
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।

√फल् १/३८१ गतौ (प) काकृ ।
√पल् (पल) १/२४२ b निष्पत्तौ (प) काकृ ।

ग—सर्वकामान् फलन्ति (नगाः)–वा. रा. ४,४४,९४ । द्रुमाः फलन्ति–हरिवं. १२७९९ । आचारः फलते धनम्–मभार. ५,३८८७ ।

ङ—√फल् (अक) = निष्पत्तौ । फलइ–गा. १७,८९४ ।
छ—√फलना } = फलने ।
छ—√फरना* }

+√फुल्ल् (फुल्ल) १/५३२ विकसने (प)
शX
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
विकासे—वो ।

√फु १/५५२ l गतौ (आ) काकृ ।
√फुल् १/२४४ a विकसने (प) काकृ ।

ङ—√फुल्ल (अक) = विकसने । फुल्लइ, फुल्लए, फुल्लेइ–रंभा.; सम्मत्त. १४० ।
च—√फुल (अक) = विकसने–पिंग. ।
छ—√फूलना = विकसने ।

+√फेल् (फेल) १/५४१ गतौ (प)
शX
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।

√पेल् (पेल) १/गतौ (प)।
√प्रेण् १ /२१३ a गतिप्रेषणश्लेषणेषु (प) काकृ ।
√फ्रेण् १/२१३ b गतिप्रेषणश्लेषणेषु (प) काकृ ।

ङ—√फेल (सक)=प्रेरणे, क्षेपणे, अपनयने। फेलदि-शौ.; नाट., संक्ष-फेलिअ-नाट.।

√बंह् (वहि) १/६२६ वृद्धौ (आ)
श×, (जै-काक-कात-वो क्षी-मै-सा-च-शा-हे।
—√वंह्[वहि]) जै-काक-कात-वो।

√वह् १/३१६g गतौ (प) काक।
√बृंह् (बृहि) १/ वृद्धौ (प)।

तद्देवतां पशुभिर्बंहयन्ते (भंहयन्ते-काठ. ११, ५)-पञ्चविं. ब्रा. २३, १६, ५। यद् बंहिष्ठम्-ऋ. सं. ४, ४, ३१, ३।

+√बद् (बद) १/४९ स्थैर्ये (प)
श× क्षी-मै-सा-च-काक-शा-हे-वो।
(जै-कात-√वद्[वद]) जै-कात।

<√पद् (पद) स्थैर्ये (प) इति कण्ठः-क्षी।
√बन्द् (बन्द) १/ स्थैर्ये (प) इति मैत्रेयः-सा।

क—बेद्=वृद्धौ ?-वा. पॉकर्नीः।

ग—ऐङ्गुदं बदरीमिश्रम् (बदति=स्थिरीभवति=छिन्नेऽपि पुनः प्ररोहति)-वा. रा. २,१०३,२९। बदर्याम्-मभार. ३,१७७,११। बदरी-शाङ्खा.गृह्य. ४,१७। बधिपे-ऋ. १,८०,१३ (तु. वें. स्क. सा; वैतु ग्रि. धा.=बद् [स्थैर्ये] इतीव ?)।

छ—√बदना (<बदनम्)=पणेन कस्यचन मतस्य स्थिरीकरणे।

+√बध् (बध) १/९५८ बन्धने (आ)
श× क्षी-मै-सा-च-काक-कात-शा-हे।
बधे निन्दे च—वो।
(जै-√बाध्[बाध]) बन्धने—जै।

√बाध् (बाधृ) १/रोटने (आ)।
√बन्ध् (बन्ध) ९/बन्धने (प)।

क—भद्-, भाद् (ह्)=चित्तविकारे-वा. पॉकर्नीः। भेध्=वेष्टने, नमने, निष्पीडने, आतङ्कने-जू. पॉकर्नीः।

ग—बधेत्-शब्रा. ५,३,५,२८। बीभत्सुः-ऋ. १,१६४,८। बीभत्सते-तैब्रा. १,१,३,८।

+√बन्द् (बन्द) १/५१ स्थैर्ये (प) इति मैत्रेयः-सा
क्षी-मै-श-च-जै-काक-सा।
कात-शा-हे-वो×

<√बद् (बद) स्थैर्ये (प)।
√पद् (पद) १/४९ स्थैर्ये (प) इति कण्ठः-क्षी।

√बन्ध् (बन्ध) ९/३७ श×	बन्धने (प) क्षी-मै-सा-च-जै, काक्र (उ), कात-शा-हे । बन्धे--वो ।	√पद् (पद) १/४९ स्थैर्ये (प) । √बद् (बद) १/४९ स्थैर्ये (प) । √बध् (बध) १/९५८ बन्धने (प) । √बन्द् (बन्द) १/५१ स्थैर्ये (प) सा ।

ग—बध्नाति–तै. ६,१,७,२; पै. १,८५,१; ऐआ. ५,१,३ ।

+√बभ्र् (बभ्र) १/५५६ जै×,श मै-सा-च-काक्र- कात-शा√बभ्र्	गत्यर्थः (प) क्षी । गतौ--हे । गत्याम्--वो ।	√मभ्र् (मभ्र) १/गत्यर्थः (प) ।

ग—बभ्रिर्वज्रम्–ऋ. ६,२३,४ ।

+√बम्ब् (बम्ब) १/४१२ मै-श-च-जै-काक्र- कात-शा×	गतौ (प) इति कौशिकः– क्षी । क्षी-सा-हे । गत्याम्–वो ।	<√बर्ब् (बर्ब) गतौ (प) ।
+√बर्ब् (बर्ब) १/४१२ श-च×, (जै)	गतौ (प) क्षी-मै-सा-काक्र-कात- शा-हे । गत्याम्--वो ।	>√बम्ब् (बम्ब) गतौ (प) । √वर्फ् (वर्फ) १/४०८ गतौ (प) । √बर्फ् १/१४३ a गतौ (प) च ।

क—बल्-बल्–, बर्-बर्—वा. पॉकर्नीः ।

ग—खदिरबर्बुरौ गौरकाण्डौ–मभाष्ये १,१,४५ । बर्बरीतीर्थमाहात्म्यम् .... । यथा वर्बरिका जाता–स्क.पु. १,३७,१ (मन. रा. मोर. सं.) ।

ङ—बब्बर (<बर्बरः)=अनार्यदेशविशेषः–पउम. ९८,६५; बर्बरदेशनिवासी—पण्ह. १,१; पउम. ९९,५५ ।

ङ—बब्बरी = बर्बरदेशीयमहिला–णाया. १,१; औप.; इक. ।

ङ—बब्बरी = केशरचना–दे. ६,९० ।

+√बर्ह् (बर्ह) १/६३१ प्राधान्ये (आ)
मै-श-काक्ष× क्षी-सा-च-जै ।
(कात-शा-हे-वो-√वर्ह्) स्तुतौ हिंसायां दाने वाचि--वो ।

√बल्ह् (बल्ह) १/प्राधान्ये (आ) ।
√बर्ह् (बर्ह) १०/हिंसायाम् (प) ।
√वर्ह् (वर्ह) १/परिभाषणहिंसाच्छादनेषु (आ)
√बर्ह् १/५४५ प्रयत्ने (आ) काक्ष ।

ग—बर्हणां कृतः-ऋ. १,५४,३. बर्हणा परिबर्हणा–निरु. ६,१८,२. परिबर्हणा = परिवृद्धिः, परिहिंसा वा–दुर्गाचा. । शरबर्हिः-शब्रा. १४,९,४,११ ।

छ—√बहराना
छ—√भुराना } (<बर्हणम्) = विस्मारणे (आच्छादने) ।

छ—√बहलाना (<बर्हणम्) = दुःखप्रसङ्गं विस्मार्य चित्तस्यान्यतो नयने (आच्छादने, वाचि) ।

√बल (बल) १/८२४ प्राणने धान्यावरोधे च (प)
श× क्षी-मै-सा ।
प्राणने—च-काक्ष-कात ।
प्राणधान्यावरोधयोः—जै ।
प्राणनधान्यावरोधनयोः—शा-हे ।
जीवने धान्यावरोधे च—वो ।

√बल (बल) १/ दाने वधे निरूपणे (आ) वो ।
√बल् ६/८० गतौ (प) काक्ष ।

ग—बल्बलीति–शब्रा. २,३,२,११; जै. २१२ [१ चक्रपरिवर्तने ('बल्बलि' इत्येवं शब्दने–सा) २–प्राणन इति विवेकः] –वै. प. को. ।

+√बल्ह् (बल्ह) १/६३२ प्राधान्ये (आ)
श× क्षी-सा-च-जै ।
(मै-कात-शा-हे-√वल्ह्) । प्राधान्यपरिभाषणहिंसादानेषु—काक्ष ।
स्तुतिहिंसादानवाक्षु—वो ।

√बर्ह् (बर्ह) १/ प्राधान्ये (आ) ।
√बिल्ह् १/५४४० प्राधान्यपरिभाषणहिंसादानेषु (आ) काक्ष ।

		√मल्ह् १/४४४b प्राधान्य-परिभाषणहिंसादानेषु (आ) काकृ।
		√वल्ह् (वल्ह) १/६४१ परिभाषणहिंसादानेषु (आ) मै।

ग—गच्छ वल्हिकान् वा परस्तराम्—अ.वे. ५,२२,७। वल्हिक०–अ.वे.प्राति. १,४६; शब्रा. १२,९,३,३। असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना–ऋ. १, १८१,७=वाचि, दार्ढ्यें, घनत्वे।

+√वस् (वसु) ४/१०६ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	स्तम्भे (प)। अपरे वकारादि-माहुः—सा।	<√वस् (वसु) स्तम्भे (प)।

√वस् (वसी) ४/१०८ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	च=परिणामे (प)। इति कण्ठः—क्षी।	√मस् (मसी) ४/ परिणामे (प)।
परिणामः=	विकारः—क्षी।	

ग—श्वानं वस्तः–ऋ. १,१६१,१३। ता वस्रि नश्यतः–ऋ. १,१२०,१२।

+√वाड् (वाडृ) १/२८३ श× (क्षी-मै-जै-शा-हे-काकृ-कात-वो-√वाड्)।	आप्लाव्ये (आ) सा। सा-च। आप्लाव्ये—क्षी-मै-जै-शा-हे। आप्लावे—काकृ-कात-वो।	√वाढ् १/१८९ b तीव्रगतौ (प) काकृ। √वृध् (वृधु) १/ वृद्धौ (आ)।
आप्लावः=	उन्मज्जनम्—दुर्गादासः।	

ग—वालमेतमबालिशम्–वा. रा. ४,२१,९।
छ—बाढ़=आपूरः (आप्लावे)।

√वाध् (वाधृ) १/५ श×	रोटने (आ)। क्षी-शा-हे। लोडने—मै-सा। विलोडने—च।	√वाह् (वाहृ) १/ प्रयत्ने (आ)

प्रतीघाते—जै ।
लोटने—काकृ-कात ।
विहतौ—वो ।

ग—बाधते-ऋ. १०,१२७,[(३७,४)२]; शौ. १,१६,३; अप ' ' बाधते १,३५,९ ।

ङ—√बाध (सक)=(१) विरोधे, (२) रोधे, (३) पीडायाम्, (४) विनाशे । बाधइ—पि. ५६३ ।

ङ—√बाह (सक)=(१) विरोधे, (२) रोधे, (३) पीडायाम्, (४) विनाशे । बाहइ, बाहए-पंचा. ५,१५; उत्र. ।

+√बाहृ (बाहृ) १/६३७ शा-शा× (मै-जै-काकृ-कात-हे-वो-√बाहृ) प्रयत्ने (आ) । क्षी-सा-च ।

√वेहृ (वेहृ) १/ प्रयत्ने (आ) सा ।

क—भाघु-स्=कफोणिः, मणिबन्धः-वा. पॉकर्नीः ।
ख—अवे.बाज़ु-स्=बाहुः-वा. पॉकर्नीः ।
ग—सह ओजो बाह्वोर्वो बलं हितम्-ऋ. ५,५७,६; यं बाहुतेव पिप्रति-१,४१,२ ।

+√बिट् (बिट) १/३१५ श-जै-कात-शा× (क्षी-हे-वो-√बिट्) । आक्रोशे (प) मै । मै-सा-च-काकृ ।

√बिड् (बिड) १/३१६ आक्रोशे (प) मै ।
√विड् (विड) १/ आक्रोशे (प) मै ।

√बिड् (बिड) १/३१६ सा-श-च× (क्षी-जै-कात-हे-वो-√बिड्) । आक्रोशे (प) मै । मै-काकृ-शा ।

√बिट् (बिट) १/३१५ आक्रोशे (प) ।

+√बिन्द् (बिदि) १/६२ श× (मै-जै-कात-हे-√बिन्द्) अवयवे (प) । क्षी-सा-च-काकृ-शा । अंशे—वो ।

√भिन्द् (भिदि) १/ अवयवे (प) सा । अथाप्यादिविपर्ययो भवति—ज्योतिर्घनो बिन्दुः—निरु. २,१,१२ ।

√वट् १/१०७ अवयवे (प) काकृ ।

क—वेन्द् = विन्दुः । ब्रेटॉ.-बन्ने=बिन्दुः । इरि.-बुइन्ने=विशाला नदी, प्रवाहः, तरङ्गः-वा. पॉकर्नीः ।

ग—ऊर्ध्वो बिन्दुरुदचरत्-अ. वे. १०, १०, १९ ।

+√बिम्ब् (बिबि) १/२०६f मर्दने (प) काकृ ।

अपाणिनीयः

क—बम्ब्, भम्भ, पम्प्-, फम्फ्=उड्डयने, वायुविहारे । लिथु. बॅम्ब् = नाभिः-वा. पॉकर्नीः ।

ग—प्रतिबिम्बन्ति-महा. ५, ५५; अन्न. ४, ७१ ।

ङ—√ बिंब (सक)=प्रतिबिम्बने । कर्म-बिंबिज्जइ-सूक्त. ४६ ।

+√बिल् (बिल) ६/८० श×

(काकृ-√बल्)....

(जै-√बिल्)....

भेदने (प) क्षी-मै-सा-कात-शा-हे-वो ।

भेदे—च-शा-हे ।

भेदने—काकृ ।

जै ।

√भिल् (भिल) १०/भेदने(प) इति कौशिकः-क्षी । बिलं भरं भवति बिभर्तेः-निरु.२, १७, १ । बिलमं भिलमं (=भेदनम्) भासनमिति वा-निरु. १, २०,२ । बिल्वं भरणाद् वा भेदनाद् वा-निरु. १,१७४ ।

क—बेल्=कर्तने, खनने ।

ग—मार्ज्मि दिधिषामि बिलमैः-ऋ. २, ३५, १२=प्रस्तरखण्डैः ?

ङ—बिल=सुषिरम्-विपा. १, ७; गउड. ।

+√बिस् (बिस) ४/१०४ काकृ×,श (मै-कात-शा-हे—√बिस्) काकृ-√बिश् ५/५४

प्रेरणे (प) क्षी-सा-च-जै

क्षेपे—वो ।

√बिस्त् १०/४४जलोत्तरणे (प) ।

बिस्यति-निघ. १/१४=गतिकर्मा ।

बिसं बिस्यतेर्भेदनकर्मणो वृद्धिकर्मणो वा—निरु. २,२४,१ ।

√बिश् ४/५४ प्रेरणे (प) काकृ ।

ग—बिसानि स्तेनो अप सो जहार-ऐब्रा. ५,३०; अ. वे. ४,३४, ५ ।

नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम्—अ. वे. ५,१७,६।

⊣ √बुक्क् (बुक्क) १/११९ शX,(जै-√बुक्क्)	भाषणे (प) क्षी-मै-सा-काकृ-कात। भषणे इत्येके—क्षी-मै-सा-च-हे। भाषणे भषणे च—काकृ। आभाषणे—शा-हे। श्वादिशब्दे—बो।	√भष् (भष) १/ भर्त्सने (प)। √फक्क् (फक्क) १/ नीचैर्गतौ (प)। √बुक्क् (बुक्क) १०/ भाषणे (प)।

क—बु—: कण्ठ्यसंयोगे—बुक्—वा. पॉकर्नी:।
ख—अवे. बुक्स्त=गर्जने, श्वश्रृगालादिशब्दे।
ङ—√भुक्क=भषणे। भुक्कइ—गा. ६६४ अ.।
छ—√भूकना, √भूँकना, √भौंकना=भषणे।

√बुड् (बुड) ६/११७ क्षी-सा-श-च-जैX	संवरणे (प) मै मै-काकृ-कात। संवरणे उत्सर्गे च—हे। संवृतौ।उत्सर्गे—बो।	√व्रुड् (व्रुड) ६/ संवरणे (प)। √बुड्ड् १/१६५ उद्गमने (प) काकृ।

ग—बुडिल०, बुलिल०—शब्रा. ४,६,१,९; १०,६,१,१; ऐब्रा. ६,३०; छान्दो. ५,११,१।

छ—√बूड़ना, छ—√डूबना } =निमज्जने। अयमुत्सर्गः।

√बुध् (बुध) १/८४२ शX	अवगमने (प) अनिट् क्षी-मै-सा-च-काकृ-कात-शा-हे। ज्ञाने (उ)—जै।	√बुध् (बुध) १/ बोधने (उ)। √बुन्ध् (उबुन्धिर्) १/ निशामने (उ)। √बुध् (बुध) ४/ अवगमने (आ)।

ग—बोधति—ऋ. २,२५,२।
छ—√बोधना*†=अवगमने।

√बुध् (बुध) १/८६० शX	बोधने (उ) सेट् क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। छेदने—बो।	>√बुध् (बुधिर्) बोधने (उ) इति नन्दी—क्षी। शेषः पूर्ववत्।

ग—बोधतु—मन्त्रब्रा. १,५,३ । बोधिषीमहि—मै. ४,९,६ ।

√बुध् (बुध) ४/६० श	अवगमने (आ) क्षी-मै-सा-च-काक्र-कात-शा-हे । ज्ञाने—जै-शा-हे वेदने—वो।	पूर्ववत्।

ग—सर्वो हि कृतमनुबुध्यते—शब्रा. २,२,३,१७ । बुध्येत—योशि. १,७८ । बुध्यति-गर्भ. १ । श्रोत्रं बुध्यते शब्दम्—मभार. १४,६६९ ।

ङ—√बुज्झ (सक)=ज्ञाने, (२) जागरे । बुज्झइ—उत्र. ।

छ—√बूझना = ज्ञाने ।

+√बुन्द् (उबुन्दिर्)१/८६१ श-च-काक्र-कात× (मै—√बुन्द्)	निशामने (उ) क्षी-सा-जै-शा-हे-वो ।	>√बुन्ध् (उबुन्धिर्) निशामने (उ)इति नन्दी–क्षी । >√चुन्द् (उचुन्दिर्) १/६०० निशाने (उ) च ।
निशानम्	=आलोचनम्—क्षी ।	√बुद् १/ निशाने (उ) वो । √बुध् (बुध) १/ बोधने (उ)।

ग—आ बुन्दं वृत्रहा ददे—ऋ. ८,४५,४; ८,६६,६; साधुर्बुन्दो हिरण्ययः–८,६६,११; बुन्द इषुर्भवति । बुन्दो वा भिन्दो वा भयदो वा भासमानो द्रवतीति वा–निरु. ६, ३३,१ । अत्र भासमानार्थो गतार्थो भवति ।

+√बुन्ध् (उबुन्धिर्) १/८६१ मै-सा-श-च-जै-काक्र-कात-शा-हे×	निशामने (उ) इत्यन्ये–क्षी-वो ।	<√बुन्द् (उबुन्दिर्) निशामने (उ) । शेषः पूर्ववत् ।

√बुन्द्>√बुन्ध् इति सुस्पष्टो विकासः ।

+√बुस् (बुस) ४/१०६ श ? (काक्र-√बुथ) (मै-जै-शा-हे-√बुस्)	उत्सर्गे (प) क्षी-सा-च-काक्र-कात । हानौ—वो ।	√बुस् (बुस) ४/ विभागे (प) सा । √व्युष् (व्युष) ४/ उत्सर्गे (प) हे । बुसम्–निघ. १/१२=उदक-नाम ।

क—बु, भु = उच्छ्रयने, उन्मादने। 'स्'-इत्यस्य विस्तारः—बुस्–वा. पॉकर्नीः।
ग—गूहते बुसम् (बुस्यते = उत्सृज्यते (मेचैः)–ऋ. १०, २७, २४।
छ—√बुसना = पर्युषितौ, उत्सर्गे।
छ—भूसा, भुस (<बुसम्)।

+√बुस् (बुस) ४/१०७ विभागे (प)। पूर्ववत्।
क्षी-मै-श-च-जै-काकृ- अपरे त्वयकारमिच्छन्ति–
कात-शा-हे-वो। सा।

पूर्वस्माद् धातोरभिन्नोऽयमर्थभेदात् पृथक् संख्यातः।

√बृंह् (बृहि) १/७२८ वृद्धौ (प) क्षी। √बंह् (बहि) १/ वृद्धौ (आ)।
श× शब्दे, च = वृद्धौ √मंह् (महि)१/ वृद्धौ (आ)।
(मै-सा-च-जै-कात-हे-वो– क्षी-शा। √वृध (वृधु) १/ वृद्धौ (आ)।
–√वृंह्) वृद्धौ—काकृ। √ब्रह् ११/३२०d वृद्धौ (प)
काकृ।

ग—विशा क्षत्रं परि बृंहति तदिदं क्षत्रम्–शब्रा. ३,६,१,२४। वृंहन्ति कुञ्जराः–मभार. ९. १९४६।
ङ—√बिह (सक) = पोषणे। ठा. ६–पत्र. ३७५; णाया. १, १,–पत्र. १०।
ङ—√बूह (सक) = पोषणे। बूहए–सूअ. २,५,३२।

+√बृह् (बृह) १/७२७ शब्दे, (प)। पूर्ववत्।
मै-श-जै-शा× क्षी।
√बृह्र् (बहिर्) इति दुर्गः—क्षी।
(सा-च-कात-हे-वो– शब्दे—काकृ।
√वृह्) ६/ वृद्धौ—ह्वि.।

ग—यज्ञं सं बबर्ह–शब्रा. १,७,३,५। सं बबर्ह–अ.वे. ९,३,३। वब्रृहाणस्याद्रेः (= वर्धमानस्य–इति सायणः) ऋ. ५,४१,१२: हर्यश्वाय बर्हया–(= उत्साहय–सायणः) समापीन्–७,३१,१२। बर्हय–कौ. १,२९८; जै. १,३१,६। [धा. वृद्धौ वृत्तिः]।

√बृह (बृह्) ६/६७ उद्यमे (प) अतिबृहति रेतः (= उद्यच्छति–दुर्गाचार्यः) निरु. ९,२२,१।
(मै-सा-श-च-जै-कात- क्षी-काकृ।
हे-वो–√वृह्) उद्यमने—शा।

वरं मूलं बृहतीति वा (= उद्यच्छति–दुर्गाचार्यः) निरु. ५,४,१।

ग—बृहति–पै. २०,४३,८।

+√बेद् (उबेदिर्) १/८६१ निशामने (उ)
मै-सा-श-च-जै-काक्र- इत्यन्ये—क्षी।
कात-शा-हे-वो×

<√बुन्द् (उबुन्दिर्) निशामने (उ)।

+√बेहृ (बेहृ) १/६३४ प्रयत्ने (आ)
क्षी-मै-श-च-जै- इत्येके—सा।
काक्र-कात-शा-हे-
वो×

<√वेहृ (वेहृ) प्रयत्ने (आ)।

+√व्युस् (व्युस) ४/१०७ विभागे (प)।
क्षी-मै-श-च-जै-काक्र- केचिदिच्छन्ति—
कात-शा-वो× सा-हे।

<√व्युष् (व्युष) विभागे (प)।
√प्युष् (प्युष) ४/ विभागे (प)।
√प्युस् (प्युस) ४/ विभागे (प)।

+√व्रण् (व्रण) १/४४७ शब्दार्थः (प) सा
क्षी-मै-श-च-जै- वशादिः क्वचित् पठ्यते
काक्र-कात-शा-हे× —सा।
शब्दे—वो।

<√व्रण् (व्रण) शब्दार्थः (प)।
√भ्रण् (भ्रण) १/ शब्दार्थः (प)।
√वण् (वण) १/ शब्दार्थः (प)।

+√व्रुड् (व्रुड) ६/११२ संघाते (प) इत्येके—मै।
श× मै-शा-हे।
(क्षी-सा-च-जै-वो- संवरणे—कात।
√व्रुड्) उत्सर्गसंहत्योः—वो।
(काक्र-√वूड्) संवरणे—काक्र।

√बुड् (बुड) ६/संवरणे (प)।
√बुड्, १/१६५ उद्गमने (प)
काक्र।

√ब्रू (ब्रूञ्) २/३३ व्यक्तायां वाचि (उ)
श क्षी-मै-सा-जै-काक्र-
कात-शा-हे।
वचने—च।
उक्तौ—वो।

ग—ब्रवीति–ऋ. १०,६१,१२। ब्रुवते–८,६,३; जै. ३,५४,११। ब्रूते–मन्त्रब्रा. १,२,२।

ङ—√ब्रू=वचने। ब्रूम, ब्रूहि–उत्त. २५, २९।

च—√बुव-वचने। बुवइ, बुवदि–कुमा.।

√भक्ष् (भक्ष) १/८९७ भक्षणे (उ) मै
क्षी-श-जै-काक्र-वो×, मै-च-शा-हे।
(कात) अदने—सा।

>√भ्रक्ष् (भ्रक्ष) भक्षणे (उ) इत्येके–मै।
>√भ्लक्ष् (भ्लक्ष) भक्षणे (उ) इत्येके–मै।

√भृक्ष् १/५७२b भक्षणे (उ) शा।

√भज् (भज) १/.. सेवायाम् (उ)।

ग—भक्षति–पै. २०,११,९। भक्षन्ति शवमांसानि–पद्मपु. ६,१३९,१७।

छ—भक्षना* भच्छना* भषना* (<भक्षणम्)=भक्षणे।

√भज् (भज) १/९८२ सेवायाम् (उ)
झ क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
भोगसेवयोः—वो।

√भज् (भज) १०/ विश्राणने (प)।

ग—भजन्ते–ऋ. १,१२५,६। भजध्वम्–शौ. १२,३,४।

ङ—√भय=सेवायाम्, (२) विभागे, (३) ग्रहणे। भयइ, भअइ–सम्म. १२४; कुमा.।

√भञ्ज् (भन्जो) ७/१६ आमर्दने (प)
श क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
मोटने—वो।

√भञ्ज् १/३१३ c हिंसागत्योः (प) काक्र।

ग—बभञ्ज–ऋ. ८,४,५। भनक्ति–शौ. १०,३,१३।

√भट् (भट) १/३०३ श	भृतौ (प) क्षी-मै-सा-च-जै-कात-शा-हे । उच्छ्राये—काक्रु । भृतौ—वो ।	<भृतः । √भट् (भट) १/७७३ परिभाषणे (प) । √वट् (वट) १/ परिभाषणे (प) । √भण्ड् (भडि) १/ परिभाषणे (प) ।

भृतिः = वेतनम्–क्षी ।

ग—हरिभिर्भटाः–भा. पु. ८,१०,९ = योद्धारः । भटः–नैष. १,१३२. = वीरः । यो भाटयित्वा शकटं नीत्वा– वृद्धमनु.–विवादके ५१,१० ।

घ—भट = भृत्यः–मिलिन्दपञ्ह २४० ।

+√भट् (भट) १/७७३ श×	परिभाषणे (प) पित् क्षी-मै-सा-च-जै-काक्रु-कात-शा-हे । भाषणे—वो ।	√भट् (भट) १/ भृतौ (प) । √भट्ट् १/९३० ? (प) काक्रु ।

ग—बलनाम्नोऽसुरस्य भटैः–ऋ. १,६,५ । यमं पाशभृतश्च तद्भटान्–भा. पु. ६,१,१९ । वैश्यायां शूद्रवीर्येण पुमानेको बभूव ह । स भट्टो वावदूकश्च सर्वेषां स्तुतिपाठकः॥ ब्र. वै. पु. ब्रह्मखण्डे, १० अध्या. ।

छ—भाट (<भट्टः) = चारणः, स्तुतिपाठकः ।

√भण् (भण) १/४५२ श×	शब्दार्थः (प) क्षी-मै-सा-च । शब्दे—जै-काक्रु-कात-शा-हे-वो ।	भनति–निघ. ३/१४ = अर्चतिकर्मा. ऋ. ६,११,३ √पण् १/२०७शब्दे r (प) काक्रु । √फण् १/२०७s शब्दे (प) काक्रु । √भ्रण् (भ्रण) १/ शब्दार्थः (प) । √वण् (वण) १/ शब्दार्थः (प) ।

ग—बभाण–बृहज्जाबालो. १,१ । भण्यते–तेजोबिन्दूप. ५,९४; महोप. ६,५० । वराहो. २,५९ ।

घ—भणति–पुग्गलपञ्ञत्ति ३३,५६ । भणे–मिलिन्दपञ्ह २१ ।

ङ—√भण (सक) = भाषणे । भणइ, भणेइ–कुमा. ।

छ—√भणना* † / √भनना* } (<भणनम्) = भाषणे ।

+√भण्ड् (भडि) १/२७० श×	परिभाषणे (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे । परिभाषायाम्—जै । वाचि—वो । 'परिहासे' इति देवः-सा ।	√भण् (भण) १/४५२ शब्दार्थः (प)। √भण्ड् (भडि) १/१७१ कुत्सायाम् (प) काकृ। √भाण्ड् १/९५, १७२ परि-भाषणे (प) काकृ।

ग—भण्डानः-पै. १७,१४,५ [धा. भेदने वृत्तिः]।

घ—भण्डति—विनय. १,४६।

ङ—√भंड (सक)=भर्त्सने, आक्रोशे। भंडइ-सण.।

छ—√भाँडना *= मुधा भ्रमणे, (२) भर्त्सने, परिनिन्दने, (३) नाशे, विकृतौ।

छ—√भँडना=निन्दने, (२) अव्यवस्थायाम्, (३) त्रोटने।

√भन्द् (भदि) १/१२ श	कल्याणे सुखे च (आ) क्षी-मै-सा। कल्याणे—च-शा-हे। प्रियसुखयोः—जै। कल्याणे सौख्ये च—काकृ-कात। शुभे मुत्प्रीत्योश्च—वो। भासने—ह्वि.। सुखम् =आत्मगुणोदयः—क्षी.।	भन्दते-निघ. ३/१४=अर्चतिकर्मा। भन्दते-निघ. १,१६=ज्वलतिकर्मा।

ग—भन्दते—ऋ. ३,३,४। भन्दना—ऋ. ८,२४,१५; भद्रं भद्रमिति ब्रूयात्-मनु. ४, १३९=प्रथमं भद्रपदमभद्रपदपरम् (मन्वर्थ.)।

ङ—√भद (सक)=(१) सौख्ये, (२) कल्याणे—विसे. ३४३९।

+√भर्ब् (भर्ब) १/४२१ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	गतौ (प) क्षी।	√बर्ब् (बर्ब) १/गतौ (प)। √वर्फ् (वर्फ १/ गतौ (प)। √बभ्र् (बभ्र) १/ गत्यर्थः (प)।
√भर्व् (भर्व) १/५७७ श-जै-काकृ-कात×	हिंसायाम् (प) क्षी-मै-सा-च-शा-हे। हिंसे—वो।	भर्वति-निघ. २/८=अत्तिकर्मा। निरु. ९,२३। √भर्व् १/७५९ हिंसने (प) जै।

√भर्भ् १/१३९k हिंसार्थ (प) कात।

ग—भर्वति-ऋ. १,१४३,५। भर्वन्-तै. १,३,१४,४। अग्निर्जम्भैस्तिगितैरत्ति भर्वति-ऋ. १,१४३,५।

√भल् (भल) १/४९१ श×	परिभाषणहिंसादानेषु (आ)। क्षी-मै-सा-काक्ष-कात-हे। परिभाषणे—च। दानहिंसापरिभाषणेषु—जै। हिंसादानपरिभाषणेषु—शा। वादिवत् (=दाने-वधे नीरूपणे)—वो। ज्ञाने (विचारे, इन्द्रिगोचरे)—ह्वि.।	√बल् १/८१२ परिभाषण-हिंसादानेषु (आ) हे। √वल्ह् (वल्ह) १/६४१ परिभाषणहिंसादानेषु (आ) मै। √भल्ल् १/४९२ परिभाषण-हिंसादानेषु (आ)। √भल् (भल) १०/आभण्डने (आ)। √भण्ड् (भडि) १/ परिभाषणे (आ)।

ग—भद्रं भल त्यस्याः—ऋ. १०,८६,२३। भलाय स्वाहा–गोगृ. ४,६,११। कान्यकुब्जे नृपश्रेष्ठो भलन्दन उरुक्रमः—ब्रह्मवै., श्रीकृष्णजन्मखण्डे १७ अध्या.।

छ—भलटी†=दात्रविशेषः (देश.)—(हिंसायाम्)।

+√भल्ल् (भल्ल) १/४९२ श×	परिभाषणहिंसादानेषु (आ)। क्षी-मै-सा-काक्ष-कात-हे। परिभाषणे—च। दानहिंसापरिभाषणेषु—जै। हिंसादानपरिभाषणेषु—शा। दाने वधे नीरूपणे—वो।	√भल्ल् १/२४७ll गतौ (प) काक्ष। √मल्ह् १/५४४b परिभाषण-हिंसादानेषु (आ) काक्ष।

क—भेरॉ-स्, भेरॅ्-स्, भेरु-स्, भेरु-स्=ईषत्कपिशम्। पु. उ. ज. बेरो; एँग्लो-सैक्साॅ. बेर=भल्लः, ऋक्षः-वा. पॉकर्नीः।

ग—क्षुरनाराचभल्लानाम्–मभार. १,१४०,६=शस्त्रभेदः (हिंसायाम्) (भल्लते=हन्तीति)। द्वीपिनः खड्गभल्लूकाः—मभार. १२,११६,६=ऋक्षाः। भल्ला-पलोल—बृहत्सं. १४,३०-भल्लः=देशविशेषः।

√भष् (भष) १/६८६ शX | भर्त्सने (प) । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। बुक्के पिशुनोक्तौ—वो । | √बुक्क् (बुक्क) १/ भाषणे (प)।

ग—भषम्–मा. ३०,१९; का. ३४,४,१। भषेयुः सहिताः सर्वे–मभार. २,१४२४; श्वा भषन्–१,५२४९; भषन्ते २,१४२४; तपस्विनं सम्पूर्णविद्यं भषन्ति–मभार. ३,१५६४१।

घ—भसति–जातक ४,१८२।

घ—भुसति, भुस्सति–दीघ. (A) १,३१७।

√भस् (भस) ३/१९ श-जै-शाX | भर्त्सनदीप्त्योः (प) क्षी-मै-सा-च-काकृ-कात-हे। भक्षणदीप्त्योः–ऋग्भाष्ये सा १२,८,७। भक्षणदीप्त्योः–द. उणा. वृ. ८/८७। भर्त्सने—च। भर्त्सने द्युतौ च—वो। | √प्सा २/ भक्षणे (प)। √भष् (भष) १/भर्त्सने (प)। बभस्ति–निघ. २/८=अत्तिकर्मा। भसथः–निघ. २/८=अत्तिकर्मा।

ग—भसत्–ऋ. ६,३,४; बप्सति–८,४३,३। बभस्ति–शौ. ९,२,२,।

√भा २/४० श | दीप्तौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। | √भास् (भासृ) १/ दीप्तौ (आ)।

ग—भाति–ऋ. ७,९,२; शत्रा. ८,४,१,१०।

घ—भाति–दीघ. २,२०५; विमानवत्थु ३५।

ङ—√भा (अक)=दीप्तौ। भाइ–कप्पू.।

ङ—√भाअ (अक)=दीप्तौ। भाअदि–शौ.।

छ—√भाना *† (<भानम्=ज्ञानम्)=(१) प्रतीतौ, (२) रुचौ (३) शोभने।

√भाम् (भाम) १/४३४ शX — क्रोधे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। — भामते–निघ. २/१२ = क्रुध्यतिकर्मा। √भा २/४० दीप्तौ (प)।

ग—वीरान् मा रुद्रो भामितो वधीः–ऋ. १,११४,८। भामितः–श्वेताश्वतरो. ४,२२; मना. २,५३। भामः–व. ४६० : ५; [ऋ. १०,८३,४]। मदेचितस्य प्ररुजन्ति भामाः–ऋ. ५,२,१०–भामाः=क्रोधा दीप्तयो वा–इति सायणः। गुरुं मित्रं तथा भामं पुत्रं च भगिनीं तथा–दे. भा. ६,१६,४९–भामः=भगिनीपतिः।

√भाष् (भाष) १/६०७ शX — व्यक्तायां वाचि (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे। वचने—च। वाचि—वो। — √भा २/४० दीप्तौ (प)। √भास् (भासृ) १/ दीप्तौ (आ)।

ग—भाषते–ऐआ. ३,१,६; गोब्रा. १,१,३१।

ध—भासते–सुत्तनिपात ४५२। भासति–धम्मपद १,२४६; सुत्तनिपात १५८।

ङ—√भास (सक)= वचने। भासइ, भासंति–भग.; उव.।

छ—√भाषना * †, √भाखना * †, √भासना * † } (<भाषणम्)=भाषणे।

√भास् (भासृ) १/६१७ श — दीप्तौ (आ) क्षी-मै-सा-च-जै-काकृ-कात शा-हे-वो। — √भा २/४० दीप्तौ (प)। √भाष् (भाष) १/६०७ व्यक्तायां वाचि (आ)।

ग—भासते–कौलोप. २,५; योशि. ६,७७।

ङ—√भास (अक)=(१) शोभने, (२) प्रतीतौ। भासए, भासंति–मोह. २९; भत्त. ११०; सुर. ७,१६२।

छ—√भासना=(१) दीप्तौ, (२) प्रतीतौ, (३) दृग्गोचरत्वे, (४) सम्पर्चने, लिप्तौ।

√भिक्ष् (भिक्ष) १/६०२ — याच्ञायामलाभे लाभे च (आ) क्षी-हे। भिक्षायामलाभे लाभे च—सा। — √भज् (भज) १/ सेवायाम् (उ)।

याच्ञायां लाभेऽलाभे
च—मै ।
याच्ञायाम्—च-जै-
काक्र-कात-शा ।
लाभाऽर्यालाभोक्ति-
क्लिशि—वो ।
क्लेशे च व्यक्तायां वाचि
—क्षी ।
तत्तद्देशप्रसिद्धार्थानां
पृथङ्निर्देशः—क्षी ।

ग—भिक्षते-ऋ. ७,३२,१७; शब्रा. ११,३,३,५ ।
घ—भिक्खति-संयुत्त. १,१७६; चरियापिटक १,१४ ।
ङ—√भिक्ख (सक)=भिक्षणे । भिक्खइ-संबोध. ३१ ।

√भिद् (भिदिर्) ७/२ विदारणे (उ)
श
क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे ।
भिदि—वो ।

ग—अण्डानि भेदति-ऋ. ८,४०,१० (भौवादिकः) । अप…भिन्धि-ऋ. ८,४५,४० । भिनत्ति-तै. २,१,५,७; पै. ७,७,२ ।

घ—भिन्दति-दीघ. २,१०७ ।

ङ—√भिंद । भिंदइ-महा. ।

+√भिन्द् (भिदि) १/६४ अवयवे (प)
क्षी-मै-श-च-जै-काक्र-कात-शा-हे-वो×
सम्मतायाम्—सा सा ।

<√बिन्द् (बिदि) अवयवे (प) ।
√भिण्ड् १/१८५ हिंसायाम् (प) काक्र ।
√भिद् (भिदिर्) ७/२ विदारणे (उ) ।

ग—भिन्दुः-साब्रा. १,४,१४ ।

ङ—√भिंद (सक)=(१) भेदने, (२) विभागे (अवयवे) । भिंदइ, भिंदए-महा. ।

ङ—√भिद (सक)=(१) भेदने, (२) विभागे (अवयवे) । भिदंति—आचा. २,१,६,९ ।

√भी (ञिभी) ३/२ श	भये (प) क्षी-मै-सा-च-जै,-काक्ट (उ),-कात-शा-हे । भीत्याम्—वो ।	√भ्यस् (भ्यस)१/ भये (आ)। √भी (ञिभी) ९/२६ भये (प) च।

क—भोइ-: भुइ-: भी—जू. पॉकर्नीः ।

ख—अवे. वयेन्ते, व्येन्ते-वा. पॉकर्नीः ।

ग—भयते-ऋ. १,५८,५; तैब्रा. २,८,३,४ । बिभेति-ऐब्रा. ४,५; शब्रा. ५,२,१,१९ ।

घ—भायसि-थेरीगाथा २,२४८ ।

ङ—√भा
ङ—√भाअ } (अक)=भये । भाइ, भाअइ-महा.; स्वप्न. ८० ।

+√भुञ्ज् (भुगि)१/१५७ मै-सा-श-च-जै-काक्ट-कात-शा-हे-वो×	भर्जने (प) क्षी ।	<√वुञ्ज् (वुगि) वर्जने (प) ।

√भुज् (भुजो) ६/१३६ श	कौटिल्ये (प) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे । वक्रणे—वो ।	√भुञ्ज् (भुगि) १/ भर्जने (प) । √भुज् (भुज) ७/ पालनाभ्यवहारयोः (प) ।

ग—परिभुजद्रोदसी-ऋ. १,१००,१४ । निर्भुजति-याज्ञ. २,१४; सुश्रु. २,३३१, १९ । व्याभुग्न इव घर्मान्ते-हरिवंश. ४३१३ ।

√भुज् (भुज) ७/१७ श	पालनाभ्यवहारयोः (प) क्षी-मै-सा, काक्ट (उ),-कात-शा-हे । रक्षाशनयोः—जै । पालने—च । त्राणे भक्षे—वो ।	भोजते-निघ. २/१२= क्रुध्यतिकर्मा ।

ग—उभये भुञ्जते विशः-ऋ. २,२४,१०; कं मानुषी भोजते विट्-ऋ. १,७२, ८ । भुङ्क्ते-शांआ. ६,२०-(भुजोऽनवने १,३,६६ इति तङ्) मै. ४,२,१ । भुनक्ति-तै. २,६,२,४ ।

घ—भुञ्जति-सुत्तनिपात १०२ ।

ङ—√भुंज (सक)=अभ्यवहारे, (२) पालने, (३) उपभोगे, (४) अनुभवे। भुंजइ—कस.; उवा.।

+√भुण्ड् (भुडि) १/[२७४] मै-सा×,श	वरणे (आ)। [क्षी] शा-हे। भरणे—च-काकृ-कात। भृतौ वृतौ—वो।	√हुण्ड् (हुडि) १/ संघाते. (आ)।
√हुण्ड् (हुडि) १/२७४ श-च-जै-काकृ-कात-शा-हे-वो×	वरणे—क्षी-सा। हरणे—मै-सा।	
√भू १/१ श	सत्तायाम् (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√भु १/५५२ ॥ गतौ (आ) काकृ।

क—भॉइ; भॉईऐ-(भुआ-, भुए-,): भोउ-: भू-:
ख—अवे. ववैति=भवति—जू. पॉकर्नीः।
ग—भवति—ऋ. १,२८,१; खि. ४,१०,१; मा. ३२,८; का. ३२,१,५।
घ—भवसि—मज्झिम. ३,१४०।
घ—होमि—जातक. ३,२६०।
ङ—भोमि—पि. ४७६।
ङ—भुवइ—पि. ४७५।
ङ—हुअइ, हुएइ, हुंति—पि. ४७६।
ङ—हवइ—कप्प.।
ङ—होइ, होअइ—कप्प.; उव.; महा.।
छ—√होना=सत्तायाम्, उद्भवे।

√भूष् (भूष) १/६७३ श	अलङ्कारे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। भूषणे—वो।	√भू १/१ सत्तायाम् (प)।

ग—भूषसि—ऋ. ८,९२,२६; भूषेम—शौ. १९,६७,७।
ङ—√भूस (सक)=(१) अलङ्कृतौ, (२) शोभने। भूसेमि—कुमा.।
छ—√भूषना *†
छ—√भूखना } (<भूषणम्)=अलङ्कारे।

√भृ (भृञ्) १/८८४ शX

भरणे (उ)।
क्षी-मै-शा-च-जै-काक्र-शा-हे ।
भृतौ—वो ।

(कात-√वृ [वृञ्]) वरणे—कात ।

√भृ (डुभृञ्) ३/ धारण-पोषणयोः (उ)।
भुरन्तु–ऋ. ५,६,७ ।

क—भर्=भृतौ ।
ख—अवे. बरैति=भरति-जू. पॉकर्नीः ।
ग—अव˙˙˙भरते–ऋ. १,१०४,३ । भरते–तै. २,३,१४,३ । भरति–शौ. ८,३,१५ ।
ङ—√भर (सक)=भरणे । भरइ–भवि.; पिंग. ।

√भृ (डुभृञ्) ३/५ श

धारणपोषणयोः (उ)
क्षी-मै-सा-जै-काक्र-कात-शा ।
धारणे—च ।
धारणे पोषणे च—हे ।
भृतिपुष्ट्योः—वो ।

√भृ (भृञ्) १/ भरणे (उ)।

√भृ (डुभृञ्) ३/५ श-च-जै-काक्र-कातX

'धारणपोषणयोः' इति द्रमिडाः—क्षी ।
क्षी-मै-सा-शा-हे ।
भृतिपुष्ट्योः—वो ।

ग—बिभर्मि–ऋ. १०,१२५,१ । बिभर्ति–मा. १९,९४; का. २१,६,१५; तै. ४,३,११,५; मै. १,६,३ ।

+√भृज् (भृजी) १/१७५ शX

भर्जने (आ)।
क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो ।

√भ्रस्ज् (भ्रस्ज) ६/ पाके (उ)।

भर्जनम् =पाकविशेषः—क्षी ।

क—भेर्ज्=भर्जने ।

ख—म. पर्सि. बर्स्तन्–वा. पॉकर्नीः ।

ग—भर्जति–मैत्रायण्युप. ५,७ । भर्जितम्–शि. ६,२३ । माषाणां भर्जयेद् वाटीः–सुश्रु. १,२३०,१७ ।

(भृज्येयुः–मै. १,१०,११; काठ. ३६,६;) भर्गः–शौ. ९,१,४; पै. ६,१९,१ (=दीप्तौ); भृजः–मै. २,८,७ (तैक्ष्ण्ये) ।

+√भृड् (भृड) ६/११९ (क्षी) श-च-काकृ-कात, शा ?, हे-वो×	निमज्जने (प) इत्यप्येके—मै 'निमज्जने' इत्येके—आत्रेयः—सा। संघाते—शा।	>√भ्रुड् (भ्रुड) ६/ निमज्जने (प) इत्यपरे—मै। √हुड् (हुड) ६/ निमज्जने (प)। √क्रुड् (क्रुड) ६/ निमज्जने (प)। √भ्रुड् (भ्रुड) ६/ निमज्जने (प)।
+√भृश् (भृशु) ४/१११ श	अधःपतने (प) क्षी-मै-सा-च-काकृ-शा-हे। अधःपते—वो।	√भ्रंश् (भ्रन्शु) ६/ अधःपतने (प)।
(जै-कात-√भ्रश् [भ्रश]	अधःपतने—जै-कात।	

ग—भृशनिस्वनाः-वा. रा. २,४०,३१। भृशम्-मनु. ७,३२।

ङ—√भुल्ल (अक)=(१) च्युतौ, (२) अधःपाते, (३) विस्मृतौ-आत्म. १९।

+√भृष् (भृषु) १/७०० मै-सा-श-च-काकृ-कात-शा-हे-वो×	हिंसासंघातयोः (प) क्षी। हिंसायां संघाते च—जै।	√वृष् १/५११c हिंसायां संघाते च (प) शा-हे।
+√भॄ ९/२० श (शा)	भरणे (प) क्षी-हे। भर्त्सने—मै-सा-च-जै-काकृ-कात-हे। भृतौ भृजि भर्त्से—वो।	√बॄ ९/१८ भरणे (प) शा, २६-हे। √बॄ ९/१७b वरणे-काकृ, हे। √वॄ ९/ वरणे (प)।
(कात-√भॄ)	भरणे—कात।	
+√भॄ ९/२१	भर्जने, च=भरणे (प) क्षी-हे। भर्जने—शा। भृतौ भृजि भर्त्से—वो।	पूर्ववत्।

पूर्वधातोरभिन्नोऽयं क्षीरस्वामिना पृथक् संख्यायते।

+√भेष् (भेषृ) १/८६९ श×	भये (उ) क्षी-मै-सा-च, जै ?	√भ्यस् (भ्यस) १/ भये (आ)। √भी (ञिभी) ३/ भये (प)।

काक्र-कात-शा-हे-वो । √भीष् (हेतुभये षुक् ७/३/४०)।
√भ्रेष् (भ्रेषृ) १/८७० भये (उ)।

√भ्यस् (भ्यस) १/६२१ भये (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो ।
श×

>√भेष् (स) भ्रेषृ (स्र) भये इति चन्द्रः-क्षी। शेषः पूर्ववत्। भ्यसते भयवेपनयोः-निरु. ३,२१,६।

ग—अभ्यसेताम्-ऋ. २,१२,१; तै. १,७,१३,२; शौ. २०,३४, १। भ्यसात्-जै. १,३९,२।

√भ्रंश् (भ्रन्शु) १/७४७ अवस्रंसने (आ) क्षी-मै-सा-च-कात-शा-हे।
श (जै √भ्रंस्)।
(काक्र-सा—√भ्रश्) अवस्रंसने—सा-काक्र।

√भृश् (भृशु) ४/ अधःपतने (प)।
√भ्रंस् (भ्रन्सु) १/ अवस्रंसने (आ) सा।
√भ्रंश् (भ्रन्शु) ४/ अधःपतने (प)।
√भ्रश् (भ्रश) १/ अवस्रंसने (आ) सा।

ग—भ्रंशते-तै. १,६,११,१; ऐब्रा. ७,५।

√भ्रंश् (भ्रन्शु) ४/११२ अधःपतने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। अधःपते—वो।
श

√भ्रश् ४/४९ अधःपतने (प) जै, कात। शेषः पूर्ववत्।

ग—भ्रश्यतु क्षिप्रमद्यैव-वा. रा. २,७५,३४।
घ—भस्सति-जातक ४,२२३; ४,५३०।।

+√भ्रंस् (भ्रन्सु) १/७४३ अवस्रंसने (आ) सा सा। अवस्रंसे—जै।
क्षी-मै-श-च-काक्र-कात-शा-हे-वो×

>√भ्रश् (भ्रश) अवस्रंसने (आ) सा। शेषः पूर्ववत्।

+√भ्रक्ष् (भ्रक्ष) १/८९७ भक्षणे (उ) मै मै।
क्षी-श-च-जै-काक्र-

√भक्ष् (भक्ष) १/ भक्षणे (उ) मै।

कात-शा-हे-वो×	अदने—सा।	√भ्लक्ष् (भ्लक्ष) १/ भक्षणे (उ)।
+√भ्रण् (भ्रण) १/४४४ श-काक्-कात×	शब्दार्थः (प) क्षी मै-सा-च। शब्दे—जै-शा-हे-वो।	√भण् (भण) १/ शब्दार्थः (प)। √व्रण् (व्रण) १/ शब्दार्थः (प)।
√भ्रम् (भ्रमु) १/८३४ श-जै×	चलने (प) क्षी-मै-सा-च-काक्- कात-शा-हे। चाले—वो।	भ्रमति–निघ. २/१४= गतिकर्मा।

ग—भृमात्–ऋ. ७,१,२२। [धा. भ्रान्तौ वृत्तिः]। भ्रमति–ध्या. ५०; योचू. १४; गी. १,३०।

घ—भमति–जातक १,४१४।

ङ—√भुम=भ्रमणे। भुमइ–सण.।

छ—√भरमना, √भ्रमना* } = चलने।

छ—√भौंना, √भँवना, √भवना* † } (<भ्रमणम्)=चलने।

√भ्रम् (भ्रमु) ४/९२ श	अनवस्थाने (प) पुषादिः क्षी-मै-सा-च-काक्-कात-शा-हे। चलने—जै। चाले—वो।	

ग—भ्राम्यति–पार. गृह्य. ३,७; मभार. १३,४३१६; कथासरि. ९,९। भ्राम्यते–श्वेताश्वतरो. १,६।

√भ्रश् (भ्रश) १/७४३	अवस्रंसने (आ) सा। क्वचित् पठ्यते–सा-काक्।	√भ्रंस् (भ्रन्सु) अवस्रंसने (आ)। द्र.√भ्रंश् १/७४७

ग—भ्रशत्–ऋ. १०,१७३,१; शौ. ६,८७,१; शत्रा. ६,७,३,७।

√भ्रस्ज् (भ्रस्ज) ६/४ श	पाके (उ) क्षी-मै-सा-च-जै, काक् (प), कात-शा-हे-वो।	√भृज् (भृजी) १/भर्जने (आ)। √भृष् (भृषु) १/हिंसा-संघातयोः (प)।

ग—भृज्जाति–ऋ. ४,२४,७ । यवमुष्टिं भ्रज्जति–गोगृ. ३,७,४ ।
घ—भज्जति–विनय. ४,२६४ ।
ङ—√ भज्ज (सक)=पाके । भज्जंति, भज्जेंति–सूअनि. ८१; विपा. १,३ ।
छ—√ भूजना
छ—√ भूँजना† } (<भृज्जनम्)=भर्जने ।

√ भ्राज् (भ्राजृ) १/१७८ दीप्तौ (आ)
शा-जै-शा-हे-वो ×   क्षी-मै-सा-च-काक्ट-कात ।

√ राज् (राजृ) १/दीप्तौ (उ) ।
भ्राजते–निघ. १/१६=ज्वलतिकर्मा ।
भ्राशते–निघ. १/१६=ज्वलतिकर्मा ।

ग–अग्नेर्भ्राजन्ते अर्चयः–ऋ. १, ४४,१२; भ्राजते–१,५६,३ ।
ङ—√ भाज (अक)=दीप्तौ । विसे. ३४४७ ।

√ भ्राज् (भ्राजृ) १/८०६ दीप्तौ (आ)
क्षी-च-काक्ट ।
√ भ्राज् (टुभ्राजृ)··   'दीप्तौ'इत्येके–क्षी ।   पूर्ववत् ।
क्षी-मै-सा-जै-कात-शा-हे ।
भासि—वो ।

ग—भ्राजसे–तैब्रा. ३,१,६,४ । भ्राजन्ते–मा. १२,१०६ ।

+√ भ्राश्(टुभ्राशृ) १/८०७ दीप्तौ (आ)   पूर्ववत् ।
श × (काक्ट-कात-हे-√ भ्रास्)   क्षी-मै-सा-च-जै-काक्ट-कात-शा ।
भासि—हे-वो ।
भ्राशते-निघ. १/१६=ज्वलतिकर्मा ।
भ्राश्यति–निघ. १/१६=ज्वलतिकर्मा ।
भ्लाश्यति–निघ. १/१६=पाठान्तरम्–देवराजयज्वा ।

क—भ्रेश्=दीप्तौ–वा. पॉकर्नीः ।

ग—नि तिग्मानि भ्राशयन् भ्राश्यानि–ऋ. सं.८,६,२०,५; वा भ्राशम्लाश. ३/१/७० इति पक्षे श्यन् । उभेयपदित्वं वक्तुं शक्यम्, अस्य धातोरात्मनेपदित्वाद् वैदिकप्रयोगस्य परस्मैपदित्वाच्च ।

√भ्री ९/३४ श (च-√भीं)	भरणे (प) क्षी मै-सा-काकृ कात-हे। भये—सा-जै-शा-हे।	√भी (ञिभी) ३/भये (प)। भ्रीणाति-निघ. २,१२= क्रुध्यतिकर्मा। √भृ ९/२० भरणे (प)।

ग—भ्रीणन्ति-ऋ. २,२८,७; मै. ४,१४,९।

+√भ्रुड्(भ्रुड) ६/११० सा-श-जै-काकृ-कात×	संवरणे (प) क्षी-च। 'संघाते' इत्येके-मै। शा-हे ? संवृतिसंहत्योः-वो।	√व्रुड् (व्रुड) ६/संवरणे (प)। √भृड्(भृड) ६/निमज्जने (प)। √भृड् (भृड) ६/संवरणे (प) मैत्रेयस्तु-सा।
+√भ्रेज्(भ्रेजृ) १/११७ श×	दीप्तौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। भासि—वो।	र्+√एज्√रेज् (रेजृ) १/ दीप्तौ (आ) इति चन्द्रः-क्षी। भ्+√रेज्=√भ्रेज्। √एज्(एजृ) १/ दीप्तौ (आ)। √भ्राज्(भ्राजृ)१/१७८ दीप्तौ (आ)।
√भ्रेष्(भ्रेषृ) १/८७० श-च-जै×	भये (उ) क्षी।	√भ्रंश (भ्रन्शु) १/१७४ अवस्रंसने (आ)। भ्रेषति-निघ. २,१२= क्रुध्यतिकर्मा।

उत्तरधातोरभिन्नः क्षीरेण पृथक् संख्यातः।

ग—भ्रेषते जनो न रेषन्मनः-ऋ. ७,२०,६। भ्रंशेऽपि—रथो वर्तमानो भ्रेषन्नेति-ऐब्रा. ५,३३। भ्रेषम्-तै. ७,३,१,१; काठ. ७,११; क. ३१,१०।

√भ्रेष्(भ्रेषृ) १/८७१ श-च-जै×	चलने, च=भये (उ) क्षी-शा-हे। गतौ—सा।	

चलने--काक्ृ-कात। पूर्ववत्।
चले भये—वो।

क—भेर्-स्—ः नॉर्वे. (प्रादे.) त्रीस=क्रोधे, उद्वेगे, प्रकाशक्षेपे–वा. पॉकर्नीः।
ग—रथो वर्तमानो भ्रेषन्नेति–ऐत्रा. ४,३३ (भ्रंशे)।

+√ भ्लक्ष् (भ्लक्ष) १/८७८ शा-च-जै-शा× (कात-√ल्लष्) स्यात् त्रुटिः। भक्षणे (उ) क्षी-मै-कात-हे-वो। अदने--सा। काक्ृ ? >√ प्लक्ष् (प्लक्ष) भक्षणे (उ) इति दुर्गः–क्षी। √ भक्ष् (भक्ष) १/८९७ भक्षणे (उ) मै। √ भ्रक्ष् (भ्रक्ष) १/८९७ भक्षणे (उ) मै।

+√ भ्लाश् (टुभ्लाशृ) १/८०८ श×, (काक्ृ-कात-हे-√ भ्लास्) दीप्तौ (आ) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे। भासि—वो। √ भ्राश् (टुभ्राशृ) १/दीप्तौ (आ)। भ्लाशयति–निघ. १/१६=ज्वलतिकर्मा–पाठान्तरम्–देवराजयज्वा।

√ भ्लेष् (भ्लेषृ) १/८८९ क्षी-श-च-जै-काक्ृ-कात-शा-हे-वो× चलने (उ) मै। मै। गतौ--सा। √ भ्रेष् (भ्रेषृ) १/चलने च=भये (उ)।

√ मंह (महि) १/६२७ श× वृद्धौ (आ) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे-वो। √ मह् (मह) १०/ पूजायाम् (प)। मघमिति धननामधेयं मंहते-र्दानकर्मणः–निरु. १,७,१। मघम्–निघं. २/ १०=धननाम।

ग—शूरो मघा मंहते–ऋ. १, ११, ३; शौ. २०, ५१, ३। असंहत्–शत्रा. १३, ५, ४, ४।

+√ मक्ष् (मक्ष) १/६५४ श-च-काक्ृ-कात× रोषे (प) क्षी-हे। संघाते—मै-सा-जै-शा-हे। संघाते रोषे च—वो। √ मक्ष् १/५२२ दंशने (आ) काक्ृ। √ म्रक्ष् (म्रक्ष) १/ संघाते (प)। √ वक्ष् (वक्ष) १/ रोषे (प)। √ मट् १/९२ b संघाते (प) काक्ृ।

क—मर्कॉ-अथवा-मॉक्-ऑ (लॅ-,कॅ)=अश्वः, मक्षिका । मक्षू, आर्याणाम्-मॅक्क्षू=मङ्क्षु, शीघ्रम् । लैति.-मॅक्स्=क्षिप्रम् । म. किम्रिक्-मॉक्षू=मङ्क्षु, द्रुतम् । पु. इरिश्- मास्=मङ्क्षु, त्वरितम् ।

ख—अवे. मक्षिँ=मक्षिका । अवे.-मॉशू= मङ्क्षु, आशु-वा. पॉकर्नीः ।

ग—मध्वो न मक्षः-ऋ. ४, ४५, ९; मधुमन्मक्षिकारपत्-१, ११९, ९ । यूकामक्षिकमत्कुणम्-मनु. १, ४० । मक्षु (मङ्क्षु)-निघ. २/ १५=क्षिप्रनाम (संघाते) । मक्षूयुभिः-ऋ. ७, ७४, ४ ।

छ—माँखना*† (<मक्षणम्)=क्रोधे ।

छ—माखना*† (<मक्षणम्)=क्रोधे- "अब जनि कोउ माखइ भट मानी"-तुलसी. ।

छ—माँखी *† (<मक्षिका) ।

+√मङ्क् (मकि) १. ८६ शX	मण्डने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । भूषे—वो ।	√मङ्क् (मकि) १/३३३ ० गत्यर्थः (आ) कात । √मङ्ख् (मखि) १/ गत्यर्थः (प) । √मङ्ग् (मगि) मण्डने (प) इति जयमङ्गलः—भट्टिः १४, १० । √मक्क् १/ गतौ (आ) वो ।

क—मंक्=गोधने (चूर्णादिः), परिवेष्टने (निष्पीडने, चूर्णने) । स्ला.-मेंक्-क=मृदु । लैति. मंकुस्=हस्तः । पु. उ. ज. मंगॉन् =न्यूनत्वे, कार्यादिः साहाय्यमन्तरा करणे । लिथु. मेङ्कस्=दुष्टः, क्षुद्रः, लघुः-वा. पॉकर्नीः ।

ग—सोमातिपूतो मङ्कुरिव चचार-शब्रा. ५, ५, ४, ११ (=गतौ-, प्रस्पन्दने) । मङ्कणक०-मभार. ३, ६०८६ । कथासरि. ३२, १००=ऋषिविशेषः ।

घ—मंकु=आपन्न०- विनय. २, ११८ ।

ङ—मंकिअ (<मङ्कितम्)=कूर्दित्वा गमनम्-दे. ८, १५ ।

ङ—मंकाइ (<मङ्कातिः)=अन्तकृन्महर्षिरेकः-अंत. १८ ।

छ—√मनकना=प्रस्पन्दने, चलने ।

+√मख् (मख) १/१३२ शX	गत्यर्थः (प) क्षी-मै-सा-च-कात । गतौ—जै-काकृ-शा-हे ।	पूर्ववत् । √मच्छ् १ ३५५ j गतौ (प) काकृ । √मयूख् १/३८० गतौ (प)काकृ ।

सर्पणे—वो । √मृख् १/४६० c चलने (आ) काक्रु ।
√मुख् १/३८ g गतौ (प) काक्रु ।

क—मख्-ऑ-स्,—(स.) लो-=प्रसन्नम् ?-वाल्दे: पॉकर्नी: ।

ग—मखस्य ते (इन्द्रस्य)-ऋ. ३, ३४, २ । मख:-निघ. ३/१७=यज्ञनाम; मखेभ्य:-निरु. ३, २१, ६=मरुद्भ्य:-दुर्गाचार्य: (गतौ) ।

+√मङ्ख् (मखि) १/१३३ मै-श-च-काक्रु-कात-शा× गत्यर्थ: (प) क्षी-सा । गतौ—हे । सर्पणे—वो । द्र.√मङ्क् १/८६ । √मङ्ग् (मगि) १/१४७ गत्यर्थ: (प) ।

ग—मङ्ख० = मगधदेश:-राजत. ८, ९९७; मङ्खक०-८, ३४५५; मङ्खना-७, १०५ ।

ङ—मंख = वृषणौ-दे. ६, ११२ ।

ङ—मंख = चित्रपटेन जीवनस्य निर्वाहयित्री भिक्षुकजाति:-णाया. १, १ टी; औप.; पण्ह. २, ४; पिंड. ३०९ ।

+√मङ्ग् (मगि) १/१४७ श× गत्यर्थ: (प) क्षी-मै-सा-च कात । गतौ—जै-काक्रु-शा-हे । सर्पणे—वो । (भट्टि. १४,१० मण्डने—जयमङ्गल: द्रष्ट.√मङ्क् १/८६ मण्डने (आ) । √मग् १/४१० k आदाने (आ)काक्रु । अङ्गलम् (एतन्मकारोपजनेन मङ्गलम्-दुर्गाचा.) अङ्गवत्-निरु. ९, ४, १ ।

क—मंग्-अथवा-मेंग्=मण्डने, भूषे । ऑस्सेतन्-मंग्=छलम्, वञ्चना-त्रा: पॉकर्नी: ।

ग—मङ्गलोपेप्सा-शत्रा. १३, ८, १, १६ । मङ्गलार्थम्-मनु. ५, १५२ ।

ङ—√मंग (सक)=(१) गमने, (२) साधने, (३) ज्ञाने । कर्म-मंगिज्जए-विसे. २२ ।

+√मङ्घ् (मघि) १/१०७ श× गत्याक्षेपे (आ) क्षी । √मङ्क् (मकि) १/३३३ c गत्यर्थ: (आ) कात । √मख् (मख) १/ गत्यर्थ: (प) ।

√मङ्ख् (मखि) १/गत्यर्थः (प)।
√मङ्ग् (मगि) १/गत्यर्थः (प)।

गत्याक्षेपः = वेगगतिः, गमनारम्भो वा--क्षी।

उत्तरधातोरभिन्नः क्षीरेण पृथक् संख्यातः।

+√मङ्घ् (मघि) १/१०८ शX	कैतवे, च = गत्याक्षेपे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। अव्यर्थे (=गते निन्दारम्भजवेषु)—वो।	पूर्ववत्। √मघ् १/४१४ b गत्याक्षेपे कैतवे च (आ) काकृ।
+√मङ्घ् (मघि) १/१५८ क्षी-श-च-जै-काकृ-कात-शाX	मण्डने (प) मै-सा-हे। भूषे—वो।	√मङ्ग् (मगि) १/ मण्डने (प) इति जयमङ्गलः–भट्टि. १४,१०। √मह् (मह) १/७२२ पूजायाम् (प)।

ग—मघवा (न्)-मभार. ३,४५,१०-(मह्यते = पूज्यते। उणा. २/१५८)। एवं सत्यपि √मघ् इति दर्शनादिहोल्लेखः कृतो मया।

+√मच् (मच) १/१६८ श-कातX	कल्कने (आ)। क्षी-मै-सा-च-जै-काकृ-शा-हे। कल्कने दम्भे शाठ्ये—वो।	>√मुच् (मुच) कल्कने (प) इति चन्द्रः–क्षी। √मञ्च् (मचि) १/१७१ कल्कने (आ) सा।

क—मेंक् = गोधने (चूर्णादेः), परिवेष्टने, (निष्पीडने, चूर्णने)। लिथु.-मेङ्कस् = दुष्टः, क्षुद्रः, लघुः–वा. पॉकर्नीः।

+√मज् (मज) १/२४७ मै-सा-श-च-जै-काकृ-कात-शा-वोX	शब्दार्थः (प)। क्षी। शब्दे—हे।	>√मुज् (मुज) शब्दार्थः (प) इत्यप्याहुः–पुरुष- >√मृज् (मृज) शब्दार्थः (प) इत्यप्याहुः–क्षी। कारः (५७ पृ.)।

छ—√मचना = कोलाहलप्रधाने कार्यारम्भे, (२) विस्तारे (खेन तुलनीयः)।

+√मञ्च् (मचि) १/१७० श-काकृ ×	धारणोच्छ्रायपूजनेषु-(आ)। क्षी-मै-सा-कात। धारणे—च। कल्कने धारणोच्छ्राय-पूजासु च—जै। कल्कने धारणोच्छ्रायपूज-नेषु च—शा-हे। उच्छ्रायधृत्यर्चाभासु कल्कने दम्भे शाठ्ये—वो।	√मञ्च् १/४९० गतौ (आ) च। √मञ्ज् १/३१३a हिंसागत्योः (प) काकृ। √मुच् १/४२२a धारणो-च्छ्रायपूजनेषु (आ) काकृ। √मुच् १. ४२२a धारणोच्छ्रा-यपूजनेषु (आ) काकृ। √मुञ्च् १/४२२ b धारणो-च्छ्रायपूजनेषु (आ) काकृ। √मच्छ् १/३५५j गतौ (प) काकृ।
√मञ्च् (मन्चु) १/१७१	धारणोच्छ्रायपूजनेषु—सा। पवित्रीकरणे ?—ह्वि.।	

क—द्रष्ट. √मच् १/१६८।

ग—मञ्चांश्च कारयामासुः–मभार. १,५३२३ (=उच्छ्राये)।

छ—√माँचना (<मञ्चनम्)=प्रारम्भे।

छ—√माँछना (<मञ्चनम्)=प्रवेशे-(लश्क.)-तुल. √मच्छ् १/३५५ J गतौ (प) काकृ।

+√मञ्च् (मचि) १/१७१ क्षी-मै-श-च-कात ×	कल्कने (आ) सा। सा-जै-काकृ-शा-हे-वो। पूर्वस्मादभिन्नोऽयम्।	पूर्ववत्।
+√मठ् (मठ) १/३३० श १/३२९	मदनिवासयोः (प)। क्षी-मै-सा-जै-शा-हे। निवासे—च-काकृ-कात। वासमदयोः—वो। 'गतौ' इति क्वचित् पठ्यते—सा।	√मट् १/६२b संघाते (प) काकृ। √मट् १/ सादे (प) सौ. धा.–वो। √मण्ट् १/९८ दाहे (प) काकृ। मण्टयेदिव–तैत्रा. २,३,९,९।

ग—मठः-मैत्रेय्युप. २,१५; निर्वाणोप. २९८,१; मठाम्नायोप. ४९,१४; मठम् - १ योत. ३२; १ संन्या. २,७०। ०माठरीपुत्र०-शत्रा. १४,९,४,३१। माठरस्य वनम्-मभार. ३,८३३५; कुटीमठम्-मभार. १२,५३४८। (मटची-छान्दो. १,१०,१)।

छ—√ मठोरना † = तक्षणेन काष्ठचिक्कणादित्वे।

छ—√ मट(क)ना = साङ्गकम्पं गतौ, (२) अपसृतौ, (३) विचलने। तुल. √ मठ् १/३२९ गतौ (प) सा।

√ मण् (मण) १/४४० शX — शब्दार्थः (प)। क्षी-मै-सा-च। शब्दे—जै-काकृ-कात-शा-हे। कूजे—वो। — √ मञ् १/२४७ शब्दार्थः (प)।

ग—मणिना-ऋ. १,३३,३। मणितम्-शिशु. १०,७५।

+√ मण्ठ् (मठि) १/२६० श — शोके (आ)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। आध्याने—वो। — √ मण् (मण) १/४४० शब्दार्थः (प)।

शोकः = आध्यानम्—क्षी।

आध्यानम् = उत्कण्ठापूर्वकस्मरणम्।

छ—माँड़ा (<मण्ठः) = वटकविशेषः। "मण्ठस्तु बृंहणो वृष्यः"-इति राजनिघण्टः।

छ—मंठ (<मण्ठः) = वटकविशेषः।

छ—माँठी* = फुल्लधातोर्विलाप्य (द्रवीकृत्य) संहिताः (घटिताः) कङ्कणाः।

+√ मण्ड् (मडि) १/२६९ शX — विभाजने (आ)। क्षी-सा। वेष्टने—मै-सा-च-जै-काकृ-कात-शा-हे। विभागे वेष्टे च—वो। — √ वण्ड् (वडि) १/ वेष्टने (आ)। √ मण्ड् (मडि) १/ भूषायाम् (आ)। मण्डूका मज्जूका मज्जनात्; मदतेर्वा मोदतिकर्मणः, मन्दतेर्वा तृप्तिकर्मणः। मण्डयतेरिति वैयाकरणाः, मण्ड एषा-

मोक इति वा। मण्डो मदेर्वा मुदेर्वा–निरु. ९,५,२।

क—मेलाx = प्रकाशने–वा पॉकर्नीः।

ग—करालकणमण्डलम्–रघु. १२,९८।

ङ—√ मंड (सक) = (१) अग्र करणे, (२) प्रारम्भे–भवि.। माँडवुं–गुर्जरभाषा।

छ—√ मढ़ना
छ—√ मढ़वाना (प्रयो.) } (<मण्डनम्) = वेष्टने।

छ—√ माँड़ना = परिवेष्टने (चूर्णादेः)।

√ मण्ड् (मडि) १/३१८ श×	भूषायाम् (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे। भूषे—वो।	√ मण्ड् (मडि) १/२६९ वेष्टने (आ)। √ मट्ट् १/११६ भूषायाम् (प) काकृ। शेषः पूर्ववदवगन्तव्यः।

ग—मण्डूकः–ऋ. ७,१०३,१। मानक्षमं मण्डनकालहानेः–रघु. १३,१६। मण्डनान्मण्डनम्–कुमारसं. ७,५।

घ—√ मंड (सक) = भूषायाम्, मंडंति–पि. ५५७।

छ—√ मंडना * = भूषायाम्, (२) प्रतिपादने, पुष्टीकरणे।

√ मथ् (मथे) १/८३२ श×	विलोडने (प) क्षी-मै-सा-च-जै-कात- शा-हे। कुन्थे गाहे च—वो।
(काकृ–√ गथ (गथे)	विलोडने—काकृ।

ग—मथ-मथ–त्रिपुरातापिन्यु. ३,३१; व. ४३०:११। ममथुः–कथासरि. ४६,२२०। दैवादिकोऽप्ययम्—न गर्गरो मथ्यति–मभार. १२,१३२०४; समुद्रस्येव मथ्यतः–१,८२२३।

छ—√ महना*।
छ—√ मथना } (<मथनम्) = विलोडने।

√ मद् (मदी) १/३०३७ श×	हर्षग्लपनयोः (प) मित् क्षी जै-शा-हे।	√ मुद् (मुद) १/ हर्षे (आ)।

हर्षग्लेपनयोः—मै-सा-
काकृ-कात ।
हर्षे गर्वे ग्लपने—वो ।

ग—मदन्ति-ऋ. १,८४,१० । मदयन्ति-पै. १६,७५,९ ।

√मद् (मदी) ४/९५ हर्षे (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो ।

ग—माद्यति-नारदपरिव्राजको. ६,३१ । प्रमाद्यति-शब्रा. ११,३,१,७ ।

ङ—√मज्ज (अक)=अभिमाने । मज्जइ, मज्जई-उत्र.; सूअ. १,२,२,१; धर्मसं. ७८ ।

√मन् (मन) ४.६३ ज्ञाने (आ)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
बोधे—वो ।

ग—यन्न जरा इति मन्यसे-ऋ. ८,८२,५; मन्यते-१०,१४६,४; मनामहे-१,२६,८ ।

√मन् (मनु) ८.८ अवबोधने (आ)
श क्षी-सा-कात ।
बोधने—मै-च-जै,
काकृ-(उ),-शा-हे ।
बोधे—वो ।

ग—मनवते (उ-शप्-विकरणौ द्र.)-ऋ. १०,१२,६; मनुते-तै ५,५,६,१; शब्रा. ४,५,६,४ ।

घ—मनुते-धम्मसंगणि १२३ ।

√मन्थ् (मन्थ) १.४१ विलोडने (प) मै ।
क्षी-श-जै-शा-हे× मै-सा-च-काकृ (कात) ।
कुन्थे गाहे—वो ।

१/४४ संक्लेशार्थेनैवायं गतार्थ इति वागीशः । उदाहरणं च तत एव बोधनीयम् ।

√मन्थ् (मन्थ) १/४४ मै-श-च-काकृ-कात×	हिंसासंक्लेशयोः (प) क्षी-जै-शा-हे । हिंसासंक्लेशनयोः—सा (स्मरति) ।	>√मान्थ् (माथि) हिंसा-संक्लेशयोः (प) इत्यपि दुर्गः—क्षी ।
√मन्थ् (मथि)	हिंसासंक्लेशयोः (प) इत्यपि दौर्गाः–क्षी । क्षी-काकृ । हिंसासंक्लेशनयोः—मै-सा कुन्थे गाहे च—वो ।	

ग—मन्थन्ति–ऋ. ६,१५,१७ । मन्थति–तै. ६,२,१,७; काश्रा. १,५,३,२ ।

√मन्थ् (मन्थ) ९/४० श×	विलोडने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । गाहे—वो ।	

ग—मथ्नन्तः–ऋ. १,१२७,७ । मथ्नामि–शौ. २,३०,१; पै. २,१७,१ ।
ङ—√महुण (सक)=(१) विलोडने, (२) विनाशे–महा. ।

√मन्द् (मदि १/१३ श× (काकृ√मिन्दू[मिदि]) स्यात् त्रुटिः ।	स्तुतिमोदमदस्वप्नगतिषु (आ) । क्षी-सा-जै-शा-हे । स्तुतिमोदमदस्वप्न-कान्तिगतिषु—मै-काकृ-कात । जाड्ये—च । स्वप्ने जाड्ये मदे मोदे स्तुतौ गतौ—वो ।	मन्दते-निघ. ३/१४=अर्चतिकर्मा । मन्दते-निघ. १/१६=ज्वलतिकर्मा । √वन्द् (वदि) १/ अभि-वादनस्तुत्योः (आ) । √मद् (मदी) ४/ हर्षे (प) ।

ग—मन्दसे–ऋ. १,५१,१२; मन्दमानः–९,६५,५ । मन्दामि–तै. ४,२,६,१ ।

+√मभ्र् (मभ्र) १/५५७ श	गत्यर्थः (प) क्षी-मै-सा-च-कात । गतौ—जै-काकृ-कात-शा-हे । गत्याम्—वो ।	√वभ्र् (वभ्र) १/गत्यर्थः (प) । √अभ्र् (अभ्र) १/गत्यर्थः (प) ।

+√मय् (मय) १/४७३ गतौ (आ)
श-कात×
क्षी-मै-सा-च-जै-काकृ-
शा-हे-वो।

√मे (मेङ्) १/९४६ प्रणि-
दाने (आ)।
√पय् (पय) १/ गतौ (आ)।
√मयूख् १/३८ गतौ (प)
काकृ।

क—मॉइ=गतौ, भ्रमणे,-वा. पॉकर्नीः।

ग—सरस्वती नः सुभगा मयस्करत्-ऋ. १,८९,३। मयः=दानवविशेषः, स तु दैत्यानां शिल्पी। मय इवापः-ऋ. १,१७५,६; यो न ते मयः-१,१७६,८; शं च मे मयश्च मे-१०,१८,८।

+√मर्ब् (मर्ब) १/४१९ गतौ (प) मै।
क्षी-श-च-जै-शा-
हे×
मै-सा-काकृ-कात।
गत्याम्—वो।

अपमृपः-पै. १,६४,३।
√मर्व् (मर्व) १/ गतौ
(प) वो।
√मम्ब् (मम्ब) १/ गत्याम्
(प) वो।
√मर्क् सर्पे-सौ. धा.—वो।
√अर्ब् (अर्ब) १/ गतौ (प)।

+√मर्व् (मर्व) १/५७५ पूरणे (प)
श-जै×
क्षी-मै-सा-च-काकृ-कात-
शा-हे-वो।
पूर्तौ—वो।

√पर्व् (पर्व) १/ पूरणे (प)।
√पूर्व् (पूर्व) १/ पूरणे (प)।

+√मल् (मल) १/४८९ धारणे (आ)
श×
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
धृतौ—वो।

√मल्ल् (मल्ल) १/ धारणे
(आ)।

क—मेल्=मलम्=वा. पॉकर्नीः।

ग—खिन्नः स्नातो मलादिव-अ.वे. ६,११५,३। माला-आश्व. गृह्य. ३,८,१७। गोगृ. ३,५,१०।

ङ—√मल (सक)=धारणे-भग. ९,३३ टी.-पत्र. ४८०।

छ—√मलना (<मलनम्)=मुहुर्मुहुः स्पर्शे, मर्दने, (२) वेष्टने (धारणे)।

छ—√मलमलाना (<मलनम्)=मुहुर्मुहुः स्पर्शे, (२) असकृन्निमीलनोन्मीलनयोः, असकृदालिङ्गने।

+√मल्ल (मल्ल) १/४९० धारणे (आ)
शX
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
धृतौ—वो।

√मल (मल) १/४८९ धारणे (आ)।
√मुल १/४९८ c धारणे (आ) काकृ।
√मुल्ल १/४९८ d धारणे (आ) काकृ।
√मल्ह १/५४४ b हिंसायाम् (आ) काकृ।

क—मेलाx=प्रकाशने–वा. पॉकर्नीः।

ग—मल्ल०–मभार. २,१०७७। मार्क. पु. ५७,४४; भा. पु. १०, ४३,१७ (मल्लते=धरति बलम् इति)=बाहुयोधी।

घ—मल्ल=बाहुयोधी–विनय. २,१०५।

घ—मल्लक=पात्रम् ?–विनय. २,१०६।

ङ—√मल्ल (सक)=धारणे–भग. ९,३३ टी.–पत्र. ४८०।

छ—माल (<मल्लः)=बाहुयोधी।

+√मव् (मव) १/५९५ बन्धने (प)
शX
क्षी-मै-सा-च-कात-शा-हे।
बन्धने पालने च—काकृ।
नहे—वो।
(जै-√मट्) बन्धने—जै।

√मु १/५५८ a बन्धने (आ) काकृ।
√मव्य् (मव्य) १/ बन्धने (आ)।
√मू (मूङ्) १/ बन्धने (आ)।

क—मेउ्-(आर्याणाम्–मॉइए-, मिएउ्ऍ)–वा. पॉकर्नीः।

+√मव्य् (मव्य) १/५०९ बन्धने (प)
शX
क्षी-मै-सा-च-जै-कात-शा-हे।
बन्धने पालने च—काकृ।
बन्धे—वो।

√मव् (मव) १/ बन्धने (प)।
√मु १/५५८ a बन्धने (आ) काकृ।

दिवादिविकरणको भ्वादौ प्रयुक्तः।

+√मश् (मश) १/७१६ शब्दे रोषकृते च (प)
शX
क्षी-मै-सा-जै।
शब्दे—च।
शब्दे रोषे च—काकृ-कात-हे।

√मष् (मष) १/ हिंसार्थः (प)।
√मक्ष् (मक्ष) १/ रोषे (प)।
√मिश् (मिश) १/ शब्दे

शब्दे रोषकृतौ च—शा। रोषकृते च (प)।
ध्वनौ कोपे—वो।

क—मशां-अथवा-मॉशओ (-लॉ,-कॉ-,)=अश्वः, मक्षिका (मशकः)-वा. पॉकर्नीः।

ग—मशकस्यारसं विषम्-अ. वे. ७,५६,३।

छ—मसैरी, मसहरी- मसारी (<मशहरी। -हरतेरनुद्यमने ३/२/९ अच्। स्त्रियां ङीप्)।

+√मष्(मष) १.६८२ हिंसार्थः (प) √मुष् (मुष) १. हिंसार्थः (प)।
शX क्षी-मै-सा-कात।
हिंसायाम्—च-जै-काक्ष-शा-हे।
वधे—वो।

क—मेर्=सञ्चूर्णने। मेर्-स्—वा. पॉकर्नीः।

ग—एकविंशत्या माषैः—तै. ५,१,८,१। मष्मषाकरं दृपदा खल्वाँ इव-अ.वे. ५,२८,८ (=आघाते, सञ्चूर्णने)। रोमाणि मषं कारयित्वा-शाङ्खा. गृ. १,२४। मष्णार० ऐत्रा. ८,२३; भा. पु. ९,२०,२८।

+√मस् (मसी) ४.१०८ परिणामे (प) >√बस् (बसी) च=परिणामे (प) इति कण्ठः—क्षी।
श क्षी-हे।
परिमाणे—मै-सा-च-जै-काक्ष-कात-हे।
परिभाषणे—शा।
परीणामे—वो।
√पस् ४.६० ॥ परिणामे (प) च।
मासा मानात्-निरु. ४,२७,१।
√मस्त् १०/४२ धारणे (प) काक्ष।

परिणामः = विकारः—क्षी।

क—मॅज्घॉ, मॅस्घॉ=सारः, तत्त्वम्—वा. पॉकर्नीः।

क—मॅनॅस्-(मॅन्स्-*मॅस्)

ख—अवे.-माँ, (षष्ठी) माँहो। न. पर्सि. माह्=मासः।

ग—मस्तिष्काज्जिह्वायाः-ऋ. १०,१६३,१। मस्तक०-मनु. ११,४३; मभार. ५,२०४६। भारपीडाव्यथितमस्तकः-मा. पु. १४,७८। मसारगल्वर्क०-वा. रा. ३,४८, १२; ५,९,१८; मभार. १२,१५८५ (=इन्द्रनीलमणिः)। मसारताराक्षि-नैषध. ९, १०४। यशो मसीमयम्-नैषध. ९,६३ (मसी=काली)।

छ—माथा (<मस्तकः)।

छ—मसा (<मसकः-भावप्रकाशे (श. क. द्रु.)-"माषवत्कृष्णमुत्सन्नं मलिनं मसकं दिशेत्")।

+√मस्क् (मस्क) १।९९ गत्यर्थः (आ)
शा-काकृ-कात× क्षी-मै-सा-च।
गतौ—जै-शा-हे-वो।

√मस् (मसी) ४। परिणामे (प)।

√वस्क् (वस्क) १। गत्यर्थः (प)।

√मस्त् १०/४२ धारणे (प) काकृ।

? छ—√मह्कना (<मस्कनम्)=(गति)-गन्धयोः।

√मस्ज् (टुमस्जो) ६।१३४ शुद्धौ (प)
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
स्नाने ब्रुडने—वो।

√मृज् (मृजूष्) २।५५ शुद्धौ (प)।

√म्रक्ष् (म्रक्ष) १/६६५ संघाते (प) मै।

ग—मज्जन्ति-ऋ. ९,६४,२१। मज्जति-पत्रा. ५,७।

घ—निमुज्जति-अंगुत्तर. ४, २।

ङ—√मज्ज (अक)=स्नाने, (२) ब्रुडने। मज्जामो-महा. ५७,७।

छ—√मज्जना* = स्नाने, (२) ब्रुडने।

छ—√माँजना (<मज्जनम्)=परिमार्जने।

√मह् (मह) १/७२२ पूजायाम् (प)
श-जै-शा× क्षी-मै-सा-च-काकृ-कात-हे।
पूजे—वो।

क—मेज् (ह्न)=दीर्घम्, विशालम्।

ख—अवे.-मजन्=दीर्घता, विशालता-वा. पॉकर्नीः।

ग—सं महेम-ऋ. १,९५,९४; ७,२,३। रातिं सत्पतिं महे-वा. सं. २२,१३।

घ—महति-विमानवत्थु४७।

√मा २।५१ माने (प)
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
मानम् = वर्तनम्—क्षी।

शब्दे रोषकृतौ च—शा। रोषकृते च (प)।
ध्वनौ कोपे—वो।

क—मशॉ-अथवा-मॉशओ (-लॉ,-कॉ-,)=अश्वः, मक्षिका (मशकः)-वा. पॉकर्नीः।

ग—मशकस्यारसं विषम्-अ. वे. ७,५६,३।

छ—मसैरी, मसहरी- मसारी (<मशहरी। -हरतेरनुद्यमने ३/२/९ अच्। स्त्रियां ङीप्)।

+√मष् (मष) १.६८२ हिंसार्थः (प) √मुष् (मुष) १. हिंसार्थः (प)।
श× क्षी-मै-सा-कात।
हिंसायाम्—च-जै-काकृ-शा-हे।
वधे—वो।

क—मेर्=सञ्चूर्णने। मेर्-स्—वा. पॉकर्नीः।

ग—एकविंशत्या माषैः-तै. ५,१,८,१। मष्मषाकरं दृषदा खल्वाँ इव-अ.वे. ५,२८,८ (=आघाते, सञ्चूर्णने)। रोमाणि मषं कारयित्वा-शाङ्खा. गृ. १,२४। मष्णार० ऐत्रा. ८,२३; भा. पु. ९,२०,२८।

+√मस् (मसी) ४.१०८ परिणामे (प) >√बस् (वसी) च=परिणामे (प) इति कण्ठः—क्षी।
श क्षी-हे।
परिमाणे—मै-सा-च-जै-काकृ-कात-हे।
परिभाषणे—शा।
परीणामे—वो।
√पस् ४.६० a परिणामे (प) च।
मासा मानात्-निरु. ४,२७,१।
√मस्त् १०/४२ धारणे (प) काकृ।

परिणामः = विकारः—क्षी।

क—मॅज्घॉ, मॅस्घॉ=सारः, तत्त्वम्—वा. पॉकर्नीः।

क—मेनेस्-(मेन्स्-*मेस्)

ख—अवे.-माँ, (षष्ठी) माँहो। न. पर्सि. माह्=मासः।

ग—मस्तिष्काज्जिह्वायाः-ऋ. १०,१६३,१। मस्तक०-मनु. ११,४३; मभार. ५,२०४६। भारपीडाव्यथितमस्तकः-मा. पु. १४,७८। मसारगल्वर्क०-वा. रा. ३,४८, १२; ५,९,१८; मभार. १२,१५८५ (=इन्द्रनीलमणिः)। मसारताराक्षि-नैषध. ९, १०४। यशो मसीमयम्-नैषध. ९,६३ (मसी=काली)।

छ—माथा (<मस्तकः)।

छ—मसा (<मसकः-भावप्रकाशे (श. क. द्रु.)-"माषवत्कृष्णमुत्सन्नं मलिनं मसकं दिशेत्")।

+√मस्क् (मस्क) १/९९ गत्यर्थः (आ)
श-काकृ-कात× क्षी-मै-सा-च।
गतौ—जै-शा-हे-वो।

√मस् (मसी) ४/ परिणामे (प)।
√वस्क् (वस्क) १/ गत्यर्थः (प)।
√मस्न् १०/४२ धारणे (प) काकृ।

? छ—√मह्कना (<मस्कनम्)=(गति)-गन्धयोः।

√मस्ज् (टुमस्जो) ६/१३४ शुद्धौ (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
स्नाने ब्रुडने-वो।

√मृज् (मृजूष्) २/५५ शुद्धौ (प)।
√म्रक्ष् (म्रक्ष) १/६६५ संघाते (प) मै।

ग—मज्जन्ति-ऋ. ९,६४,२१। मज्जति-पत्रा. ५,७।

घ—निमुज्जति-अंगुत्तर. ४, २।

ङ—√मज्ज (अक)=स्नाने, (२) ब्रुडने। मज्जामो-महा. ५७,७।

छ—√मज्जना* = स्नाने, (२) ब्रुडने।

छ—√माँजना (<मज्जनम्)=परिमार्जने।

√मह् (मह) १/७२२ पूजायाम् (प)
श-जै-शा× क्षी-मै-सा-च-काकृ-कात-हे।
पूजे—वो।

क—मेज् (ह्न)=दीर्घम्, विशालम्।

ख—अवे.-मजन्=दीर्घता, विशालता-वा. पॉकर्नीः।

ग—सं महेम-ऋ. १,९५,९४; ७,२,३। रातिं सत्पतिं महे-वा. सं. २२,१३।

घ—महति-विमानवत्थु४७।

√मा २/५१ माने (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो।

मानम् =वर्तनम्—क्षी।

ग—क्षेत्रमिव वि ममुः-ऋ. १,११०,५। तनौ ममुस्तत्र-शिशु. १,२३। गिरं निर्मान्ति वाग्मिनः-मनु. ५,६४। माति-भा. पु. २,७,३०; कथासरि. २२,१३१।

√मा (माङ्) ३/६ मानेशब्दे च (आ)
श क्षी-मै-सा-काकृ-कात।
माने—च-जै-शा।
मानशब्दयोः—हे।
शब्दे माने च—वो।

ग—मिमीते-ऋ. ३,१,५; शब्रा. ३,३,२,९। गावो निर्मान्ति धेनवः-ऋ. ९,३३,४।

(+)√मा (माङ्) ४/३३ माने (आ) इति दुर्गः-क्षी। मायते-निघ. ३/१९ =
च-शा×,श क्षी-मै-सा-जै-काकृ-कात- याच्ञाकर्मा।
हे-वो।

+√माङ्क्ष् (माक्षि) १/६६० काङ्क्षायाम् (प)
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
स्पृहे—वो।
'न'-मध्यपाठेनैवेष्टसिद्धेः, इदनुबन्धो वेदेषूच्चारणभेदार्थः-दुर्गादासः।
ङ—√मह (सक)=काङ्क्षायाम्। महइ-कुमा.; सण.।

+√मान् (मान) १/९५७ पूजायाम् (आ) √मन् (मन) ४/ ज्ञाने (आ)।
श× क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
विचारे, अर्चे च—वो।
√मन्+सन्- ह्वि.।

ग—मीमांसन्ते-तै. ६, २, ६, ४; शांब्रा. २, ९; नृसिंहपूर्वतापिन्यु. ३, ३; वरदपूर्वतापिन्यु. २, २।
ङ—√मीमंस (सक)=विचारे-स. ७३०।
ङ—√वीमंस-(सक)=विचारे, पर्यालोचने-सम्मत्त. ५६।

+√मान्थ् (माथि) १/४४ हिंसासंक्लेशयोः (प) इत्यपीति दौर्गाः- क्षी-हे। कुन्थे—वो।
मै,सा (चौ. सं. ×),-च-जै-काकृ-कात-शा×
<√मन्थ् (मन्थ) हिंसासंक्लेशयोः (प)।
<√मन्थ् (मथि) हिंसासंक्लेशयोः (प) इत्यपीति दौर्गाः-क्षी।

कुन्थः=वधक्लेशौ-दुर्गादासः।

+√माह्‌ (माहृ) १/८८० माने (उ)
शX(च-√माह्‌ क्षी-मै-सा-च-जै-काक्र-
[माह]) कात-शा-हे-वो।
मानम्‌=वर्तनम्‌।

√मह्‌ (मह) १/ पूजायाम्‌ (प)।

ग—माहकस्थली-धूमादिगणे पा. ४/२/१२७।
छ—माहिल=आल्हाखण्डस्य योद्धैकः।

√मि (डुमिञ्‌) ५/४ प्रक्षेपणे (उ)
श क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे।
क्षेपे—वो।

√मि १/२२५ गतौ (प) काक्र।
मिनोति-निघ. २/१९= वधकर्मा।
मिनाति-निघ. २/१९= वधकर्मा।
मिनाति-निघ. २/१४= गतिकर्मा।

ग—मिनोतु-ऋ. १०,१८,१३; तैआ. ६,७,१। मिनोति-तै. ५,५,७,१; शब्रा. ३,६,१,२।

ङ—√मिण (सक)=(१) परिमाणे, माने उन्माने, (२) ज्ञाने, निश्चये। मिणइ-विसे. २१८६।

+√मिच्छ्‌ (मिछ) ६/१८ उत्क्लेशे (प)
श क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे।
बाधे—वो।

<√पिच्छ्‌ (पिछ) उत्क्लेशे (प) इति द्रमिडाः-क्षी।
√मिष्‌ (मिष) ६/स्पर्धायाम्‌ (प)।
√मिष्‌ (मिषु) १/सेचने (प)।

ग—मिच्छमानाः-खि. २,१४,११।
ङ—√मीचना
ङ—√मीटना } (<मिच्छनम्‌)=उन्मीलनबाधे, निमीलने।
स्पर्धार्थक-मिष्‌-धातुतो व्युत्पत्तिः शक्यते कर्तुम्‌।

√मिथ्‌ (मिथृ) १/८५३ मेधाहिंसनयोः (उ)
मै-श-जै काक्र-कातX क्षी-सा।
मेधाहिंसयोः—शा-हे।
वधे मेधायाम्‌—वो।

मेथतिराक्रोशकर्मा-निरु. ४,२,१।
√मिद्‌ (मिदृ) १/८५३ मेधाहिंसनयोः (उ)।

√मिध् (मिधृ) १/८५३ मेधा-हिंसनयोः (उ) सा ।
√मृध् (मृधु) १/८५९ उन्दे (उ) ।
√मथ् (मथे) १/ विलोडने (प) ।

ग—मिथती (तौदादिकः ?)-ऋ. ७,९३,५; मेथेते-१,११३,३ । मिथुनम्-वा. रा. १,२,१५ । मिथित्वा-भा. पु. ४,२९,५३=मिथुनीभूय ।

√मिद् (ञिमिदा) १/७३४ स्नेहने (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे । स्निहि—वो । स्नेहे—जै । पूर्ववत् ।
शX

√मेद् ६/.... —ह्वि. ।

ग—मेदताम्-ऋ. १०,९३,११ । मेदुरम्-गी. गोवि. १,१ ।

+√मिद् (मिदृ) १/८५३ मेधाहिंसनयोः (उ) इति दुर्गः-क्षी क्षी-सा । मेधाहिंसयोः—मै-च-कात-हे । गतिहिंसयोः—काकृ । वधमेधयोः—वो । द्रष्ट.√मिथ् (मिथृ) १/ मेधाहिंसनयोः (उ) ।
श-जै-शाX

√मिद् (ञिमिदा) ४/१३० स्नेहने (प) क्षी-मै-सा-च-काकृ-कात-शा-हे । स्नेहे—जै । स्निहि—वो । √मिद् (ञिमिदा) १/ स्नेहने (प) । √मिन्द् (मिदि) १०/ स्नेहने (प) ।
श

ग—मेद्यन्तु-ऋ. १०,९३,११ । मेद्यति-तै. ५,१,२,५ ।
घ—मेज्जति-धम्मसंगणि १९२ ।

+√मिन्व् (मिवि) १/५८४ श-जै× | सेचने (प) क्षी-मै-सा-च-काकृ-कात शा-हे। सेके—वो। | √निन्व् (निवि) १/ सेचने (प)। √पिन्व् (पिवि) १/ सेचने (प)।

√मिळ् (मिल) ६/८३ (क्षी) श-च-जै× (लौकिकात्–६/८२–क्षी) | श्लेषणे (प) मै क्षी-मै-सा-काकृ-कात-शा-हे। श्लिषि—वो (उ)। | √मीळ् (मील) १/ निमेषणे (प)।

ग—अभिसममिलत्–मै. १,५,१२। मिलित्वा–योगकुण्डल्यु. १,६५; वरदोत्तर-तापिन्यु. ४,२६। मिलन्ति–कथासरि. १९,५३।

ङ—√मीळ् (अक) = श्लेषणे–वि. ११।

√मिल् (मिल) ६/१५५ क्षी-श-जै-काकृ-कात-शा-हे× | सङ्गमे (उ) मै। मै-च। सङ्गमने—सा। श्लिषि—वो।

ग—(मेलके बलाबलमुक्तम्–मनुटीकायां कुल्लूकभट्टः–२,१३६)। मिलिता देवदानवाः–दे. भा. १,११,८०। ततो विद्याधरेन्द्रेण मिलिष्यामः सुमेरुणा–कथासरि. ४५,७।

ङ—√मिल (अक) = मेलने–रंभा.;महा.; वकृ.–मिलंत–से. १०१६।

छ—√मिलना = सङ्गमे, साक्षात्कारे, श्लिषि।

+√मिश् (मिश) १/७१५ श× | शब्दे रोषकृते च (प) क्षी-मै-सा-जै-कात। शब्दे रोषकृतौ च—शा। शब्दे—च। शब्दे रोषे च—काकृ-कात-हे। ध्वनौ कोपे—वो। | √मश् (मश) १/ शब्दे रोषकृते च (प)।

ङ—√मिस (सक) = शब्दे–तंदु. ४४।

+√मिष् (मिषु) १/६९० श× | सेचने (प) क्षी-मै-सा-च-जै- | √मृष् (मृषु) १/६९८ सेचने (प)।

काक्-कात-शा-हे वो। √मिह् (मिह) १/९७७ सेचने (प)।

ग—मेषत्-मै. ४,१४,१६ ['नेषत्' इति शोधः (तु. सपा. १०,१७,५;Bc.)]। मिष्टः=मधुररसः। यथा-'मिष्टः कटुश्च'-भावप्र. (श. क. द्रु.)।

—√मिष् (मिषु) ६/७३ स्पर्धायाम् (प)
श×
क्षी-मै-सा-च-जै-शा-हे।
स्पर्धायां वाचि—काक्।
कात ?
स्पर्धे—वो।
निमीलोन्मीलनयोः—ह्वि.।
मेषो मिषतेः (=दर्शनार्थस्य—दुर्गाचा.)—निरु. ३,६,७।

क—मेइस्=निमीलोन्मीलनयोः-वा. पॉकर्नीः।

ग—गौरमीमेदनु वत्सं मिषन्तम्-ऋ. १,१६४,२८; शौ. ९,१५,६; -मिषन्तम्=अनिमिषन्तम् (=अव्यवहितदर्शनम्-दुर्गाचा.)-निरु. ११,४२, १। पीवानं मेषमपचन्त वीराः-ऋ. १०,२७,१७ (मिषति=अन्योन्यं स्पर्द्धते इति)। सुखं मेषाय मेष्यै-वा. सं. ३,५९। मिषम्-नैषध. १,११८=छलम्। मिषं कृत्वा-कथासरि. ६४,१२५=स्पर्द्धनम्। मिषताम्-मभार. ८,४१,३०=पश्यताम् (नील.)।

घ—निमिसति दीघ. २,२०

√मिह् (मिह) १/९७७ सेचने (प)
श
क्षी-मै-सा-च-जै-काक्-कात-शा हे।
सिचि—वो।
मिक्षति-निघ. २/१४=गतिकर्मा।
मेक्षामि-शौ. ७,१०७,१।
मेघयन्ती-तै. ४,४,५, १।

क—मेइघु=जलोत्सर्गे, मूत्रोत्सर्गे। अर्मे. मेज्। लैति, मेइऑ। पु. आइस्. मीग। लिथु. मिश्ति=मूत्रणे। (लिथु. मेज़्त) स्ला. मूज़ेति।

ख—अवे. मएजैति=मेहति-जू. पॉकर्नीः।

ग—अवमेहन्ति-ऋ. ९,७४,४। मेहति-तै. ७,१,१९,३; शब्रा. १०, ६, ४,१। मेहतु-वा. रा. २,७५,२२=अभिमुखं मूत्रादिकं करोतु (तिल.)।

√मी (मीङ्) ४/२९ हिंसायाम् (आ)
श
क्षी-मै-सा-च-जै-काक्-कात-शा-हे।
वधे—वो।

ग—मीयते-गोब्रा. २,२,४ । तस्यै द्वै अक्षरे अमीयेताम्-तै. ६,१,६,२ । मीयते ? अमीयत-कौषीतकिब्राह्मणो. ३,१ । प्रमीयताम्-वा. रा. २,७५,३५=म्रियताम् (तिल.) । बालाश्च न प्रमीयन्ते-मनु. ९,२४७ = म्रियन्ते (मन्वर्थ.) ।

√मी (मीञ्) ९/४ श | हिंसायाम् (उ) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे । वधे—वो । | √मिनोति, मिनाति-निघ. २/१४ = वधकर्मा ।

ग—मिनाति-तैब्रा. २,६,४,३ । मेति (आदादिकः ?) तैआ. १०,४८,१[1] । [१ गतौ, २ हिंसायामिति विवेकः]; प्रमीणाति, प्रमीणीते-मभाष्ये-८,४,१५; ४ ⁄ ५ ⁄ ८ ।

घ—मिनाति-विभंग. १०८ = मापने (ऋ. १,७१,१०) ।

+√मीमृ (मीमृ) १/४६२ शा-जै×(काक्ृ-√मि, √मृ, इति द्वौ धातू) । | गतौ (प) । क्षी-मै-सा-च-काक्ृ-कात-शा । गतौ शब्दे—वो । गतौ शब्दे च—हे ।

√मीम् (मीमृ) १/४६३ | शब्दे, च = गतौ (प) । क्षी । | मिमाति-३/ गर्जने, ह्वि-√मा । गावो मिमन्ति धेनवः-ऋ. ९,३३,४ ।

पूर्वधातोरभिन्नमिमं क्षीरस्वामी पार्थक्येन संख्याति ।

ग—मीमति-ऋ. १,३८,८ (=शब्दे); १,६९,४; गौरमीमेत्-१,१६४,२८; मीमयत्-२०,२७,२२ ।

√मील् (मील) १/५१८ श | निमेषणे (प) । क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे । निमेषे—वो । | √मिल् (मिल) ६/ संगमे (प) । √मिष् (मिष) ६/ स्पर्धायाम् (प) ।

क—द्रष्ट. √मिष् ६/७३ ।

ग—उन्मीलन्ति निमीलन्ति-षब्रा. ६,१०. (इन्दि. स्तु. १,४१,१०) । तदा सर्वं निमीलति-मनु. १,५२ । मीलितः-ऐआ. २,१,४ ।

घ—निमीलति–जातक १,२७९।

छ—मीड़ना (<मीलनम्) नेत्रमर्दने–बुं. ख.।

√मीव् (मीव) १/५६३ स्थौल्ये (प)।
श×
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
पीवे—वो।
प्रेरणे, अपसारणादौ—
ह्वि.।

क—मेऊ्-, मेऊएँ-(आर्याणाम्-मिएऊए-ः मीऊ्-)=प्रेरणे। लिथु. मौति=परिवर्तने।

ख—अवे. मीवामहि=पार्थक्ये, अपसारणे–जू. पॉकर्नीः।

ग—तं स्तोत्राय प्रमीवति–शत्रा. ५,२,२,१९; ५,४,४,२५=प्रेरणादौ।

ग—[मीवगः=दीर्घः, महान्, पर्वतः–महाव्युत्पत्तिः १७९;] (बौद्ध-साहित्ये प्रयुक्तप्रायः)।

+√मुङ्ख् (मुखि) १/१३९ गत्यर्थः (प) चन्द्रः पपाठ—सा। सा।
क्षी-मै-श-च-जै-काकृ-
कात-शा-हे-वो×

√मङ्ख् (मखि) १/ गत्यर्थः (प)।
√मुख् १/३८ g गतौ (प) काकृ।

? ग—मुङ्ख०–राजत. ७,१९०; मुङ्खट०–८,१०९२।

+√मुच् (मुच) १/१६८ कल्कने (आ) इति चन्द्रः—क्षी। क्षी-सा-कात-हे। कल्कने दम्भे शाठ्ये—वो।
मै-श-च-जै-काकृ-शा×

<√मच् (मच) कल्कने (आ)।
√मुच् १/४२२ a धारणोच्छ्रायपूजनेषु (आ) काकृ।

√मुच् (मुच्लृ) ६/१४७ मोक्षणे (उ)।
जै×, श
क्षी-मै-सा-च-काकृ-
कात-शा-हे।
मोक्षे—वो।

द्रष्ट. √मञ्च् १/१७०।

क—मॉङ्ग्-, मॉङ्क्-स्-ः=सर्पणे, स्खलने। लिथु.–मुक्ति=मोचने, पलायने, रक्षणे–जू. पॉकर्नीः।

ग—मुमोक्तु–ऋ. ८,६७,१४; मुमोचति–८,१८ [१२; ६७, १८]। मुञ्चति–तै. २,१,२,२।

घ—मुञ्चति–जातक १,३७५।

ङ—√मुंच (सक)=त्यागे। मुंचइ–कुमा.।

ङ—√मुअ=त्यागे। मुअंति–गा. ३१९।

च—√मुव=त्यागे। मुवइ–भवि.।

च—√मुक्क (सक)=त्यागे। मूकवुं–गुर्जरभाषा।

छ—मोकना *† =त्यागे, (२) प्रक्षेपणे।

+√मुञ्च् (मुचि) १/१६९ श-जै-काकृ-शा×	कल्कने (आ)। क्षी-मै-सा-च-कात-हे। कल्कने दम्भे शाठ्ये—वो। कल्कनम्= दम्भः कथनं च—क्षी। कल्कनम्= दम्भः शाठ्यं च—मै।	√मुच् (मुच्लृ) ६/ मोक्षणे (उ)। √मुञ्च् १/५१५ गतौ (प) जै। द्र.√मञ्च् १/१७०।

मच् १/१६८ >√मञ्च् १/१७१ >√मुच् १/१६८ >√मुञ्च् इति व्युत्पत्तिः।

+√मुज् (मुज) १/२४७ श-जै-कात-वो×	शब्दार्थः (प) इत्यप्याहुः—क्षी। क्षी-मै-सा-च। शब्दे—काकृ-शा-हे।	√मज् (मज) शब्दार्थः (प)। √मुज् १०/ मृजाध्वन्योः (प) वो।

क—द्रष्ट. उत्तरधातुः।

+√मुञ्ज् (मुजि) १/२४८ श-जै-वो×	शब्दार्थः (प) क्षी-मै-सा-च-कात। शब्दे—काकृ-शा-हे।	>√मृञ्ज् (मृजि) शब्दार्थः (प) इत्यप्याहुः—क्षी। √म्रुज् १/७९i शब्दे (प) काकृ। √म्रुञ्ज् १/७९j शब्दे (प) काकृ।

क—मु-,मू-कण्ठ्यवर्णविस्तारः-ग् (ज्)=ध्वनौ। लैति. मोगिओ-ईरे= गर्जने, ध्वनौ–वा. पॉकर्नीः।

√मुच् ६/१४७>√मुञ्च् १/१६९>√मुञ्ज् इति विकासः। निरुक्ते ९.८,१ तु मुञ्जशब्दः√मुच् ६/१४७ धातुना साध्यते। तद्यथा–"सोमस्येव मौज-

वतस्य भक्षः मौजवतो । मूजवति जातः । मूजवान् पर्वतो मुञ्जवान् । मुञ्जो विमुच्यते इषीकया ।" अत्र विकासक्रमः स्पष्टः ।

ग—स मुञ्जं प्राविशत् तस्मात् स सुषिरः-शब्रा. ६,३,१,२६; आसन्दी मुञ्ज-विवायना-१२,८,३,१६ । मुञ्जः-शौ. १,२,४ ।

छ—मूँज (<मुञ्जः) ।

√मुट् (मुट) १/३२० प्रमर्दने (प) इति श-च-जै-काक्र-शा× दुर्गः—क्षी । क्षी-मै-सा-कात-हे-वो ।		<√मुण्ड् (मुडि) प्रमर्दने (प) । √मुट् (मुट) ६/ आक्षेप-प्रमर्दनयोः (प) । √मुट्ट् १/११८ प्रमर्दने (प) काक्र । √मुट्ट् १०/२६ b सञ्चूर्णने (प) काक्र ।

क—मेर्-, मेरा×घ्=वेष्टनम्, कवरी, अन्तर्गुम्फितम् । लिथु. मेल्ुम्-कण्टकमयम्, निशितम्-वा. पॉकर्नीः ।

ग—तरुलतामुन्मोटते-इन्दिशे स्प्रूशे ५६६; मोटन०-का. श्रौ. ७,३,२१; २६,३,३ ।

+√मुट् (मुट) ६/९४ श	आक्षेपप्रमर्दनयोः (प) क्षी-मै-सा-जै-काक्र-कात-शा-हे । प्रमर्दने—च । प्रमर्दने, आक्षेपे च—वो ।	पूर्ववत्

छ—√मोड़ना (<मोटनम्) =मर्दने । परिवर्तनार्थकाः 'मुड़ना, मोड़ना' प्रभृतयोऽस्माद् भिन्नाः ।

+√मुड् (मुड) १/३२० प्रमर्दने (प) क्षी-मै-श-च-जै-काक्र-कात-शा-हे-वो×	इति धनपालः-सा	<√मुट् (मुट) प्रमर्दने (प) सा । √मुड्ड् १/१६२ सेचने (प) काक्र । शेषः पूर्ववत् ।

छ—√मोड़ना (<मोडनम्)=मर्दने ।

√मुट् >√मुड् इति सुस्पष्टो विकासः ।

+√मुड् (मुड) ६/१०२ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	उत्सर्गे (प) इत्यात्रेयः—सा ।	<√पुड् (पुड) उत्सर्गे (प) । √बुड् ६/१०८ उत्सर्गे (प) शा । √वुड् ६/१३७ उत्सर्गे (प) हे ।
+√मुण् (मुण) ६/५४ श×	प्रतिज्ञाने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√मन् (मन) ४/ ज्ञाने (आ) । √मुण् १/२०७/शब्दे (प) काकृ । √पुण् (पुण) ६/ कर्मणि शुभे च (प) । √मुर् (मुर) ६/ संवेष्टने (प) ।

ग—मुणन्तु–तैआ. १,२७,६ ।
घ—मुनाति–धम्मपद ३,३९६ ।
ङ—√मुण (सक)=ज्ञाने । मुणइ, मुणंति–कुमा. ।
छ—√मुनना=स्वीकारे—बुं. ख. ।

+√मुण्ट् (मुटि) १/३२२	खण्डने (प) इति कौशिकदुर्गौ—क्षी । प्रमर्दने—च । मर्दे—वो ।	<√मुण्ड् (मुडि) खण्डने (प) । √मुट् (मुट) १/३२० प्रमर्दने (प) । √मिण्ट् १/१०३ प्रहरणे (प) काकृ ।
+√मुण्ठ् (मुठि) १/२६२ श	पलायने (आ) क्षी-च-जै-काकृ-कात-शा-हे । पालने—मै-सा । पलाये—वो ।	

अत्र पलायनार्थे बहुमतम् । मै-सा. पालनार्थे पेठतुः । स्यादत्र देशभेदसङ्केतः, उत वा 'पलायने' इत्यत्र भ्रान्त्या लैपिक्या त्रुट्या वा यकारलोपे लकारोत्तरवर्त्याकारस्य पूर्वभावत्वे सति 'पालने' इति भवत्येव । पुलिन्दखण्ड–(बुन्देलखण्ड)–भाषायां

'मौंठ'-शब्दः पोटलिकार्थे प्रयुज्यते। सा च पोटलिका महिष्ठा भवतीति रक्षणार्थत्वं तत्र युक्तमेव।

छ—मौंठ (<मुण्ठः) पोटलिका—बुं. ख.।

+√मुण्ड् (मुडि) १/२७२ मज्जने (आ) — द्रष्ट. √मुट् १/३२०।
श — क्षी-काकृ-कात। — द्रष्ट. √मुड् १/३२०।

(जै—√मण्ड् [मडिङ्]).... शुद्धौ—जै।
मार्जने—मै-सा-च-शा-हे
मग्ने—वो।
मज्जनम्=शुद्धिर्न्यग्भावश्च—क्षी।

ङ—√मुंड (सक)=मुण्डने, परिवापणे, ·(२) दीक्षायाम्, संन्यासदाने। मुंडइ—भवि.।

+√मुण्ड् (मुडि) १.३२० प्रमर्दने (प) — >√मुट् (मुट) प्रमर्दने (प) इति दुर्गः—क्षी।
मै-श-च-जै-काकृ-कात- क्षी-सा-हे। — √मुड् (मुड) १/.प्रमर्दने (प) इति धनपालः–सा।
शा× छिदि मर्दे—वो। — √मुण्ड् (मुडि) १/ खण्डने (प) शेषः पूर्ववत्।

ङ—पूर्ववदुदाहरणं ज्ञानीयम्।

+√मुण्ड् (मुडि) १/३२२ खण्डने (प) — √मुण्ड् (मुडि) १/ प्रमर्दने (प)। शेषः पूर्ववत्।
श× क्षी-मै-सा-च-जै-काकृ-कात-शा।
प्रमर्दने खण्डने च—हे।
छिदि मर्दे—वो।
'खण्डप्रमर्दनयोः' इति कण्ठः—क्षी।

क—मेल्=प्रमर्दने, संकुट्टने, सञ्चूर्णने। * मेल्—ड् :—वा. पॉकर्नीः।
ग—क्षत्रधर्मो न मुण्डनम्—मभार. १२,२३,४६=केशच्छेदनम्।
घ—मुण्डेति (प्रयोज.)=परिवापणे—महाबोधिवंस १०३।
ङ—√मुंड (सक)=मुण्डने, परिवापणे, (२) दीक्षायाम्, । मुंडइ-भवि.।

छ—√मूँड़ना=प्रवञ्चने, (२) मुण्डने, परिवापणे।

√मुद् (मुद) १/१६ श	हर्षे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√मद् (मदी) ४/ हर्षे(प)। √मुद् (मुद) १०/ संसर्गे (प)।

क—मॉइद्-,मुद्-रॉ=मुदितः (मृ)-जू. पॉकर्नीः।

ग—मोदते-ऋ. २,५,६; शत्रा. ९,४,१७। अमोदन्-वा. रा. २,४८,४-मोदः =आन्तरो हर्षः (तिल.)।

ङ—√मुअ (सक)=मोदे-से. ७,३७।

छ—√मोदना=मोदे, (२) गन्धे।

+मुर् (मुर) ६/६४	संवेष्टने (प) क्षी-मै-सा-च-जै-कात-शा-हे। संवरणे—काकृ। वेष्टने—वो।	√मुट् (मुट) ६/९४ आक्षेपप्रमर्दनयोः (प)। √मुड् (मुड) १/३२० प्रमर्दने (प) सा। √मुर्च्छ् (मुर्च्छा) १/२०९ मोहसमुच्छ्राययोः (प)।

ग—मुरा (मुरति=सौरभेण वेष्टयति)-ग. पु. १९०=स्वनामख्यातगन्धद्रव्यम्। मुरला (मुरम्=वेष्टनं लातीति) उत्त. रा. च. ३,१=नर्मदा नदी। मुरली—राधातन्त्रे। मुरः क्लेशे च सन्तापे कर्मभोगे च कर्मिणाम्। दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्तितः-ब्र. वै. श्रीकृष्णजन्मखण्डे ११० अध्या.। मुरलामारुतोद्धूतम्-रघु. ४,५५।

छ—√मुड़ना, √मुरना }=वेष्टने। परितो भ्रमणे।

छ—√मोरना>√मोड़ना=वेष्टने। परितो भ्रामणे।

√मुर्च्छ् (मुर्च्छा) १/२०९ श×	मोहसमुच्छ्राययोः (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। मोहे—च। मोह उच्छ्रये—वो।	

क—मेरे=घनत्वे, आतञ्चने-वा. पॉकर्नीः।

ग—मूर्च्छति–मै. २,६,६; काठ. १५,५। रोषमूर्च्छिता–वा. रा. २,१४,२०= क्रोधव्याप्ता (तिल.)। शिलोच्चये मूर्च्छति मारुतस्य–रघु. २,३४=प्रसरति (सञ्जी.)।

घ—मुच्छति–धम्मपद २,६७; दीघ. ३,४३।

ङ—√मुच्छ (अक)=मूर्च्छाभावे, (२) आसक्तौ, (३) वृद्धौ। मुच्छइ, मुच्छए–कस.; सूअ. १,१,४,२।

छ—√मुरछना
छ—√मुरुछना } (<मूर्च्छनम्)=संज्ञानाभावे।

+√मुर्व् (मुर्वी) १/५७२ श-जै×	बन्धने (प) क्षी-मै-सा-च-काकृ-कात-शा-हे। नहे—वो।	√मु १/५५८ a बन्धने (आ) काकृ। √मू (मूङ्) १/ बन्धने (आ)। √मव् (मव) १/ बन्धने (प)।

क—मेल्=संकुट्टने, संचूर्णने। लैंत. मल्व=वन्यगुल्मविशेषः–वा. पॉकर्नी।

ग—मूर्वा–सुश्रु. १,१३७,९ =तृणम्; बृ. सं. ५४,८७।

√मुष् (मुष) १/६८३ मै-श-च-जै-काकृ-कात-शा-हे×	हिंसार्थः (प) कषादिः क्षी-सा। वधे—वो। चौर्ये—ह्वि.।	√मष् (मष) १/ हिंसार्थः (प)। √मुश् ४/५७ खण्डने (प) काकृ। √मुष् (मुष) ४/ खण्डने (प) इत्येके–मै। √मुष्क् १/४१२ p गतौ (आ) काकृ।

ग—मोषथा वृक्षं कपन्नेव–ऋ. ५,५४,६।

+√मुष् (मुष) ४/११४ क्षी-जै-काकृ-कात-शा×,श	खण्डने (प) इत्येके–मै मै-सा-च-हे। छिदि—वो।	<√मुस् (मुस) खण्डने (प)। पूर्ववत्।

ग—मुषलः–मभार. १३,४,५२=विश्वामित्रसुतः।

√मुष् (मुष) ९/५८ श	स्तेये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। लुण्टने—वो।	

क—मेउस् = मोषणे–जू. पॉकर्नीः।

ग—अमुष्णीतम्—ऋ. १,९३,४. तैब्रा. २,८,७,१० । मुष्णामि–पै. २,४१,५ ।

+√मुस् (मुस) ४/१०७ खण्डने (प) क्षी-मै-सा-जै-कात-शा-हे । छिदि—वो । √मुष् (मुष) ४/ खण्डने (प) मै ।
श-च-काकृ×

ग—सन्नमुसले–मनु. ६,५६; मभार. १२,८८३१ । स्कन्धेनादाय मुसलम्–मनु. ८,१५=आयुधविशेषम् । मुसलः—मा. पु. ११६,१८ ।

√मुह् (मुह) ४/८५ वैचित्त्ये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।
श

ग—मुह्यन्तु–ऋ. १०,८१,६; तै. ४,६,२,६; मै. २,१०,२; शौ. ६,६७,१ । मुह्यति–शब्रा. १,५,२,१५ ।

घ—मुय्हति–मिलिन्दपञ्ह ३८६ ।

ङ—√मुज्झ (अक) १–मोहे, २–सम्भ्रमे । मुज्झइ–आचा.; उत्त.; महा. ।

च—(√मोह (सक) १–मोहे, २–सम्भ्रमे । मोहइ–भवि.)

छ—√मोहना (<मोहनम्) ।

√मू (मूङ्) १/९५२ बन्धने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । बन्धे—वो । √मव् (मव) १/ बन्धने (प) । √मव्य् (मव्य) १/ बन्धने (प) । √मु १/५५८ बन्धने (आ) काकृ ।
श

ग—मूते (सप्तमी)–मै. १,१०,२०; काठ. ३६,१४ [नाप. (वंशादिनिर्मिता करण्डिका)] । मूक०–मभार. ३,३९,७=दानवभेदः; मूकांश्च पङ्गून्–२,५,१२५ ।

यद्यप्ययं मूकशब्द उणादौ √मव् धातुतः साधितस्तथाप्यस्माभिः 'मू' इति दर्शनादिहैवोपन्यस्तः ।

+√मूल (मूल) १/५२९ प्रतिष्ठायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे. वो (उ) । √मूल् (मूल) १०/रोहणे (प) ।
श×

क—मॉ [उ] लॉ-ः मूलॉं = मूलम्, क्षुपः-वा. पॉकर्नीः।

ग—महाद्रुमा उन्मूलन्ति-षत्रा. (इन्दिशे स्तूदियन् १४१); बद्धमूलस्य मूलं हि-शिशु. २,३८।

+√मूष् (मूप) १/६६९ स्तेये (प)
श×(काकृ√मूष् [मुष] क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
लुण्टने—वो।

√मुष् (मुष) ९/स्तेये (प)।
√मुष् (मुष) १/हिंसार्थः (प)।
√मूषः-निघ. ४,१ (= मूषिका-देवराजय.)।

ग—मूषो न शिश्ना व्यदन्ति-ऋ. १,१०५,८। मूषकैः परिधावद्भिः-वा. रा. २,३३,१९। मूषासिक्तं यथा ताम्रम्-पञ्चद. ४,२-मूषा = तैजसावर्तिनी।

घ—मुसति-दीघ. २,१८३ = व्याकुलत्वे।

ङ—√मूखना
ङ—√मूसना } (< मूषणम्) = चोरणे।

√मृ १/४८ मरणे (प) इत्याभरणे पठ्यते-
क्षी-मै-श-च-जै-काकृ- तद् भाष्यविरोधादुपेक्ष्यम्-सा।
कात-शा-हे-वो×

क—द्रष्ट. उत्तरधातुः।

ग—सो चिन्नु न मराति न वयं मराम-ऋ. १,१९१,१०; जीवातुं न मरामहे-१,९१,६; जरसा मरते पतिः-१०,८६,११।

घ—मरति-महावंस ५,२७।

ङ—√मर (अक) = मरणे। मरइ-भग.।

√मृ (मृङ्) ६/१२२ प्राणत्यागे (आ)
श (काकृ-√म्री) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
मृतौ—वो।

क—मेर्, मेर् = प्राणत्यागे। लिथु,-मेर्देति, मरिन्ति, मिर्ति = मरणे। सेत्रं.-मॉ रिति। हित्ताइ.-मेइर्-त (मेर्त्) = मरणे।

ख—अवे.—म्रियेइते (= मृइर्येइते)-वा. पॉकर्नीः। अवे.-मिर्येइते-पी. टी. ऐस. पालि-इँग्लिशकोशे।

ग—म्रियसे-ऋ. १,१६२,२१। म्रियते-शब्रा. २,१,३,४; काब्रा. १,१,३,३; तांब्रा म्रियेत्-अमृतनादोप. ३९।

घ—मिय्यति-सुत्तनिपात ८०४; नेत्तिपकरण २३।

ङ—√मिज्ज (अक)=मरणे। मिज्जंति-सूअ. १,७,९।

√मृक्ष् (मृक्ष) १/६५३ संघाते (प)
क्षी-मै-श-च-जै-काकृ- सा।
कात-शा-हे-वो ×

√म्रक्ष् (म्रक्ष) १/६६५ संघाते (प) मै।
√मक्ष् (मक्ष) १/संघाते (प)।
√मक्ष् (मक्ष) १/रोषे (प)।
√मृज् (मृजूष्) २/शुद्धौ (प)।
√मुक्ष् १/२७९ संघाते (प) काकृ।

क—मेल्ज् प्रोञ्छने, मार्जने, दोहने-, स्-ः

ग—मृक्षाः-ऋ. ८,७४,१३। मृक्षः-ऋ. ८,६६,३ [विप. ([शूर] इन्द्र-) धा. वृषकर्मणि वृत्तिः (वैतु. वें. सा.) √मृज् इत्यनेन शोधनसवृत्तितेति, PW. प्रभृ. नाप. (अश्वदेहमार्जनोपकरण-) ?] मृक्षिणीषु-ऋ. १०,९८,६ [नाप (वाहिनी-[धारा-, नदी-]) धा. प्रवहणे वृत्तिः (तु. [अंशतः] PW. ORN. प्रभृ. वैतु.वें. सा ? GRV. = [विदीर्णा-] स्थली-इति, GW. झञ्झावात इति च)] नदीझञ्झावातादिषु संघातोऽपि सुस्पष्टः।

ङ—√मंख (सक)=म्रक्षणे। मंखइ-राज.।

+√मृग् (मृग) ४/१३९ अन्वेषणे ? (प) मै, (आ) सा।
क्षी-श-च-जै-काकृ (मै सा)।
कात-शा हे-वो ×

ग—मृग्यम्-ऋ. प्राति. ४,४१। मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति माम्-(अम्बिका-पुरातत्त्वसभापत्रिका ७,११, ४० श्लो.)-इति त्वकारान्तस्यैव भावे क्विपि, अकारलोपे मृगं करोतीति कण्ड्वादित्वात् क्ये साध्यम् इति दुर्गादासः।

+√मृज् (मृज) १/२४७ शब्दार्थः (प) सा
क्षी-मै-श-च-काकृ- सा।
कात-शा-वो × शब्दे - जै-हे।

<√मज् (मज) शब्दार्थः (प)।
द्र. √मुज् १/२४७।
√मुञ्ज् १/२४८।

क—द्र. √मृक्ष् १/६५३।

√मृज् (मृजूष्) २/५५ शुद्धौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। श
<√मृज् (मृज) १/शब्दार्थः (प)। √मार्ष्टि–निघ. २, १४=गतिकर्मा। √मार्ज् १०/९० शुद्धौ (प) काकृ।

क—मेल्ज् (अथवा–मेल्ज्?) = प्रोञ्छने, मार्जने। मॉल्जॉ = प्रपूरणे। लिथु. मिल्ज्ति = प्रपूरणे; (द्विरुक्तौ)–मल्ज्यति। रसन्; च. स्लावो. म्लेस्ति = प्रपूरणे–जू. पॉकर्नीः।

ख—मर्जैति, मुर्जैति = त्वगुत्पाटने, नग्नत्वे, स्पर्शे (प्रोञ्छने)–वा. पॉकर्नीः।

ग—मृजन्ति–ऋ. ३,४६,५; मै. २,१,९। मृष्टे–शब्रा. १,२,३,३। मार्ष्टि–शांआ. १२,२।

+√मृञ्ज् (मृजि) १/२४८ शब्दार्थः (प) इत्यप्याहुः-क्षी। मै-श-च काकृ-शा-वो× क्षी-सा-कात। शब्दे—जै-हे। <√मुञ्ज् (मुजि) शब्दार्थः (प)।

ग—मृञ्जत (व. व.)–ऋ. ९, २४, १; ९, ५६, २६। निमृञ्ज्यात्–शब्रा. १४, ९, ४, ५।

√मृड् (मृड) ६/४८ शX सुखने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। सुखसहने—शा। मोदे—वो। मृळतिर्दानकर्मा पूजाकर्मा वा–निरु. १०, १५, १। √मुद् (मुद) १/ हर्षे (आ)।

क—मेल्ज्=प्रोञ्छने, मार्जने, दोहने।—ड् = क्षमायाम्, सहने।

ख—मूर्ज्दा = सहने, क्षमायाम्–वा. पॉकर्नीः।

ग—ममृड्युः–ऋ. ४, १८, ८। मृळ–ऐब्रा. ५, १९। मृडसे–काठ. ३७, १३।

+√मृड् (मृड) ९/४४ काकृ×,श सुखने (प) क्षी-च-जै-कात-शा-हे। √मृ (मृङ्) ६/प्राणत्यागे (आ)। √मृद् (मृद) ९/ क्षोदे (प)।

क्षोदे—मै-सा।
'सुखे च' इति केचित्—सा।
'सुखने' इत्यपरे—सा।
सुखसहने—शा।
मोदे—वो।

√मृण् (मृ॰ण) ६/५१ श

हिंसायाम् (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
हिंसे—वो।

√मृ (मृङ्) ६/ प्राणत्यागे (आ)।
√मॄ ९/ हिंसायाम् (प)।
√मृण्ड् (मृडि) १०/ छेदने (प) सा।

क—मेल्-, मेलु-: म्ले-,मेल्-द्-: म्ले-द्-,मेल्-ध्-,म्ल्-आइ-: म्लि, म्ली-, मेलु-क्-: म्ला-क्-, म्लेउ-: म्लु, म्लू=आघाते, सञ्चूर्णने; लिथु.-मल्विन्ति (=म्रियति संस्कृ.)=नाशे। लिथु. मलित। सेर्बो-क्रोटि. म्लजेति=सञ्चूर्णने। पु. च. स्लाव्रो. म्लेत। रसन्. मॉलॉत-जू. पॉकर्नीः।

√मृद् (मृद) ९/४३ श×

क्षोदे (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
क्षुदि—वो।

√मृद् १/५१६ b मर्दने (आ) च।
√म्रद् (म्रद) १/ मर्दने (आ)।
मर्दति-निघ. २/१४=गति-कर्मा।
मर्दति-निघ. २/१९=वध-कर्मा।
मृध्नन्ति-का. श्रौ. २२,३,४५ <मृद्नन्ति।

क—मेल्-द्-, (म्‌ ऍ) ले-द्=मृदु। पु. उ. ज.-मिल्जि। ऍंग्लो-सैक्सॉ. मिल्ते। पु. आइस्. मिल्ति=प्लीहा, रोषः।

ख—अवे.-मर्दैते-जू. पॉकर्नीः।

ग—परिमृद्नन्तौ-वा. रा. २, ७७, २६=मार्जयन्तौ (तिल.); मृद्नन्ती कुशकण्टकान्-२, २७, ७।

घ—मद्दति-जातक ३, २४५, ३७२; सुत्तनिपात ७७०।
ङ—√मद्द (सक)=चूर्णने, (२) अभ्यङ्गे, मर्दने। मद्दाहि-कप्प.।
च—√मल (सक)=मर्दने। मलइ, मलेइ-भवि.।

छ—√ मर्दना* / मरदना* / मल्ना } (<मर्दनम्)=मर्दने ।

√मृध् (मृधु) १/८५९ उन्दे (उ)
शX
क्षी-मै-च-कात-शा-हे ।
उन्दने—मै·सा ।
रुन्धे—काकृ ।
स्याल्लैपिकी त्रुटिः ।
क्लिदि—वो ।
उपेक्षायाम्—ह्वि. ।

क—मेल्-ध् (*मेल्-ध्-औ)-जू. पॉकर्नीः ।

ग—मर्धति-ऋ. ७, ५९, ४; मृधाति-६, २९, ३ (तौदादिकोऽपि ?); मर्धतः-कौ. २, २०३ ।

√मृश् (मृश) ६/१४४ आमर्शने (प) √मृष् (मृषु) १/ सहने, च=सेचने (प) ।
श
क्षी-मै-सा-काकृ-कात-शा-हे ।
आमर्शे—च-जै ।
मृशि—वो ।

आमर्शनम्=स्पर्शः-क्षी ।

क—मेर्श्=ग्रहणे, स्पर्शे, बोधने । मेर्कु-(शु) । मेक्र्स्=वस्तु । मर्सेस्,-ऐदिस्=मूल्यम्, पुरस्कारः-वा. पॉकर्नीः ।

ग—तमद्भिरभिमृशति-शत्रा. १, २, २, ११ । विश्वं मृशन्तीम्-शौ. ८, ९, ९ । मृशते- पै. १, १०९, ४ (पाठभेदः) । सर्वो विमृशते जन्तुः-मभार. ९, १८७५ ।

+√मृष् (मृषु) १/६९८ सेचने (प) √मृज् (मृजूष्) शुद्धौ (प) ।
शX
क्षी । मृष्टम्-बृहत्संहि. ८५,९ ।

उत्तरधातोरभिन्नोऽयं क्षीरेण पृथक् संख्यातः ।

+√मृष् (मृषु) १/६९९ सहने, च=सेचने (प) √मृश् (मृश) ६/ आमर्शने (प) ।
शX
क्षी-मै-सा-जै-कात-शा-हे ।
सेचने—च ।
√मृष् (मृष) ४/ तितिक्षायाम् (प) ।

	सेचने हसने च—काक्ट । सेचने क्षान्तौ च—वो (उ)।	
√मृष् (मृष) ४/५३ श	तितिक्षायाम् (उ) क्षी-मै-सा-जै-काक्ट-कात-शा-हे । क्षान्तौ—च-वो । क्षमायाम्—काक्ट-कात ।	√मृष् (मृषु) १/ सहने च-सेचने (प) । √मृश् (मृश) ६/आमर्शने(प)।

क—मेर्ष्-, मेर्ष्-स्=विघ्ने, कांपे-जू. पॉकर्नीः ।

ग—न तं पूषापि मृष्यते–ऋ. ६, ५४, ४। मृष्यन्ति ये चोपपतिम्–मनु. ४,२१७।

ङ—√मरिस (सक)=तितिक्षायाम् । मरिसइ–महा.; स. ६७० ।

च—√मरुस (सक)=तितिक्षायाम् । मरुसिज्ज–भवि. ।

ङ—√मरह (सक)=तितिक्षायाम्–णाया. १, ८–पत्र. १३५ ।

√मॄ ९/१८ मै-च-काक्ट-कात×, श ?	हिंसायाम् (प) क्षी-सा-जै-शा-हे । वधे—वो ।	√मृ १/ मरणे (प) । √मृ (मृङ्) ६/१२२ प्राणत्यागे (आ)।
मॄ ९/२९ क्षी-श-जै-काक्ट-कात-शा-हे-वो×	हिंसायामित्येके-मै । मै-सा-च ।	√मृण् (मृण) ६/५१ हिंसायाम् (प) । √कॄ ९/२९ हिंसायाम् (प) मै ।
मॄ ९/… ह्वि. ।		

ग—मृणीहि–ह्वि. । मया नोपलब्धम् ।

घ–मणाति–धम्मसंगणि २१८; खुद्दकपाठ २४ ।

√मे (मेङ्) १/९४६ श×	प्रणिदाने (आ) क्षी-मै-सा । प्रतिदाने—च-जै-काक्ट-कात-शा-हे । प्रतीदाने—वो ।	√मा (माङ्) ३/ माने शब्दे च (आ) ।

प्रतीदानम् = परीवर्तः–दुर्गादासः ।

क—माइ=विनिमये । लेट्टिश्–मिजु, मीजु, मीत=विनिमये–वा. पॉकर्नीः ।

ग—अपमयेत–मै. ४,२,७। निमयेत् पक्वमांसेन–मभार. १२, २९२३। प्रणिमयते–मभाष्ये १, १, २०, $\frac{१७}{उ४}$।

+√मेट् (मेटृ) १/२८९ सा-श-जै-काक्र-कात-शा-हे×	उन्मादे (प) इति दौर्गाः—क्षी क्षी-वो। उन्मादने—मै-च।	<√म्रेट् (म्रेटृ) उन्मादे (प)। √मेड् (मेडृ) १/५६१ उन्मादे (प) जै। √म्रेड् (म्रेडृ) १/ उन्मादे (प)। √म्लेट् (म्लेटृ) १/ उन्मादे (प)।

विकासः स्पष्टः-√मेट् >√मेड् >√म्रेट् >√म्रेड् >√म्लेट्।

ग—मेळिं मदन्तम्-ऋ. ३, २६, ९। मेडवः-कथासरि. ४०, ५।

+√मेथ् (मेथृ) १/८५४ मै-श-च-जै-कात-शा×	मेधाहिंसनयोः (उ) क्षी-सा। गतिहिंसयोः—काक्र। मेधाहिंसयोः सङ्गमे च—हे। वधे मेधायां सङ्गे च—वो।	द्रष्ट. √मिथ् १/८५३

ग—मेथिष्ठाः पिन्वानाः–तै. २,७,१६,३। इह मेथिमभिसंविशध्वम्–अ. वे. ८,५,२०। विष्णवे त्वेति मेथीम्–शन्ना. ३,५,३२१–मेथी=स्तम्भः (मिथन्ते=सङ्गच्छन्ते पशवोऽत्रेति)। √मिथ् १/८५३ धातुनास्य न शक्यते कर्तुं सिद्धिः, तस्य सङ्गार्थत्वाभावात्।

घ—मेधि (<मेथी)-दिव्यावदान २४४।
छ—मेढी, मेढ़ी=स्तम्भः–बुं. ख.।

+√मेद् (मेदृ) १/८५४ श-जै-शा×	मेधाहिंसनयोः (उ) इति दुर्गः—क्षी। क्षी-सा। मेधाहिंसयोः—मै-च-कात-हे। गतिहिंसयोः—काक्र। वधमेधयोः—वो।	<√मेथ् (मेथृ) मेधाहिंसयोः (उ)। शेषः पूर्ववत्। √मिद् (ञिमिदा) १/ स्नेहने (आ)।

+√मेध् (मेधृ) १/८५५	सङ्गमे, च=मेधाहिंसनयोः (उ) क्षी-सा। सङ्गमे, च=मेधाहिंसयोः—	√मिध् (मिधृ) १/८५३ मेधाहिंसनयोः (आ) सा।

मै-जै-कात-शा-हे।	शेषः पूर्ववत्।
सङ्गमे—च।	मेधा—निघ. २/१०=
गतिहिंसयोः सङ्गमे च—	धननाम।
काक्र।	(सङ्गच्छतेऽनेन सर्वम्)
मेथृवत् (= वधे मेधायां	
सङ्गे च)—वो।	

ग—सनिं मेधामयासिषम्—ऋ. १,१८,६; मेधं शृतपाकं पचन्तु—१,१६२,१०। मेध्या—मभार. ३,२२१,२३=नदी; त्रीन् मेधानाहरिष्यति—मभार. १,१२३,३९—मेधान्=यज्ञान्। न मेधया न बहुना श्रुतेन—मुण्डकोप. ३,२,३। मेधिर०—ऋ. १,२५,२०—मेधिरः=मेधावी। मेधयुम्—ऋ. ४,३८,३।

+√मेप् (मेपृ) १/३६७ गतौ (आ)
मै-श-काक्र-कात× क्षी-सा-च-जै-शा-हे।
(च—√मेव् [मेवृ]) गत्याम्—वो।

+√मेव् (मेवृ) १/५०६ सेवने (आ)
श× क्षी-च-जै-शा-हे-वो।
सेचने—मै-सा-काक्र-कात।

ग—मेवाडे च तथा प्रोक्तः—स्क. पु. १,३९,४० (मन. रा. मो. संस्करणम्)।

छ—मेवा=सेवनीयं फलम्।

छ—मेव=मरुस्थानाभिजना जातिः।

छ—मेवड़ी='सँभाल' इति भाषाप्रसिद्धम्।

छ—मेवाड़=मरुस्थानप्रान्तः—(<मेवाडः—स्क. पु. १,३९,४०)।

√म्ना १/९१३ अभ्यासे (प) √मन् (मन) ४/ ज्ञाने
श क्षी-मै-सा-च-जै-काक्र- (आ)।
कात-शा-हे-वो। समाम्नायः समाम्नातः—
निरु. १,१।

क—मेन्=चिन्तने, विचारणे—वा. पॉकर्नीः।

ग—मम्नाते इन्द्र रोदसी—ऋ. ७,३१,७। एके समामनन्ति—आश्व. गृ. ८,१३,३२।

+√म्रक्ष् (म्रक्ष) १/६६५ सङ्घाते (प) मै क्षी-सा-श-जै-शा- मै-च-कात-वो। (हे ?)×

√मक्ष् (मक्ष) १/ संघाते (प) मै। म्यक्षति-निघ. २/१४= गतिकर्मा। मिम्यक्ष-ऋ. ६,५०,५; शौ. २०,९४,२।

ग—पांशुना च म्रक्षन्ति-ललित. ३२५,१४ (कालिकातासंस्करणम्)= म्रक्षणे।

ङ—√मंख=म्रक्षणे। मंखइ-राज.।

छ—मक्खन, माखन (<म्रक्षणम्)=नवनीतम्।

√म्रद् (म्रद) १/७६० मर्दने (आ) श×(जै√मद् [मर्दैप् मर्दे]) प्रतीयते प्रमादः। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। क्षोदे—वो।

√मृद् (मृद) ९/ क्षोदे (प)। √म्रित्—गर्भः अपास्यन् म्रित्येत्-शब्रा. ३,२,१,३१

ग—पणेश्चिद् वि म्रदा मनः-ऋ. ६,५३,३। नेत्पशून् प्रमदे करवामहे-शब्रा. ४,४,३,११। यज्ञमेव तन्म्रदयति (मृदु-नामधा.)-तै. ६,१,४,४।

√म्रुच् (म्रुचु) १/१९२ गत्यर्थः (प) श-काकृ× क्षी-मै-सा-च। गतौ—जै-कात-शा-हे। गत्याम्—वो।

√म्लुच् (म्लुचु) १/ गत्यर्थः (प)।

ग—आदित्यः निम्रोचन्-अ. वे. २,३२,१। आदित्यः पुर उदेति पश्चान्नि-म्रोचति-काठ. २३,८। सूर्योऽभिनिम्रोचति-तै. ६,४,२,१।

+√म्रुञ्च् (म्रुन्चु) १/१९० गत्यर्थः (प) श-कात× क्षी-मै-सा-च। गतौ—जै-काकृ-शा-हे। गत्याम्—वो।

√म्रुच् (म्रुचु) १/ गत्यर्थः (प)। √म्लुच् (म्लुचु) १/ गत्यर्थः (प)। √म्लुञ्च् (म्लुन्चु) १/ गत्यर्थः (प)।

+√म्रेट् (म्रेटृ) १/२८९ उन्मादे (प) श-च-जै-काकृ- क्षी-वो।

√मेट् (मेटृ) १/ उन्मादे (प)।

कात-शा-हे ×
उन्मादने—मै ।
सा (मैसू. संस्करणे) ।
√मेड् (मेड़ृ) १/२६१
उन्मादे (प) जै ।
√म्रेड् (म्रेड़ृ) १/२८९
उन्मादे (प) ।
√म्लेट् (म्लेटृ) १/२९०
उन्मादे (प) ।

√म्रेड् (म्रेड़ृ) १/२८९ उन्मादे (प) इति पठन्ति—क्षी
मै-श-च-कात ×
क्षी-सा-जै-शा-हे-वो ।
उन्मादने—काकृ ।
प्रसादीकरणे, कृतार्थीकरणे (?)—ह्वि. ।
<√म्रेट् (म्रेटृ) उन्मादे (प)।
√म्रेड् (म्रेड़ृ) १/८२ a
अनादरे (प) कात ।
शेषः पूर्ववत् ।

ग—गच्छेयुरुप च निम्रेडेरन्-छान्दोग्यो. ३,१९,४ । वाक्यमाम्रेडयति देवराट्-मभार. ३,१०३८३ ।

√म्लुच् (म्लुचु) १/१९३ गत्यर्थः (प)
श-काकृ ×
क्षी-मै-सा-च ।
गतौ—जै-कात-शा-हे ।
गत्याम्—वो ।
द्रष्ट. √म्रुञ्च् १/१९० ।

ग—अ(उ)पम्लुक्तम्-ऋ. १०,५२,४ । म्लोचन्ति-शब्रा. १४,४,३,३३; बृहदारण्यको. १,५,२२ ।

√म्लुञ्च् (म्लुन्चु) १/१९१ गत्यर्थः (प)
श-कात-शा-हे ×
क्षी-मै-सा-च ।
गतौ—जै-काकृ ।
गत्याम्—वो ।
पूर्ववत् ।
√म्लुच् > √म्लुञ्च् इति क्रमः ।

√म्लेच्छ् (म्लेछ) १/२०२ अव्यक्तायां वाचि (प)
श ×
क्षी-मै-सा-जै-काकृ-शा-हे ।
अव्यक्ते वचने—च ।
व्यक्तायां वाचि (!)—
(म्लिष्टम्=अविस्पष्टोक्तौ) ।

काक्र-कात ।
देश्योक्तौ—वो ।

ग—न ब्राह्मणो म्लेच्छेत्-शब्रा. ३,२,१,२४ । नार्या म्लेच्छन्ति भाषाभिः-मभार. २,२०,४० । ब्राह्मणेन न म्लेच्छितवै-मभाष्ये १,१,१ ।

+√म्लेट् (म्लेट्ट १/२९० उन्मादे (प)
शा-जै-काक्र-कात- क्षी-हे-वो ।
शा-हे×, (सा) उन्मादने—मै-च ।
धातुवृत्तौ नास्ति ।
वा. ग. प. पठति ।

√म्लेड् १/८२ b अनादरे (प) कात ।
शेषः√म्रेड् १/२८९ वत् ।

+√म्लेव् (म्लेवृ) १/५०७ सेवने (आ)
श× क्षी-च-जै-शा-हे-वो ।
सेचने—मै-सा-काक्र-कात ।

√मेव् (मेवृ) १/ सेवने (आ) ।
√प्लेव् (प्लेवृ) १/ सेवने (आ) ।

√म्लै १/८८९ गात्रविनामे (प)
क्षी-मै-च-जै-काक्र-कात-शा-हे ।
हर्षक्षये—सा ।
'गात्रविनामे' इति क्वचित् पठ्यते—सा ।
कान्तिसंक्षये—वो ।
विनामः=कान्तिक्षयः-क्षी ।

क—मेल् =सञ्चूर्णने, प्रमर्दने ।
ख—अवे. म्रात=म्लातम्-वा. पॉकर्नीः ।
ग—म्लातानि-ऋ. ८,५५,३ । म्लायति-शब्रा. ८,१,४,१ ।
घ—मिलायति-संयुत्त. १,१२६; इतिवुत्तक ७६ =मृदूभावे ।
ङ—√कुम्हलाना (<कु+म्लानम्) ।

√यज् (यज) १/९८६ देवपूजासङ्गतिकरणदानेषु (उ) ।
श क्षी-मै-सा-काक्र-कात-शा-हे ।
देवपूजायाम्—च ।
दानदेवपूजासंगत-

√यक्ष् (यक्ष) १०/१६१ पूजायाम् (आ) ।
यक्षते-तांब्रा. ९,१०,१ ।
इयक्षति-निघ. २/१४=गतिकर्मा ।

	करणेषु—जै।	इयक्षति-ऋ. ८,३१,
	देवार्चादानसंगकृतौ—वो।	[१५-१८]।
		यक्षामः-वा. रा. ७,४,१२।

क—इअजु =धार्मिकी पूजा।

ख—अवे. यजैते=यजते-वा. पॉकर्नीः।

ग—अव⋯यजति-ऋ. १,३१,१५; तै. १,५,९,२। यजते-ऐब्रा. १,१; तैब्रा. १,३,२,३।

घ—यजति-दीघ. १,१३९; अंगुत्तर. १,१६८।

ङ—√जय (अक) [यकारस्य जकारो जकारस्य च यकारो वर्णविपर्ययो वा]= (१) पूजायाम्, (२) यागे। जयइ-उत्त. २५,४।

√यत् (यती) १/२९	प्रयत्ने (आ)	यतते-निघ. २/१४=गतिकर्मा।
श	क्षी-मै-सा-च-जै-	
	काकृ-कात-शा-हे।	
	यत्ने—वो।	

क—इअत्=यत्ने।

ख—अवे. यतेइति, यतयेइति-वा. पॉकर्नीः।

ग—यतते-ऋ. १,९५,७; [सपा. पै. १५,१२,५; 'यजते' इति पाभे.] तै. १,५,११,३; शब्रा. १२,२,३,१। यतति-ऋ. ७,३६, [(३,५९,१) २]; येतिरे-१,८५,८।

√यभ् (यभ) १/९६५	विपरीतमैथुने (आ)	>√जभ् (जभ) १/ विप-
श-कात×	क्षी-सा।	रीते मैथुने (आ) मै।
	विपरीते मैथुने—मै।	√जम्भ् (जभि) १/ च=
	मैथुने—सा-च-जै-	विपरीतमैथुने (आ)।
	काकृ-कात-शा-हे-वो।	

क—इअभ्—इभ्=स्पर्शे, रतौ। पु. च. स्लावो. जेब्, जेति तथा जेबति= मैथुने-वा. पॉकर्नीः।

ग—न मा यभति कश्चन-तै. ७,४,१९,२। यभ माम्-अ.वे. २०,१३६,११। यियप्सत इव मे मनः-शाङ्खा. श्रौ. १६,४,६। सुतां यभितुमुद्यतम्-भा. पु. १०,८५,४७। यभस्व नित्यम्—सुभाषि.।

√यम् (यम) १/९६९ उपरमे (प) √यज् (यज) १/ देवपूजा-
श-च-जै-काकृ-कात-वो× क्षी-मै-सा-शा-हे। सङ्गतिकरणदानेषु (उ)।
√यम् (यमु) १/९९२ मै-सा-च-काकृ-कात-हे। √यत् (यती) १/ प्रयत्ने
क्षी-जै-शा× विरतौ—वो। (आ)।
√यम् (यमः) ८०३dd अपरिवेषणे (प) मित्
श-जै-शा-हे× परिवेष्टने—काकृ।

क—इएेम् = धारणे, ग्रहणे—वा. पॉकर्नीः।

ग—यच्छति—ऋ. ५,८०,२; तै. १,६,८,४; शौ. १९,३२,२। ? यमति—ऋ. १,१००,९। (अपरिवेषणे तथा परिवेषणे)–यमयति—शत्रा. १४,१,३,४।

घ—यमति–जातक ३,४८८।

ङ—√जच्छ (सक) = (१) उपरमे, विरामे, (२) दाने। जच्छइ–कुमा.।

छ—√जमना (<यमनम्) = आतञ्चने, पूर्वस्याः स्थितेर्विरामे, स्थिरीभावे।

+√यय् (यय) १/४७९ गतौ (आ) मै। √येल् १/२४७q गतौ (प)
क्षी-सा-श-च-जै-काकृ- मै। काकृ।
कात-शा-हे-वो×
ग—ययेयुः—मै. ३,६,९।

√यस् (यसु) ४/९७ प्रयत्ने (प) √येष् (येषृ) १/ प्रयत्ने
श क्षी-मै-सा-च-जै-काकृ- (आ)।
कात-शा-हे। यहुः—ऋ.८,६०,१३; यहो-
यतने—वो। ऋ. १,२६,१०।

क—इएेस् = प्रकम्पने, फेनः, उत्फगनम्, उत्क्वथनम्।

ख—अवे. यएद्, येइति = उत्क्वथने, उत्फणने—वा. पॉकर्नीः।

ग—तपुर्ययस्तु—ऋ. ७,१०४,२। रामाभिषेकार्थमिहायस्यसि—वा. रा. २,१४,६२। आत्मार्थमायस्य—मा. पु. ३४,१२।

√या २/३८ प्रापणे (प) याति—निघ.२१/४=गतिकर्मा।
श क्षी-मै-सा-च-जै- √इ (इण्) २/ गतौ।

	काक्ठ-कात-शा-हे । गतौ—वो ।	यामि–निघ. ३/१९=याच्ञा-कर्मा ।

क—ऐइ्=गतौ । *इ्आ (संस्कृते) । लैति.–जानुस् ।
ख—याइति=गतौ–वा. पॉकर्नीः ।
ग—याति–ऋ. १,५०,९; तै. ४,६,३,३; शौ. १०,८,१८ ।
घ—यासि–जातक १,२९१ । यामि–पेतवत्थु २,८ ।
ङ—√या (सक)=(१) गतौ, (२) प्रापणे, (३) ज्ञाने । यंति–विसे. ४३१; कुमा. ८,८ ।

ङ—√जा (सक)=(१) गतौ, (२) प्रापणे, (३) ज्ञाने । जाइ–सुपा. ३०१ ।

छ—जाना । महाराष्ट्रि.–जाणें ।

√याच् (डुयाचृ) १/८४८ श-च-जै-काक्ठ-कात×	याच्ञायाम् (उ) क्षी-मै-सा-शा । याचने—हे-वो ।	यामि—निघ. ३/१९= याच्ञाकर्मा । ऋ. ८, ३३,११ ।
√याच् (टुयाचृ) इति दुर्गः–क्षी	क्षी-मै-सा-च-काक्ठ-कात-शा-हे । याचने—जै-वो ।	यानॅम् =दानम् –अवेस्ता यस्न ९,१९ ।
		अयासिषम्–ऋ. १,१८, ६=याचने । √यास् ।

क—इ्ऐक् =भाषणे, वचने-वा. पॉकर्नीः ।
ख—यासङ्हु=याचस्व–अवेस्ता, यस्न ९,२ ।
ग—याचति–तै. १,५,९,६; मै. १,५,१२; शौ.९,६,४। याचते–शब्रा.२,३,४,३३ ।
घ—याचति–जातक ३,४९ ।
ङ—√जाय (सक) = प्रार्थने, याचने । वक्ठ–जायंत–पण्ह.. १,३ ।
छ—√याचना
छ—√यॉंचना * } (<याचनम्)=याच्ञायाम् ।
छ—√जॉंचना=सत्यासत्याद्यनुसन्धाने, (२) याचने ।

√यु २/२२ श	मिश्रणे (प) क्षी-मै-सा-च-जै-काक्ठ-कात-शा-हे । 'अमिश्रणे' इत्येके–क्षी ।	यौति–निघ. ३१/४= अर्चतिकर्मा । √यु १०/ जुगुप्सायाम् (आ) ।

क्षी-सा ।
मिश्रणेऽमिश्रणे—वो ।

क—इुऐउ=मिश्रणे, लेट्टिश्-जौत् =मिश्रणे-वा. पॉकर्नीः ।

क—इुऐउ=बन्धे,योगे ।

ख—अवे.-यव् =व्यस्ततायाम् । (वर्तमानकाले-यवयेइति)-वा. पॉकर्नीः ।

ग—युवस्व-ऋ. ६,६,७; युयोतु-५,५०,३ । यौमि-शौ. २,२,१; पै. १,७,१ ।

[+]√यु (युञ्) ९/७ जैX,श — बन्धने (उ) क्षी-मै-सा-च-काक्ृ-कात-शा-हे-वो । — √यु २/२२ मिश्रणे (प) ।

+√युङ्ग् (युगि) १/१५५ शX(जै-√पुङ्ग् [पुगि]) मुद्रणदोषः । — वर्जने (प) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे-वो । — √जुङ्ग् (जुगि) १ वर्जने (प) ।

छ—जुंग=वृद्धदारको वृक्षः ।

√युच्छ् (युछ) १/२११ शX,(काक्ृ-√युञ्छ् [युछि]) — प्रमादे (प) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे-वो । पार्थक्ये—ह्वि. । — √यु २/२२ मिश्रणे (प) 'अमिश्रणे' इत्येके—क्षी ।

ग—युच्छति-ऋ. ५,५४,१३ । युच्छन्ति-पै. ५,२२,६ ।

+√युज् (युज) ४/६४ श — समाधौ (आ) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे-वो । कर्मणि—ह्वि. ।

ग—युज्यते-ऋ. ५,१,३; तै. ३,१,१०,२; शौ. १०,२,३ । युज्यस्व-गी. २,३८ ।

√युज् (युजिर्) ७/७ श — योगे (उ) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे । युतौ—वो । — √यु २/२२ मिश्रणे (प) । √यु (युञ्) ९/७ बन्धने (उ) ।

क—इ्रएउ=बन्धे, योगे।

ख—यओज्-, युज्=बन्धे, योजने-वा. पॉकर्नीः।

ग—युङ्क्ते-ऋ. १,८४,१६; तै. २,११,३। योजते-ऋ. ७,१६,२। युनक्ति-शांब्रा. ३,३। युनजते-ऋ. ७,२७,१; तै. १,६,१२,१ [श्नम्शपौ विकरणौ द्रष्टव्यौ]।

घ—युञ्जति-धम्मपद ३८२।

+√युत् (युतृ) १/३० श×(हि-मुद्रणदोष-दूषितो लीविश-सं.)	भासने (आ) क्षी-मै-सा-शा-हे। दीप्तौ—जै-वो। भाषणे—च-काकृ-कात।	√जुत् (जुतृ) १/ भासने (आ)। √ज्युत् (ज्युतृ) १/ भासने (आ)। √द्युत् (द्युत) १/ दीप्तौ (आ)।
√युध् (युध) ४/६१ श	प्रहरणे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। युद्धे—वो।	युध्यति-निघ. २/१४=गतिकर्मा।

क—इ्रएउध्=प्रहरणे, युद्धे।

ख—अवे. यूइ्र्येइन्ति=प्रहरणे, युद्धे-वा. पॉकर्नीः।

ख—अवे. यओस्ति-पी. टी. एस. पालि-इँग्लिशकोशे।

ग—योत्सि-ऋ. १,१३२,४। युध्यति-मै. ४,४,१; शब्रा. ३,४,४,२२; युध्यन्ते-तैआ. ६,३,२। युध्यस्व-गी. २,१८।

घ—युज्झति-धम्पपद २,१५४।

ङ—√जुज्झ (अक)=युद्धे। वक्क-जुज्झंत-सुर. २, ५१; ९,२२२।

ङ—√जूझ (अक)=युद्धे-सिरि. १०२५।

ङ—√झूझ (अक)=युद्धे। झूझंति-संबोध. १८।

च—√जोह (अक)=युद्धे। जोहइ—भवि.।

छ—√जूझना*=युद्धे।

√युप् (युप) १/१२२ श	विमोहने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। विमोहे—वो।	

ग—युयोप नाभिरुपरस्यायोः-ऋ. १,१०४,४; मृत्योः पदं योपयन्तः-१०,१८,२।

युपितम्-शौ. ४,२५,२। युप्यतीति दिवादेः परिचायको प्रयोगो नोपलभ्यते।

+√यूष् (यूष) १/६७१ शा-शा×	हिंसायाम् (प) क्षी-मै-सा-च-काक्र-कात-हे। हिंसायां संघाते च—जै। वधे—वो।	√जूष् (जूष) १/ च=हिंसायाम् (प)। √युष् भजने-सौ. धा.-वो.। √युष् १/२९३ i हिंसायाम् (प) काक्र।

ग—पात्राणि यूष्ण आसेचनानि-ऋ. १,१६२,१३। यूषः-शाङ्खा. श्रौ. ४,१८,१३; गोगृ. ४,१,७।

√येष् (येषृ) १/६१० श×(सा-जै√एष् [एषृ])	प्रयत्ने (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। यत्ने—वो। औष्ण्ये—ह्वि.।

क—इष्एस्=क्वथने, उत्फणने।

ख-अवे. यएस्येइति=उत्फणने, उत्क्वथने-वा. पॉकर्नीः।

ग—उखा येषन्ती-ऋ. ३,५३,२२ [धा. उत्क्वथने वृत्तिः (वैतु. वें. सा. स्रवणे इति, सा [शौ]=√जेष् [प्रयत्ने] इति च)]; शौ. ४,७,४। निर्येषति तै. २,५,१,४।

+√यौट् (यौटृ) १/२८८ शा-काक्र-शा-हे×	सम्बन्धे (प) क्षी-मै-च-कात-वो। बन्धे—सा-जै।	√यौड् (यौडृ) १/३७१ सम्बन्धे (प) शा; २३४-हे। √यौण्ड् १/८१ सम्बन्धे(प) काक्र। युक्त० >युट्ट्>√यौट् इति स्यात्।

√रंह् (रहि) १/७२४ श×	गतौ (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। गत्याम्—वो।	रंहति-निघ.२/१४=गतिकर्मा। √रह् (रह) १/७२३ त्यागे (प)।

क—लेंग्ह्-,नासिक्यम्-लेंग्ह्-वा. पॉकर्नीः।

ग—स रंहते उरुगाय-ऋ. ९,९७,९। रंहति-ब्रह्मसू. ३,१,१। हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमध्यमेषु गमिमेव त्वार्याः प्रयुञ्जते—महाभाष्ये पस्पशाह्निकम्।

√रक्ष् (रक्ष) १/६४९ पालने (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो।

क—अलेक्=अपसारणे, रक्षणे-जू. पॉकर्नीः।

ग—यं सुगोपा रक्षसि-ऋ. २,२३,५। रक्षते-शांआ. ७,२०। रक्षति-तै. ४,३, ११,१। रक्षमाणाः-ऋ. १०,६८,१ [वेगवद् उत्पतने वृत्तिः]। रक्षीः-शौ. ५,७,१ [धा. हिंसायां वृत्तिः]।

घ—रक्खति-सुत्तनिपात २२०; जातक ४,२५५।

ङ—√रक्ख (सक)=रक्षणे, पालने। रक्खइ-उव.; महा.।

छ—√राखना*†
छ—√रखना
छ—√रक्खना
छ—√रक्षना *
} (<रक्षणम्)=रक्षणे।

+√रख् (रख) १/१३६ गत्यर्थः (प)
श× क्षी-मै-सा-च-कात।
गतौ—जै-काकृ-शा-हे।
सर्पणे—वो।

√रच्छ् १/३५५g गतौ (प) काकृ।
√रङ्ख् (रखि) १/ गत्यर्थः (प)।
√लख् (लख) १/ गत्यर्थः (प)।
√लङ्ख् (लखि) १/ गत्यर्थः (प)।
√रघ् १/४१२jj गतौ (आ) काकृ।

+√रग् (रगे) २/७७९ शङ्कायाम् (प)
श× क्षी-मै-शा-च-काकृ-
कात-शा-हे।
शङ्कने—जै।
शङ्के—वो।

√लग् (लगे) १/ सङ्गे (प)।
√रख् (रख) १/१३६ गत्यर्थः (प)।

ग—[रगडः = तालः-क्षी]।

+√रङ्ख् (रखि) १/१३७ मै-श× — गत्यर्थः (प) क्षी-सा-च-कात। गतौ—जै-काक्र-शा-हे। सर्पणे—वो। — √प्रेङ्खोल् (प्रेङ्खोल) १०/ चापले-वो।

ग—काकरङ्खः-मभार. ५,१३३,१४ = काकवत् रङ्खति = पलायते (नील.)।

ङ—√रंखोल (अक) = चलने, कम्पने, (२) दोलने-वज्जा. ६४।

√रङ्ग् (रगि) १/१४३ श× — गत्यर्थः (प) क्षी-मै-सा-च-कात। गतौ—जै-काक्र-शा-हे-वो। — रजति-निघ. २/१४ = गतिकर्मा।

√रख् (रख) १/ गत्यर्थः (प)।

√रङ्ख् (रखि) १/ गत्यर्थः (प)।

√लङ्ख् (लखि) १/ गत्यर्थः (प)।

क—रेंग् = परिवर्तने, निर्देशने, विस्तारे, गतिविशेषे। नासिक्यम्—: इरि.रेंग् = नितम्बः, श्रोणिः-त्रा. पॉकर्नीः।

ग—रङ्गति-यशस्ति. च. २,८६ = चलति।

ङ—√रंग (अक) = इतस्ततश्चलने-कप्प.; पउम. १०, ३१।

ङ—√रंग (सक) = वर्णं। कर्मणि-रंगिज्जइ-संबोध. १०।

√रङ्घ् (रघि) १/१०२ श× — गत्यर्थः (आ) क्षी-मै-सा-च-कात। गतौ—जै-काक्र-शा-हे। गमने—वो। — रजति-निघ. २/१४ = गत्यर्थः।

ग—अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम्-रघु. ३, २१ इत्यत्र यद्यपि वैयाकरणा √लङ्घ् धातुं स्मरन्ति, ८/२/१८ काशिकोक्त्या च लो रत्वमापादयन्ति तथाप्यन्ते √रङ्घ् वा √रघ् वा धातुः श्रूयते, इत्यनेनैव सम्बन्धः साध्यताम्, क्लिष्टकल्पनाश्रयणानौचित्यात्, अर्थसादृश्याच्च।

√रञ्ज् (रन्ज) १/९८३ श× — रागे (उ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो।

√रञ्ज् (रन्ज) १/८०३ श-जै-शा-हे-वो × — मित्।

रजति-निघ. २/१४ = गतिकर्मा।

रञ्जयति-निघ. ३/१४ = अर्चतिकर्मा।

ग—अनुरञ्जन्ति–वा. रा. ७,९९, ११। रामे रञ्जतु मे मनः–कथासरि. ४३,१६५। रजतः–शब्रा. १२, ८, ३, ११; तांब्रा. १७, १, १४। रजतम्–ऐब्रा. ७, १२।

घ—रञ्जति–सुत्तनिपात ४२४।

ङ—√रञ्च (अक)=रागे। रञ्चइ–कुमा.; वज्जा. ११२।

ङ—√रज्ज (अक)=रागे, (२) वर्णे। रज्जइ–आचा.; उत्त.।

ङ—√रय (अक)=रागे, (२) वर्णे—आचा.।

छ—√रंजना *=(१) प्रसादे, (२) भजने, (३) वर्णे।

छ—√रजना *
√रयना *† } = वर्णे, (२) अनुरागे, (३) संयुक्तौ।

छ—√राँचना *† (अक)
छ—√राँजना† (सक) } =रागे।

√रञ्ज. (रन्ज) ४/५६ शं — रागे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

रागः= वर्णान्तरोत्पादनमासक्तिश्च–दुर्गादासः।

क—रेंग्=वर्णे, सौवर्णे रङ्गे–वा. पॉकर्नीः।

ग—अरज्यत–अ.वे. १५, ८, १। स्त्रियो वा केषु रज्यन्ते–मभार. १३, २२३४। न कामेऽपि वेश्या रज्यति–कथासरि. ३८, ३९। नेत्रे स्वयं रज्यतः–उत्तररा. १०२, १८ (१३८, २)। अरज्यत्–शिशु. ९, ७। √युज् ४/ धातुवदिमं ह्विट्नीमहाशयः कर्मवाच्यं कुतो नाश्रुतवान्?

√रट् (रट) १/२९४ श — परिभाषणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। वाचि—वो। — √रठ् (रठ) १/ परिभाषणे(प)। √रण् (रण) १/ शब्दार्थः(प)।

ग—क्रौञ्चीं भयार्तामिव रारटन्तीम्—वा. रा. २, ७७, ३२। रटन्तः करटाः कटु–काशीख. ६८, ५३। रटन्ति–बृ. सं. १९, ७; कथासरि. १८, १०९।

च—√रड (अक)=(१) रोदने, (२) क्रन्दने, उच्चैः शब्दे। रडइ–भवि.। रड़ते=रोदिति—महाराष्ट्रि.।

छ—√रटना।

छ—रार<रारि (<राटिः)=कलहः।

+√रठ् (रठ) १/३३३ च×,श	परिभाषणे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे । भाषणे—वो	√रट् (रट) १/परिभाषणे (प) । √रण् (रण) १/ शब्दार्थः (प) । √रिण् १/२०७८ शब्दे (प) काकृ ।

छ—√रढ़ना* = रटने । "उतरे बनता जै राम रढ़ैं"–तुलसी. ।

छ—√ररना† = रटने । [रठ† = शुष्कः (म्)] ।

√रण् (रण) १/४३८ श×	शब्दार्थः (प) क्षी-मै-सा-च । शब्दे—जै-काकृ-कात-शा-हे । रुति—वो ।	√रट् (रट) १/ परिभाषणे (प) । √रण् (रण) १/गतौ (प) मित् । व्+√रण् = √व्रण् (व्रण) १/ शब्दार्थः (प) ।

क—ऐर् । (ऐ) रे- = उत्तेजने, प्रोत्साहने–वा. पॉकर्नीः ।

ग—रणन्ति–ऋ. ८, ९२, २०; कौ. २, ७३; शौ. २०, ११०, २ ।

घ—रण = प्रमोदः, युद्धम् ।

छ—√रनना (<रणनम्) = शब्दे, झङ्कारे ।

छ—√लरना
छ—√लड़ना } (<रणनम्) = युद्धे ।

छ—[√राँढ़ना† = रोदने, विलापे (<रण्डा ?)] ।

+√रण् (रण) १/७८९ श×	गतौ (प) मित् । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√रल् १/२४७ hh गतौ (प) काकृ । √रल्ल् १/२४७ ii गतौ (प) काकृ । √रिण्व् (रवि) १/गत्यर्थः (प) । √रम् (रमु) १/क्रीडायाम् (प) ।

क—आँग्ल.–√रन् = गतौ, धावने—वागीशः ।

ग—रणयन्तु–शौ. ४,२१,१; तैब्रा. २,८,८,१ । रणय–मभार. ५,१५,२७ = इष्टं कामं गमय = प्रापय (नील.)–टीकायामेव ।

√रण्व् (रवि) १/५९० शा-काक्र-कात × (हे-√रम्ब् [रबु]) गत्यर्थः (प) क्षी-मै-सा-च । गतौ—जै-शा-हे । व्रजे—वो ।

√रण् (रण) १/७८९ गतौ (प) ।
√रण्व् (रवि) १/ गत्यर्थः (प) ।
√रव् १/२५६ e गतौ (प) काक्र ।

ग—रण्वः–ऋ. १,१४४,७ । बृहस्पतिस्त्वा सुम्ने रण्वतिं–तै. १,२,५,१=रमयतु ।

छ—√रामना * ‡ (<रम्बनम्–हे<रण्वनम्)=भ्रमणे, विचरणे ।

√रद् (रद) १/५१ श × विलेखने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे । उत्पाटे—वो ।

क—रेद्–ःरॉद्–ःरूद् = विलेखने । लैति. रॉदो=दन्तैर्दशने, विलेखने, भक्षणे; रादो=दन्तैः खण्डने, विलेखने–वा. पॉकर्नीः ।

ग—रदन्ति–ऋ. ७,६०,४; मै. ४,१२,४ । रदति–तांब्रा. १६,६,६; जैब्रा. १४५ ।

छ—रँदना (<रदनम्)=यन्त्रविशेषेण विलेखनान्मसृणीकरणे ।

√रध् (रध) ४/८० श हिंसासंराद्ध्योः (प) क्षी-मै-सा-शा-हे । हिंसायाम्—च-काक्र । संराध्ये हिंसने च—जै । संराद्धौ हिंसायां च—कात । हिंसने पाके—वो ।

रध्यतिर्वशगमनेऽपि दृश्यते —निरु. १०,४०,२ ।

क—लेम्–,लेन्ध्=भेदने, त्रोटने; पु. प्रशि. लन्दन् =रन्धम् (द्वितीया)–वा. पॉकर्नीः ।

ग—रध्यतु—ऋ. १,५०,१३; शौ. १७,१,६ । रध्यति–शब्रा. ३,४,२,३; (ऋ.६, २५,९–हिंसायाम्) ।

घ—रन्धि=पाके–मिलिन्दपञ्ह १०७ ।

छ—√राँधना (<रन्धनम्)=पाके ।

√रप् (रप) १/३९९ श × व्यक्तायां वाचि (प) क्षी-मै-सा-जै-काक्र-कात-शा । वचने—च ।

√लप् (लप) १/ व्यक्तायां वाचि (प) । वि रप्शते–ऋ. ४,४५,१= पूर्णतायाम् ।

व्यक्ते वचने—हे ।
वदे—वो ।

क—लेप्=शब्दे । पामीर्. लॉवम्, लेवम्=शब्दाः, शब्दे, वचने, परम्परा—वा. पॉकर्नीः ।

ग—रपति-ऋ. १०,६१,१८; रपामि–१०,१०,११; शौ. १८,१,१२ । रारपीति–ऋ. ६,३,६ ।

√रफ् (रफ) १/४०९ शX — गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । वक्रे गत्याम्—वो । — √रम्फ् (रफि) १. गतौ (प) । √ऋफ् (ऋफ) ६. हिंसायाम् (प) । √रिफ् (रिफ) ६. कत्थनयुद्धहिंसादानेषु (प) मै ।

क—रेप्=सञ्चूर्णने, मर्दने, अपसारणे । लैति.-रपिऑ,-ऐरे=अपसारणे, मर्दने—वा. पॉकर्नीः ।

ग—रफिताय-ऋ. १०,११७,२ [धा.रिक्तभावे वृत्तिः ? वैतु. सा.GW प्रभृ. हिंसायां रोगे इति, वे. शब्दे इति]।

छ—√रपटना† (<रफणनम्=सर्पणम् । तु. (फार.) रफतन्)=स्खलने ।

छ—√रवड़ना (<रफणम्=सर्पणम्)=भ्रामणे, चालने ।

छ—√रपाती=कृपाणः [हिंसायाम्]–(डिंग.) ।

√रभ् (रभ) १/९५९ जै-शाX,श — राभस्ये (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो । आरम्भे—च
राभस्यम्=कार्योपक्रमः–क्षी । — √लभ् (डुलभष्) १/प्राप्तौ (आ) ।

क—रेम् (अथवा रेमाx)=विश्रान्तौ, एकत्रीकरणे, विश्वासे, स्थापने । लिथु. रम्बुस्=मन्दः (म्), निष्क्रियः । लिथु. रेम्वेति–वा. पॉकर्नीः ।

क—रव्=तीव्रम्, कलहकारिन् (री)—वा. पॉकर्नीः ।

ग—ये त्वारभ्य-ऋ. १,५७,४ । रभस्व-शौ. ११,१,१४ । रभे–पै. १९,३१,२ ।

ङ—√रंभ=गमने । रंभंति–कुमा. ।

√रम् (रम) १/८३८ श-च-जै-काकृ-कात-वो× | क्रीडायाम् (आ) क्षी-मै-सा-शा-हे ।
√रम् (रमु) १/८५६ क्षी-श-शा× | मै-सा-च-जै-काकृ-कात-हे । क्रीडे—वो ।

रम्णाति–निघ. २/१९= वधकर्मा ।
√रम् १०/७१ b परिवेष्टने (प) काकृ ।
रामयः–ऋ. १,१२१,१३ [धा. दीपने वृत्तिः] ।

क—रेम्=विश्रान्तौ, शयने, निमज्जने, वेगेन क्षेपणे, उच्छालने ।
ख—रम्यातु् =विश्रान्तौ, शयने–वा.पॉकर्नीः ।
ग—रमते–ऋ. २,३८,२; शौ. १०,७,३७; पै. ५,२१,७ ।
घ—रमति–संयुत्त. १,१७९ ।
ङ—√रम (अक)=(१) क्रीडायाम् , (२) संभोगे । रमइ; रमए–कुमा. ।
छ—√रमना, √रवना* } (<रमणम्)=क्रीडायाम् ।
छ—√रामना*† =भ्रमणे, विचरणे ।

√रम्फ् (रफि) १/४१० श× | गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । वधे गत्याम्—वो ।

ङ—√रंभ (सक)=गतौ । रंभंति–कुमा. ।
ङ—रप्फ=वल्मीकम्–दे. ७,१; गुर्जरभाषायाम्–राफडो ।
छ—राँपी=पादूकृतामुपकरणम् ।

√रम्ब् (रबि) १/३७३ श-जै-काकृ-शा× | शब्दे (आ) क्षी-मै-सा-कात-हे,-वो (प) । अवस्रंसने—च ।

√लम्ब् (लबि) १/ शब्दे (आ) ।
√अम्ब् (अबि) १/ शब्दे (आ) ।
√रम्ब् (रबि) १/ गत्याम् (प) वो ।
√रम्भ् १/३६२a धारणे (प) काकृ ।

क—रेम्ब्=विरूपणे, वेष्टने । लिथु. रेम्बेति=वृद्धौ, प्रापणे; रम्बुस्=मन्दम् । इरि.–रेम्बद्=विरूपणम् ,वेष्टनम् —वा. पॉकर्नीः ।

ग—रम्बते—ऋ. १०,८६ (१६; १७); शौ. २०,१२६,१६; अवरम्बमाणः–ऋ. ८,१,३४।

√रम्भ् (रभि) १/३८२ मै-श-च×

शब्दे (आ) इति दुर्गः–क्षी। क्षी-सा-जै-काकृ-कात-शा-हे-वो।

<√रेभ् (रेभृ) शब्दे (आ)। √अम्भ् (अभि) १/ शब्दे (आ)। शेषः पूर्ववत्। √रम् (रम) १/ क्रीडायाम् (आ)।

ग—रम्भमाण०–भा. पु. १०,३६,२।

छ—√रँभाना / √रम्हाना / √राँभना } (<रम्भणम्)=हम्बारवे।

+√रय् (रय) १/४७९ श×

गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।

√री ९/ गतिरेषणयोः (प)। रयीयान् ऋ. ३,६२,२।

ग—रयः—वा. रा. २,६४,६९। वृक्षस्येव नदीरयाः–मभार. २,१७,६।
छ—रई (<रयः=स्पन्दने)=खजः, मन्थनदण्डः।

√रस् (रस) १/७०६ श×

शब्दार्थः (प) क्षी। शब्दे—मै-सा-च-जै-काकृ-कात-शा-हे-वो।

√रास् (रासृ) १/ शब्दे (आ)। रसति—निघ. ३/१४= अर्चतिकर्मा। रथो रंहतेर्गतिकर्मणः।··· रसतेर्वा–निरु. ९,११,३। रसा नदी रसतेः शब्दकर्मणः–निरु. ११,२५,१।

क—रास्=शब्दे। गॉथि. रज्द। पु. उ. ज. रस्त=भाषणम्–वा. पॉकर्नीः।
ग—अरसत्–शब्रा. ६,१,१,११। रसति–गोपालपूर्वतापिन्यु. ५। रास राक्षसः–वा. रा. ७,७,२८।

घ—रसति—जातक २,४०७।
ङ—रस=क्रन्दने, उच्चैः शब्दे। रसइ–गा. ४३६।

√रहू (रह) १/७२३ श×	त्यागे (प) क्षी-मै-सा-जै-काक्ठ- कात-शा-हे। परित्यागे—च। त्यजि—वो।	√रह (रह) १०/ त्यागे (प)।

क—रेघु् = त्यागे।

ख—अवे. रजहू = रहः (निर्जनता)। न. पर्सि.-राज् = ऋणदाने-वा. पॉकर्नीः।

ग—नोत्सहे त्वां विरहितुं शून्ये-वा. रा. २,५१,१७। रहित०-मभार. ६, ५८२४। रहति-प्रशस्ति. च., ३ आ., ४२९ पृ. = मुञ्चति।

ङ—√रह (सक) = त्यागे—कल्पू.; पिंग.।

√रा २/४६ श	दाने (प) क्षी-मै-सा-जै-शा-हे। आदाने—च-काक्ठ- कात। दाने ग्रहणे—वो	√ला २/आदाने (प)। √रै १/८९४ शब्दे (प)। राति-निघ. ३/२० = दान- कर्मा।

क—रा (इ) = दाने-वा. पॉकर्नीः।

ग—रासि—ऋ. १,१४०,१२। राते-तै. ३,४,९,१; तैब्रा. १,७,२,१। राति-रापू. १,१।

+√राख् (राखृ) १/१२२ श×	शोषणालमर्थयोः (प) क्षी-मै-सा-जै-काक्ठ- कात-शा-हे। शोषणे—च। ओखृवत्(=शोषालम- र्थयोः)—वो।	√लाख् (लाखृ) १/ शोषणा- लमर्थयोः (प)। √द्राख् (द्राखृ) १/ शोषणा- लमर्थयोः (प)। √ध्राख् (ध्राखृ) १/ शोषणा- लमर्थयोः (प)। √लाघ् (लाघृ) १/ सामर्थ्ये (प)।

+√राघ् (राघृ) १/१०९ श×	सामर्थ्ये (आ) क्षी-मै-सा-च-जै-काक्ठ- कात-शा-हे। शक्तौ—वो।	पूर्ववत्।

√राज् (राजृ) १/८०५ श	दीप्तौ (उ) क्षी-मै-सा-च, जै (आ), काकृ-कात-शा-हे-वो।	√रा २/ दाने (प)। √रास् (रासृ) १/२४० दीप्तौ (आ) जै; १४४—शा।

क—रेजु =पदम्, विस्तारे, निर्देशनम्, उद्देश्यम्।

ख—अवे. रस्तर् = राष्ट्रम्—वा. पॉकर्नीः।

ग—राजति-ऋ. ४,५३,४; राष्टि-१,१०४,४। राजते-ध्यानबिन्दूप. १०४; योशि. १,३८।

घ—राजति-विमानवत्थु १३४।

छ√ राजना * (<राजनम्)=(१) उपस्थितौ, (२) शोभने।

√राध् (राध) ४/६७	राधोऽकर्मादृवृद्धावेव (प) क्षी-मै-सा-हे। संसिद्धौ—च-जै-काकृ-कात-शा। सिद्धौ—वो।	√रध् (रध) ४/ हिंसासंराद्ध्योः (प)।

क—रे-ध्-, रॉ-ध्, रृ-ध्:—जू. पॉकर्नीः।

ग—नरकाय राध्यति-आपस्त. १०५; राध्यते विद्युति मानवद्भवति-तैत्तिरीयो. ३,१०,६। तन्मे राध्यताम्-वा. सं. १,५। दैवं तत्रापराध्यति-वा. रा. ६,१०१,९।

√राध् (राध) ५/१६ श	संसिद्धौ (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। सिद्धौ—वो। संराध्ये—जै।

क—पूर्ववत्।

ग—राधति-ऋ. ११,६३,६। राध्नोति-शब्रा. १,३,५,१०[२]; जैउ. १,१६,३,१०।

छ—√ राधना =(१) आराधने, पूजायाम्, (२) सिद्धौ, पूर्तौ, (३) साधने।

√रास् (रासृ) १/६१८ श-जै×	शब्दे (आ)। क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।	रासति-निघ. ३/२०—दानकर्मा। √राश् १/ शब्दे (आ) वो

क—रास्=शब्दे, क्रन्दने-वा. पॉकर्नी: ।

ग—रासते–ऋ. १,९६,८; शत्रा. ३,९,४,४ । रासमाना–पै. १७,३,१२; [धा. दाने वृत्तिः] ।

छ—√राहना=यन्त्रकुट्टने (टङ्कने)–[कुट्टनेन शब्दो जायते, तत्रैवाकूतम्] ।

√रि ५/२९	हिंसायाम् (प) ।	रिणाति–निघ. २/१४=
श-च-जै काक्ट-कात-	(क्षी. यु. मी. सं. ×)	गतिकर्मा ।
शा-हे-वो ×	क्षी-मै-सा ।	रिणाति–ऋ. १,१६६,६ ।
	प्रवाहे, शनैः सर्पणे	√रि ६/ गतौ (प) ।
	—ह्वि. ।	√चिरि ५/ हिंसायाम् (प) ।

अरिण्वन्–मै. सं. इति ह्वि. । मया नावाप्तम् ।

+√रि ६/१२३	गतौ (प) ।	√रि ५/ हिंसायाम् (प) ।
श (काक्ट-कात √रिप्	क्षी-मै-सा-च-जै-काक्ट-	
[रिपि] संभूय पठितं	कात-शा-हे-वो ।	
धातुद्वयम्) ।		

ङ—√रिअ (सक)=गतौ । रियइ– सूअ. २,२,२०; सुपा. ४४५ ।

√रिख् (रिख) १/१३९	गत्यर्थः (प) द्रमिडाः	<√रङ्घ् (रखि) गत्यर्थः (प) ।
क्षी-मै-श-च-जै-कात-शा-	पठन्ति—सा ।	√रेखा (कण्ड्वा. ३५)
हे-वो ×	सा ।	श्लाघासादनयोः (प)
	गतौ—काक्ट ।	सा ।
६/	ह्वि. ।	√लेखा (कड्वा. ३०) स्खलने
		च (प) सा ।
		√लिख् (लिख) ६/ अक्षर-
		विन्यासे (प) ।

ग—आ रिख किकिरा कृणु पणीनां हृदया कवे–ऋ. ६,५३,७ । रेखा–कालाग्निरुद्रो. ४; त्रिपुरो. १०; रुद्रजाबालो. १,१४; जाबालयु. २० ।

ङ—√रेखना (<रेखणम् , लेखनम् ?)=रेखाकर्षणे, (२) विलेखने ।

√रिङ्ख् (रिखि) १/१५३	गत्यर्थः (प) इति	<√रिङ्ग् (रिगि) गत्यर्थः
मै-सा-श-च-जै-काक्ट-कात-	द्रमिडानाम्—क्षी ।	(प) ।

शा ×	क्षी । गतौ—हे । सर्पणे—वो ।	√लिङ्ग् (लिगि) १/ गत्यर्थः (प)।

क—*(स्) रेङ्घ् (अथवा (स्) रेङ्ख्-?)=रोहणे, रिङ्गणे (दृढम्)-वा. पॉकर्नीः ।

ग—रिङ्खता-भा. पु. २,७,२७ ।.अथाहमहमिकया सरिङ्खणम्-हालास्यच. ४,७ ।

ङ—√रिक्ख=चलने । रिक्खंतो-कुप्र. ६७ ।

√रिङ्ग् (रिगि) १/१५३ शा ×	गत्यर्थः (प)। क्षी-मै-सा-च-कात । गतौ—जै-काकृ-शा-हे-वो ।	>√रिङ्ख् (रिखि) गत्यर्थः (प)। √रिङ्घ् (रिघि) १/४१२ ॥ गतौ (आ) काकृ ।

क—पूर्ववत् ।

ग—जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः-भा. पु. १०,८,२१ ।

ङ—√रिंग (अक)=रिङ्गणे, (२) प्रवेशे । रिंगइ-पिंग.; टि. ।

छ—√रिंगना (<रिङ्गणम्)=शनैर्गमने—बुं. ख. ।

छ—√रेंगना (<रिङ्गणम्)=कीटसरीसृपाणां गमने ।

√रिच् (रिचिर्) ७/४ श	विरेचने (उ)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । विरेके—वो ।	√ऋज् (ऋज) १/ गतिस्थानार्जनोपार्जनेषु (आ)। √रिज् (रिज) १/ गतिस्थानार्जनोपार्जनेषु (आ)। √रिच् (रिच) १०/ वियोजनसम्पर्चनयोः (प)।

क—लेइकु=निवृत्तौ, रोधे, शेषांशस्य त्यागे ।

ख—अवे.-रएक्सनङ्ह=रेक्णस् (=साधु, शोभनम्)। इरिनक्सति=रिणक्ति-वा. पॉ. ।

ग—रिणक्-ऋ. २,१५,८ । रिणक्ति-ऐब्रा. ३,७[३]; गोब्रा. २,३,३[२]; काठ. २८,१; क. ४४,१ ।

छ—√रेचना* (<रेचनम्)=मलनिर्गमे, विरेचने ।

छ—√रीतना (<रिक्तम्)=रिक्तीभावे ।

+√रिज् (रिज) १/१७३ मै-सा-श-च-जै-काक्र-कात-शा-हे×	गतिस्थानार्जनोर्जनेषु (आ)। अन्ये तु—क्षी। ऋज्यर्थे (=भृजि)—वो।	<√ऋज् (ऋज) गतिस्थानार्जनोर्जनेषु (आ)।
+√रिण्व् (रिवि) १/५९१ श-काक्र× (हे-रिम्ब् [रिबु])	गत्यर्थः (प)। क्षी-मै-सा-च-कात। गतौ—जै-शा-हे।	√रिम्ब् १/गत्याम् (प) वो। √रण्व् (रवि) १/ गत्यर्थः (प)। √रण् (रण) १/ गतौ (प)।

छ—√रेलना (<रेणना<रिणना<रिण्वनम्)=प्रेरणे, (२) अतिभोजने।

अ√रिप् (रिपि) ६/१५ पाणिनीयः	गतौ (प) काक्र-कात। लेपे—ह्वि.।	√लिप् (लिप) ६/ उपदेहे (उ)।

क—लाइप् =लेपे-वा. पॉकर्नीः।
ग—रिरिपुः-ऋ. ५,८५,८; तै. ३,४,११,६। रिप्तम्-ऋ. १,१६२,९।

√रिफ् (रिफ) ६/२६ क्षी×, श (च-काक्र√ऋफ्)	कत्थनयुद्धहिंसादानेषु (प) मै। मै-हे। कत्थनयुद्धनिन्दाहिंसादानेषु—सा-जै-काक्र-कात। कत्थने। हिंसायाम्—च। कत्थनयुद्धनिन्दनहिंसादानेषु—शा। अर्फे (=दानश्लाघानिन्दाहिंसाजौ)—वो। भर्त्सनहिंसयोः—काक्र।	<√ऋफ् (ऋफ) हिंसायाम् (प)। √रिह् (रिह) ६/ कत्थनयुद्धहिंसादानेषु (प)। √ऋह् (ऋह) ६/ कत्थनयुद्धहिंसादानेषु (प)।

ग—रिफती-शौ. ३,२८,१। विरिफितं विरिफितस्य-ऐब्रा. ५,४। रिफ्यते-आ. श्रौ. १,५,१०। अवरिफन्तौ-काठ. २७,८। आरेफन्तः-शांब्रा. १७,९ (औवादिकः ?)।

√रिशृ (रिश) ६/१३९ श×	हिंसायाम् (प) क्षी-मै-सा-च-काक्ठ-कात- शा-हे। हिंसने—जै। हिंसे—वो। दारणे—ह्वि.।	√रिष् (रिष) १/ हिंसार्थः (प)। √रि ५/ हिंसायाम् (प)। वा लिशते-शब्रा. ४,४,३,१३। √लिश् (लिश) ६/ गतौ (प)

क—राइ=दारणे। *राइश्-संस्कृते—वा. पॉकर्नीः।

ग—रिशन्तीः—ऋ. ६,२८,७ [रुशन्तीः-इति पाभे.]। रिशाम्-शौ. ११,११, १५। धीरा रिशन्ताम्-ऋ. १०,१६९,१।

√रिष् (रिष) १/६८५ श×	हिंसार्थः (प) क्षी-मै-सा-कात। हिंसायाम्—सा-च-जै- काक्ठ-शा-हे। वधे—वो।	रिषण्यति-ऋ. २,२३,१२।

क—राइ-दारणे। राइस्—ः

ख—अवे. रएस्-, इरिस्=दारणे। (वर्तमानकाले-रएस्येइति, इरिस्येइति)-वा. पॉकर्नीः।

ग—भ्रेषते जनो न रेषत्-ऋ. ७,२०,६; मा रिषाम वयं तव-१,९४,१ (तौदादिकः)।

√रिष् (रिष) ४/१२२ क्षी-मै-श-च-जै-काक्ठ- कात-शा-हे-वो×	हिंसायां, च=रोषे (प) सा।	√रिष् (रिष) १/६८५ हिंसार्थः (प)।

क—, ख—पूर्ववत्।

ग—रिष्यति-शौ. १४,१,३०; तैआ. १,११,७; जैब्रा. ५८; छान्दो. ४,१६,३[२]।

घ—रिस्सति-मज्झिम. १,८५।

छ—√रिसना † / रीसना* } =रोषे।

√रिह् (रिह) ६/२७ मै-श-च-जै-काक्ठ-कात-	कत्थनयुद्धहिंसादानेषु (प) इति द्रमिडाः—क्षी	<√ऋह् (ऋह) कत्थनयुद्ध- हिंसादानेषु (प)।

शा-हे-वो ×	आस्वादे—ह्वि.।	√लिह् (लिह) २/ आस्वादने (उ)। √रिफ् (रिफ) ६/ कत्थनयुद्धहिंसादानेपु (प) मै। √रिह् १/ वधे (प) वो। रिहति—निघ. ३/१४= अर्चतिकर्मा।

ग—रिहते-ऋ. ८,२०,२१। रेढि-मै. १,६,५। रिहन्ति-शत्रा. ४,२,१,१०; रेह्वि-ऐआ. ३,१,६।

√री (रीङ्) ४/३० श	स्रवणे (आ) क्षी-च-शा-हे। श्रवणे—मै-सा-च-जै-काकृ-कात। क्षरणे—वो।	√री (रीङ्) ९/ गतिरेषणयोः (प)। रीयते-निघ. २/१४= गतिकर्मा।

क—ऐर्=उत्तेजने, प्रवाहे। ऐरेइ—:—वा. पॉकर्नीः।

ग—रीयते घृतम्-ऋ. १,१३५,७; रीयते १०,५३,८; शौ. १२,२,२६।

ङ—√री } (अक)=चलने, गतौ। रीयइ, रीइज्जा-आचा.; सूअ. १,२,
ङ—√रीअ } २,५; उत्त. २४,७।

√री ९/३० श	गतिरेषणयोः (प) प्वादिः क्षी-मै-सा-हे। गतौ रेषणे च—शा। श्रवणे—जै-काकृ-कात। वधे गतौ—वो। प्रवाहे—ह्वि.।	√री (रीङ्) ४/ स्रवणे (आ)। √ली ९/ गतौ (प) वो। रिणाति-निघ. २/१४= गतिकर्मा।

क—पूर्ववत्।

ग—रिणाति पश्वः सुधितेव बर्हणा—ऋ. १,१६६,६=पृथक्करोति-दुर्गाचा.।

√रु (रुङ्) १/९४४ श-काकृ ×	गतिरेषणयोः (आ) क्षी-मै-सा। गतौ—च। गतौ रोषे च—जै।	√रु २/२३ शब्दे (प)।

गतौ रोषणे च—कात-शा ।
गतौ रेषणे च—हे ।
वधे गत्याम्—वो ।
दारणे—ह्वि ।

ग—अरवन्त—तांब्रा. ७,५,११ । रवत्-तैब्रा. ३,६,६,४ ।

ङ—√रव } (सक)=वचने, (२) वधे, (३) गतौ, (४) [अक] रोदने,
ङ—√रय } (५) शब्दे । रवइ-संक्षि. ३३ ।

√रु २/२३ शब्दे (प) क्षी-मै-सा-च-जै-काक्ठ-कात-शा-हे-वो । रौति-निघ. ३/१४=अर्चतिकर्मा ।
श

क—रॉइ-, रेउ-, रु-, रु=गर्जने, शब्दे—वा. पॉकर्नीः ।

ग—शून्ये रौमि-मभार. १,३०२२ । रौति नृत्यति-भा. पु. ७,७,३४ । रोरवीति-शौ. १८,३,६५ । श्वखरोष्ट्रे च रुवति-मनु. ४,११५ ।

ङ—पूर्ववत् ।

+√रुङ्ग् (रुगि) १/१५४ वर्जने (प) मै क्षी-श-च-जै-काक्ठ-कात-शा-हे-वो× मै । <>√वुङ्ग् (वुगि) १/ वर्जने (प) ।

वकाररकारयोर्लिपौ भृशं सादृश्यम् । वकारोदरं मनाक् सङ्कोचं नीयेत चेत् तर्हि वकारो रकारोपमः प्रतीयेत । इयमेव घटनेह घटिता । अक्षरचुञ्चूनामेषा पाठभेदकृपा ।

√रुच् (रुच) १/७३६ दीप्तावभिप्रीत्यां च (आ) क्षी-मै-शा-हे । दीप्तावभिप्रीतौ च-सा-जै (क्षी. यु. मी. सं.) । दीप्तौ—च-काक्ठ-कात । प्रीतिप्रकाशयोः—वो । √रोचते-निघ. १/१६ ज्वलतिकर्मा ।
श

अभिप्रीतिः=अभिलाषः—क्षी ।

क—लॉइच्=दीप्तौ, दर्शने ।
ख—रओचन्त=रुचिमान्, रोचमान०, दीप्तियुतः (ता, तम्) । प्रयोज.-रओचयेइति=रोचयति-वा. पॉकर्नीः ।
ग—रोचते-ऋ. १,५८,२; तै. १,३,१४,८; शौ. १०,८,२४; शब्रा. ६,५,१,७ ।

घ—रोचति-थेरगाथा २,४१५। रुच्चति-सुत्तनिपात ५६५।

ङ—√रोअ (सक)=निर्णये। रोअए—दस. ५,१,७७।

ङ—√लोअ (अक)=रुचौ-कस.।

छ—√रुचना* } =रुचौ।
√रुचना }

√रुज् (रुजो) ६/१२५ भङ्गे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
श

√रुज् (रुज) १०/ हिंसायाम् (प)।

क—लॉइग् (ज्) भङ्गे। लिथु. लुञ्ति=भङ्गे।

ख—अवे.-उरुक्सृति=भङ्गे-वा. पॉकर्नीः।

ग—रुजति-ऋ. १०,८९,६; मै. ४,६,४। रुजामि—तै. १,२,१४,४।

+√रुट् (रुट) १/७३८ दीप्तौ (आ)
मै-सा-श-च-जै-काकृ- क्षी-हे।
कात-शा× दीप्तिप्रतिहत्योः—वो।

>√रुट् (रुट) १/ प्रतिघाते (आ) इत्येके।
√रुच् (रुच) १/७३६ दीप्तावभिप्रीत्याम् (आ)।

+√रुट् (रुट) १/७३८ प्रतीघाते (आ) इत्येके, बाधृ
श-कात× रोटने इति लिङ्गात्-क्षी,
मै-सा-च-हे।
प्रतिघाते—जै-काकृ-शा।
दीप्तौ—हे।
दीप्तिप्रतीहत्योः—वो।

<√रुट् (रुट) दीप्तौ (आ)
√रुठ् (रुठ) १/ प्रतीघाते (आ)।
√लुठ् (लुठ) १/ प्रतीघाते (आ)।
√रुट् १/८८ विशरणगत्यवसादनेषु (प)

√रुठ् (रुठ) १/३३५ उपघाते (प) इत्यपि
श-जै× दौर्गाः—क्षी
क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।

काकेनालोड्यमानां ताम्-वा. रा. २,१०५,३९। काकेनारोध्यमानां ताम्-वा.रा.२,९६,४०।

ग—रोठमानस्य वैदेहीं मांसार्थे वायसस्य…वा. रा. ५,६६,३०।

√रुठ् (रुठ) १/७३९ मै-सा-श-च-जै-शा×	प्रतीघाते (आ) क्षी-कात-हे-वो। प्रतिघाते-काकृ। प्रतिघाते द्युतादौ— रोठते-सा १०/२४८	>√रुट् (रुट) प्रतीघाते (आ) इत्येके—क्षी। √लुठ् (लुठ) १ प्रतीघाते (आ)

ग—पूर्ववत्।

ङ—√रुल (अक) = संवेशने, विश्रान्तौ-धर्मवि. ८०।

+√रुण्ट् (रुटि) १/३२४ श-शा×	स्तेये (प) क्षी-मै-सा-च-जै-काकृ-कात-हे-वो।	>√रुण्ठ् (रुठि) स्तेये (प) इत्येके-क्षी। √लुण्ट् (लुटि) १/स्तेये (आ)। √रुण्ट्—स्तेये-सौ.धा. वो। √रुण्ड् (रुडि) १/स्तेये (प) सा।
+रुण्ठ् (रुठि) १/३२४ मै-श-च-जै-काकृ-कात-शा-हे×	स्तेये (प) इत्येके-क्षी क्षी-वो।	<√रुण्ट् (रुटि) स्तेये (प)। √लुण्ठ् (लुठि) १/स्तेये (प)। शेषः पूर्ववत्।
+√रुण्ठ् (रुठि)१/३४० मै-सा-श-च-जै-काकृ-कात-शा-हे×	आलस्ये गतिप्रतिघाते च (प) क्षी। गत्यालस्यस्तेयखोटे—वो।	पूर्ववत्।
+√रुण्ठ् (रुठि)१/३४२ श×	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	पूर्ववत्।
√रुण्ड् (रुडि) १/३२३ क्षी-मै-श-च-जै-काकृ-कात-हे-वो×	स्तेये (प) शाकटायनः-सा। सा-शा।	

ग—सद्वार्या रुण्डेन रेमे-कथासरि. १५,४१; पृष्ठः-स रुण्डः पुरुषोऽभ्यधात्-६५,११। अवरुण्डनम्-यशस्ति. च., ३ आश्वा, ३९८ पृ.=आरुण्डनम्।

√रुद् (रुदिर्) २/५६ शअश्रुविमोचने (प) क्षी-मै-सा-जै-काक्ृ-कात-शा-हे । अश्रुविमोक्षणे—च । रोदे—वो । √रुध् (रुधिर्) ७/ आवरणे (उ) ।

क—रॉइ-, रोइ-,रु-,रू=शब्दे, रोदने । रॉइद्—:

ख—अवे. रओद्=रोदने, क्रन्दने-वा. पॉकर्नीः ।

ग—रुदन्ति–ऋ. १०,४०,१०; तै. १,५,१,२; शौ. १४,१,४६ । रोदिति–छान्दो. ३,१५,२ । रुदति–षब्रा. ५,७; वउ. ३,५८ । रोदन्ति–जैउ. १,१०,२,४. (भौवादिकः), रोदमानायाः–भा. पु. ४,३०,१४ ।

घ—रुदन्तो–दीघ. १,११५; सुत्तनिपात ६७५; ६९१ ।

ङ—√रुव (अक)=रोदने। रुवइ–संक्षि. ३६; भवि.; महा. । रुवामि–कुप्र. ।

ङ—√रुव्व (अक)=रोदने । रुव्वइ–संक्षि. ३६ ।

ङ—√रुअ (अक)=रोदने । रुअइ–संक्षि. ३६ ।

ङ—√रोअ (अक)=रोदने । रोअइ–संक्षि. ३६ ।

छ—√रोना=रोदने ।

+√[अनु] रुध् (अनो रुध)४/६२ श कामे (आ) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे-वो । √रुद् (रुदिर्) २/अश्रुविमोचने (प)। √रुध् (रुधिर्) ७/आवरणे (उ)।

ग—अनुरुध्यसे–ऋ. ८,४३,९; तै. ४,२,३,३ ।

√रुध् (रुधिर्) ७/१ श आवरणे (उ) क्षी-मै-सा-च-जै-काक्ृ-कात-शा-हे । आवृत्तौ—वो । आवरणे व्याप्तौ—क्रि. र. स. । √रुद् (रुदिर्) २/ अश्रुविमोचने (प) ।

क—उएर्द्=आच्छादने, आश्रये, रक्षणे। रुध्—:

ख—अवे. रओदैति=आवरणे–वा. पॉकर्नीः ।

ग—रुणद्धि–ऋ. १०,४२,९; शौ. ११,५,५; मै. ४,२,४ ।

घ—रुन्धति-चरियापिटक ३,१०; मिलिन्दपञ्ह ३१३; रुम्भति-जातक ६,३९१।

घ—रूहति-विनय. २,५५।

ङ—√रोह=रोधे-काल.; बृह. ३।

छ—√रोधना * (<रोधनम्)=रोधे।

छ—√रूँधना, √रुझना, √रूझना =रोधे।

रुप् (रुप) ४/१२३ श	विमोहने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। विमोहे—वो।	√लुप् (लुप) ४/ विमोहने (प)। √लुभ् (लुभ) ४/ विमोहने (प)।

क—रॉइ=सञ्चूर्णने, खनने, छेदे। रॉइप्=छेदने, भङ्गे—वा. पॉकर्नीः।

ग—रुप्यन्ती-तैब्रा. २,१,१,२। अरुप्यत्-काठ. २४,४; क. ३९,१। रोपः-पै. ३,३७,१ [धा. छेदने वृत्तिः]।

घ—रुप्पति-सुत्तनिपा. ७६७।

√रुश् (रुश) ६/१३८ श	हिंसायाम् (प) क्षी-मै-सा-च-काकृ-कात-शा-हे। हिंसने—जै। हिंसे—वो।	√रुष् (रुष) १/ हिंसार्थः (प)। रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः—निरु. २,२०,१; ६,१३,२। √रुज् (रुज) १०/ हिंसायाम् (प)।

ग—रुशन्तम्-ऋ १,९२,२; शौ १४,१,३८; रुशन्तीः-तैब्रा. २,८,८,१२; शौ. ४,२१,७।

रुष् (रुष) १/६८४ श×	हिंसार्थः (प) क्षी-मै-सा-कात। हिंसायाम्-च-जै-काकृ शा-हे। वधे—त्रो।	√रुष् (रुष) ४/ रोषे (प)। √रुट् (रुट) १०/ रोषे (प) रुश् (रुश) ६/ हिंसायाम् (प)।

क—ऍर्ड्=उत्तेजने।-विस्तारः—रॉइ-स्-ः लिथु. रुस्तु, रुस्ति=रुष्टः (मू)-वा. पॉकर्नीः।

ग—रोषति—ऋ. ८,४,८; शौ. २०,५८,२; जै. ३,५५,११; कौ. २,६७०। रुषता-पै. ५,३१,१ (तौदा.), [भाप.। धा. बन्धने वृत्तिः]।

√रुष् (रुष) ४/११७ रोषे (प)
क्षी-मै-सा-च-जै-
काकृ-कात-शा-हे।
क्रुधि—वो।

क—रॉइ-स्—ः लिथु. रुस्तस्=रुष्टः, अप्रसन्नः-वा. पॉकर्नीः।

ग—रणे यस्य च रुष्यामि-वा. रा. ३,३५,२७; इन्द्रेण रुष्यता-४,४३,२०; रुष्यन्ती-५,३६,३९।

ङ—√रूस (अक)=रोषे। रूसइ, रूसए-उव.; कुमा.।

छ—√रूसना, √रूखना =रोषे।

√रुह् (रुह)१/८४३ शX बीजजन्मनि (प)
क्षी-सा-शा।
जन्मनि प्रादुर्भावे—
मै-कात।
बीजजन्मनि प्रादुर्भावे च—
सा।
प्रादुर्भावे—च।
जनने—जै।
जन्मनि—काकृ-हे।
जन्याम्—वो।

√रुध् (रुधिर्) ७/१ आवरणे (उ)।
रोधति-ऋ. ८,४३,६=वृद्धौ।

क—लॉइध्=वृद्धौ, प्रादुर्भावे।
ख—अवे. रओदैति=वृद्धौ, प्रादुर्भावे-वा. पॉकर्नीः।
ग—रोहति-ऋ. ८, ४१, ८; तै. ५, ३, ६, ३; शत्रा. ५, १, ५, १।
घ—रुहति-इतिवुत्तक ६७।
ङ—√रुह (अक)=उत्पत्तौ, (२) व्रणपूर्तौ। रुहइ-नाट.; कर्मणि-स. ४१३।
ङ—√रोह (अक)=उत्पत्तौ। रोहंति-गउड.।
ङ—√रुप्प (सक)=रोपणे, वपने। रुप्पसि-धर्मवि. ६७।

छ—√ रुह्ना* (<रोहणम्)=आरोहणे, वृद्धौ ।
छ—√ रोह्ना* (<रोहणम्)=आरोहणे, (२) सादित्वे (अश्वारोहणे) ।

√ रूष् (रूष) १/६६५ भूषायाम् (प) ।
क्षी-मै-श-च-जै-काक्व- इति सुधाकरः—सा ।
कात-शा-हे वो ×

ग—शेते पांसुषु रूषितः—मभार. ९,३; पांसुषु रूषितगात्र०—वा.रा. २,६७,२४ । 'रूषति' इति नावाप्यते प्रयोगः ।

+√ रेक् (रेकृ) १/७७ शङ्कायाम् (आ) ।
श×(काक्व-√ एक् [एकृ]) लैपिकी त्रुटिः । क्षी-मै-सा-च-जै-काक्व-कात-शा-हे-वो ।
√ रग् (रगे) १/ शङ्कायाम् (प) ।
अरेक्लस्यत्—काठ. ७,१०; क. ५,९ ।

[छ—√ रेंकना (अनु. ?)=गर्दभरासने ।]

√ रेज् (रेजृ) १/१७८ दीप्तौ (आ) इति च
मै-श-जै-काक्व-कात-शा-हे× चन्द्रः—क्षी ।
क्षी-सा-च-वो ।
कम्पने—ह्वि. ।
√ भ्रेज् (भ्रेजृ) १/ दीप्तौ (आ) ।
रेजते—निघ. २/१४=गतिकर्मा ।
√ एज् (एजृ) १/ कम्पने (आ) ।

क—लाइज् (ग्)-, लॉइज् =कूर्दने, कम्पने ।
ख—न. पर्सि. आलेक्सतन् = कूर्दने, ताडने—वां. पॉकर्नीः ।
ग—रेजते—ऋ. १,८०,१४; भिया यामेषु रेजते—१,३७,८; रेजति—१,१६८,५ ।
ङ—√ रेरिज्ज (अक)=अतिशयशोभने—णाया. १,२,—पत्र. ७८ ।

√ रेट् (रेटृ) १/८४९ परिभाषणे याचने च (उ)
श×, (काक्व√ रेड् [रेडृ]) क्षी ।
परिभाषणे—मै-सा-च-जै-काक्व-कात ।
याचने परिभाषणे च—शा ।
परिभाषणयाचनयोः—हे ।
√ रट् (रट) १/ परिभाषणे (प) ।
√ रठ् (रठ) १/ परिभाषणे (प) ।
रेळते—निघ. २/१२=क्रुध्यतिकर्मा ।

याचे वाचि च—वो।

√रेड् वञ्चने—ह्वि.।

ग—अरेडता (=अनादरमकुर्वता) मनसा तच्छकेयम्–तै. १,६,३,२; काठ. ३२,२।

+√रेपृ (रेपृ) १/३६८ मै-श-च-काक्ष-कात× — गतौ (आ)। क्षी-सा-जै-शा-हे। शब्दे गमने च—वो। — √लेपृ (लेपृ) १/ गतौ (आ)। √ग्लेपृ (ग्लेपृ) १/ कम्पने गतौ च (आ)। √रेबृ (रेबृ) १/ गतौ (आ) मै। √रेवृ (रेवृ) १/ गतौ (आ) मै।

ग—न ध्वस्मानस्तन्वी ३ रेप आधुः–ऋ. ४,६,६।

+√रेपृ (रेपृ) १/३७० मै-श-च-काक्ष-कात× — शब्दे च=गतौ (आ)। क्षी-हे। शब्दे गमने च—वो। गतौ—सा-जै-शा। — पूर्ववत्।

पूर्वधातोरभिन्नोऽयं धातुः क्षीरेण पृथक् संख्यायते।

+√रेबृ (रेबृ) १/३७४ क्षी-सा-श-जै-काक्ष-कात-शा-हे× — गतौ (आ)। मै-च। — पूर्ववत्।

छ— √रेवना† √रेना† }=कस्मिंश्चिद् वस्तुनि प्रवेश्य संधार्य वाऽवलम्बने (दे.श.)।

√रेभृ (रेभृ) १/३८२ श× — शब्दे (आ)। क्षी-मै-सा-च-जै-कात-शा-हे-वो। भर्त्सने—काक्ष। — √रम्भ् (रभि) शब्दे (आ) क्वचित् पठ्यते—क्षी। √रेपृ (रेपृ) १/ शब्दे, च= गतौ (आ)। √रै १/८९४ शब्दे (प)। रेभति–निघ. ३/१४= अर्चतिकर्मा।

क—राइभ् = शब्दे ? लेट्टिश्-रिबेत = तर्जने-वा. पॉकर्नीः ।

ग—रेभते-मै. १,८,२ । रेभमाणाः-मभार. ४,१,५३,२५ = हम्बारवं कुर्वाणाः (नील.) । रिभ्यते-ऋ. ७,७६,७ इति रिभ् धातुरपि । रेभति-ऋ. १,१०५,९ । रेभन्ति-तै. ७,१,१,३ ।

+√रेव् (रेवृ) १/५०८ शX	प्लुतगतौ (आ) । क्षी-हे । गतौ—मै-जै-शा-हे । प्लवगतौ—सा-च-काकृ-कात । प्लुतौ व्रजे च—वो ।	√रेप् (रेपृ) १/ गतौ (प) । √रेब् (रेबृ) १/ गतौ (प) मै । √प्लेव् (प्लेवृ) १/ गतौ (प) ।

ग—न रेवता पाणिना-ऋ. ४,२५,७ । रेवा = नर्मदा ।

+√रेष् (रेषृ) १/६१५ शX	अव्यक्ते शब्दे (आ) इत्यपि चन्द्रः—क्षी । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । ह्रेषायाम्—वो ।	<√ह्रेष् (ह्रेषृ) अव्यक्ते शब्दे (प) ।
√रै १/८९४ श	शब्दे (प) । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√रा २/ दाने (प) ।

क—रे (इ)-, राइ = उच्चैरारावे, क्रन्दने, भषणे । लिथु.-रिऐजु, रिऐति = तर्जने-वा. पॉकर्नीः ।

ग—रायसि-ऋ. ७,५५, [३;४]; राय-७,५५,३ ।

+√रौड् (रौडृ) १/३५१ श-काकृ-कातX	अनादरे (प) क्षी-मै-सा-च-जै-शा-हे । टान्तवत् (=अनादरे) —वो ।	√रौट् (रौटृ) १/ अनादरे (प) वो । √रुट् (रुट) १/ प्रतीघाते (आ) । शेषः पूर्ववत् ।

छ—रौरा (<रौडः) = कलहः ।

+√लख् (लख) १/१३८ गत्यर्थः (प)
श-काकृ×
क्षी-मै-सा-च-कात।
गतौ—जै-शा-हे।
सृपि—वो।

√रख् (रख) १/ गत्यर्थः (प)।
√रङ्ख् (रखि) १/ गत्यर्थः (प)।
√लङ्ख् (लखि) १/ गत्यर्थः (प)।

√लग् (लगे) १/७८० सङ्गे (प) घटादिः।
श×
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

√लग् (लग) १०/ आस्वादने (प)।
लग्यतेर्वा स्यादाश्लेषकर्मणः-निरु. ४,९,१।

क—(स्) लेग्-ः (सं) लूग्-तथा—(स्) लेग्=मृदु, शिथिलम्, मन्दम्-वा. पॉकर्नीः।

ग—लगति-नादबिन्दू. ३८; यो. १,२७। विवादोऽत्रालगत् तयोः-कथासरि. ७७,१२। खलु लगन्ति गिरः-शिशु. ९,६९।

घ—लगति-विनय. १,२०२।

छ—√लगना = सङ्गे।

+√लङ्ख् (लखि) १/१३९ गत्यर्थः (प)
श×
क्षी-मै-सा-च-कात।
गतौ—जै-काकृ-शा-हे।
सृपि—वो।

√रङ्ख् (रखि) १/ गत्यर्थः (प)।
√रङ्ग् (रगि) १/ गत्यर्थः (प)।
√लङ्ग् (लगि) १/ गत्यर्थः (प)।

ङ—लंख (<लङ्खः) = लम्बतरवेणोरुपरि नटनशीला नटजातिः।

+√लङ्ग् (लगि) १/१४४ गत्यर्थः (प)
श×
क्षी-मै-सा-च-कात।
गतौ—जै-काकृ-शा-हे।
खञ्जने—हे।
गतौ खञ्जे—वो।

√लाङ्गलं लङ्गतेर्लाङ्गूलवद् वा। लाङ्गूलं लगतेर्लङ्गतेर्वा-निरु. ६,२५,१।
√लग् (लगे) १/ सङ्गे (प)।
शेषः पूर्ववत्।

क—(स्) लेग्-ः (सं) लूग्-तथा-(स्) लेग्=शिथिलम्, मृदु, मन्दम्-वा. पॉकर्नीः।

क—लॅंग=इतस्ततो दोलने, स्पन्दने-वा. पॉकर्नीः।

ग—लङ्ग०-कात्या. श्रौ. २२,३,१९। कपीनां किल लाङ्गूलम्-वा. रा. ५,५३,३ (गी. प्रे. सं.); तस्य लाङ्गलहस्तस्य-वा. रा. २,११८,२८ (गी. प्रे. सं.)।

ङ—लंगिम=यौवनम्, (२) प्रत्यग्रता-कप्पू.।

छ—लँगड़ा (फा.-लंग) = पङ्गुः।

छ—लांग (<लाङ्गूलम्)=कच्छं धौतवस्त्रस्य।

√लङ्घ् (लघि) १/१०३ गत्यर्थः (आ)
शX
क्षी-मै-सा-च-कात।
गतौ—जै-काकृ-शा-हे।
भोजननिवृत्तौ चेति स्वाम्यादयः—सा।
'शोषणे' इत्यग्रे—सा।
अभुग्गत्योः—वो।

√रंह् (रहि) १/ गतौ (प)।
√रङ्ग् (रगि) १/ गत्यर्थः (प)।
√लङ्ग् (लगि) १/ गत्यर्थः (प)।
√लघ् १/४१२ jj गतौ (आ) काकृ।

ग—इतस्ततो विलङ्घद्भिः-भा. पु. १०,४६,१०। साकं भेकैर्विलङ्घन्तः-१०,१२,१०।

घ—लङ्घति-जातक-३,२७२।

ङ—√लंघ (सक)=(१) अतिक्रमणे, (२) भोजननिवृत्तौ। लंघइ, लघेइ-महा.; भवि.।

छ—√लाँघना
छ—√लंघना* } (<लङ्घनम्)=अतिक्रमणे।

√लङ्घ् (लघि) १/१०४ भोजननिवृत्तौ, च=गत्यर्थः (आ)
क्षी।

पूर्वस्माद् धातोरभिन्नमिमं क्षीर एव पृथक् संख्याति।

+√लङ्घ् (लघि) १/१५६ शोषणे (प) मै।
क्षी-(सा)-श-शाX
मै-च-जै-कात-शा-हे।
शोषणे उत्पवने च—काकृ।
शोषे—वो।
सा (१/१०६) गत्यर्थके स्मरति, नात्र पठति।

+√लछ् (लछ) १/२०३ श×, (काकृ— √लञ्छ् [लञ्छ])	लक्षणे (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो ।	√लक्ष् (लक्ष) १०/ दर्शनाङ्क- नयोः (उ) । √लाञ्छ् (लाछि) १/ लक्षणे (प) ।
+√लज् (लज) १/२३४ श×	भर्त्सने (प) क्षी-च-जै-काकृ-कात- शा-हे-वो । भर्जने भर्त्सने च—मै- सा । भर्जने—जै ।	√लाज् (लाज) १/ भर्जने च (प) । √लज् (लज) १०/ प्रकाशने (प) सा । लजति–निघ. २/१४= गतिकर्मा ।

ग—आचारलाजैरिव पौरकन्याः–रघु. २,१० ।

+√लज् (ओलजी) ६/१० वो×,श	व्रीडे (आ) क्षी-मै-सा-च-जै- कात-शा-हे । व्रीडायाम्—काकृ ।	√लज् १/ व्रीडे (आ) वो ।
+√लञ्ज् (लजि) १/२३५ श×	भर्त्सने (प) क्षी-च-काकृ-कात- शा-हे-वो । भर्जने भर्त्सने च—मै- सा ।	√लज् १/२३४ भर्त्सने (प) । √लाज् (लाज) १/ भर्त्सने (प) । √लाञ्ज् (लाजि) १/ भर्त्सने (प) ।

छ—लंज=पादः, कच्छम्, पुच्छः, लंपटता, स्रोतः ।
छ—लंजिका (<लञ्जिका)=वेश्या ।

+√लट् (लट) १/५९५	बाल्ये (प) क्षी-मै-सा-च । परिभाषणे बाल्ये च— जै-काकृ-कात-शा-हे । बाल्योक्त्योः—वो ।	√रट् (रट) १/ परिभाषणे (प) । √लत् घाते–सौ. धा.—वो । √रण् (रण) १/ शब्दार्थः (प) ।

बाल्यम्=बालक्रिया—क्षी ।

ग—लटभललनाभोगसुलभः–वैराग्यशतके द्वात्रिंशः श्लोकः; लटभ०=सलावण्य० । शोभते लटभभ्रुवः–विक्रमाङ्कदेव. ८,६ ।

छ—लट (<लट्वा)=चूर्णकुन्तलः।

छ—√लटकना (<लटनम्)=प्रेङ्खणे, दोलने, कालक्षेपे।

छ—लटक=हावः, मनोहराङ्गभङ्गिः, (२) कुञ्चनीयता, नम्यता।

छ—लटका = सविलासं भाषणम्।

छ—√लटना (<लटनम्)=प्रेङ्खणे, दोलने, श्रान्तिहेतुके स्खलने (बालक्रियेयम्)।

+√लड् (लड) १/३५४ श	विलासे (प) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे-वो।	√लट् (लट) १/ बाल्ये (प)। √लल् (लल) १/ ईप्सायाम् (प) सा।
लड् (लडिः) १/८०३ श×	जिह्वोन्मथनयोः (प) मित्। क्षी, सा। जिह्वोन्मथने—मै-सा-जै। उन्माथने—सा। जिह्वोन्मन्थने—च-काक्ट-कात-शा-हे-वो। उन्मनजिह्वयोः—वो।	

ग—सावित्रे लड्डुकान् दद्यात्—मत्स्यपु. २५५,२०। लड्डुकानि तिलानां च—ब्रह्मवै. पु. ३,८,५३। लड्डुकैः फेनिकाभिश्च—काशीख. ४,९५।

घ—लळति—जातक २,१२१।

(ङ—√लल (अक)=विलासे, (२) प्रेङ्खणे। ललइ, ललेइ—सण.)।

छ—लड़का; लड़की; लाड़; लाड़ला (ली)।

√लप् (लप) १/४०० श×	व्यक्तायां वाचि (प) क्षी-मै-सा-जै-काक्ट-कात-शा। वचने—च। व्यक्ते वचने—हे। भाषे—वो।	√रप् (रप) १/ व्यक्तायां वाचि (प)।

क—लेप्=वचने। पामीर्—लोवम्, लेवम्=वचने। रसन्—लेपेतत=प्रलापे।

ख— न. पर्सि. लाबा, लाबा=विकत्थनम्, मिथ्याप्रशंसनम्–वा. पॉकर्नीः ।

ग—विलपन्–अ.वे. ६,२०,१; लालपन्ती–त्रिपुरो. ६ । विलपामहे–वा. रा. ६,९५,२६ । प्रलपन्–गी. ५,९ । लपतु–मभार. १३,४५१७ ।

घ—लपति–सुत्तनिपात ७७६; इतिवुत्तक १२२ ।

ङ—√लव (सक)=वचने । लवइ–कुमा.; संबोध. १८; सण. ।

ङ—√लालप्प (सक)=अतिवचने, (२) मुहुर्भाषणे, (३) गर्हितवचने । लालप्पइ–सूअ. १,१०,१९ ।

ङ—√लाव (सक)=आकारणे (प्रयोज.) । लावएज्जा–सूअ. १,७,२४ ।

छ—√लवड़ना *† (<लपनम्) [र् > ड् स्वयंभूः]=असत्यभाषणे, (२) गप्पे (जल्पने) ।

√लभ् (डुलभष्) १/९६० प्राप्तौ (आ) क्षी-मै-सा-च-काक्र-कात-हे-वो ।
जै-शा×,श

√लभ् (लभ) ६/१२५ प्राप्तौ (आ) शा ।

क—रब्=कोपाकुलम्, प्रचण्डम्, स्पृष्टम्, आहतम् ?–वा. पॉकर्नीः ।

ग—अन्वालेभिरे–ऋ. १०,१३०,७ । लभते–शब्रा. २,२,३,१ । लभेत्–शौ. २०,१३६,१६ । लभामि–खि. २,६,१७ ।

घ—लभति–थेरगाथा १,३५; सुत्तनिपात १८५ ।

ङ—√लच्छ
ङ—√लभ
ङ—√लब्भ
ङ—√लज्झ
(सक)=प्राप्तौ । लभइ, लभए–आचा.; कस.; विसे. १२१५; भवि—लच्छिसि–उव. । कर्मणि–लज्झइ; लब्भइ–महा. ६०,१६ ।

ङ—√लह (सक)=प्राप्तौ । लहइ, लहेइ, लहए–महा.; पि. ४५७ ।

च—√लह (सक)=प्राप्तौ–पिंग. ।

छ—√लहना=प्राप्तौ ।

+√लम्ब् (लबि) १/३७४ शब्दे (आ) क्षी-सा ।
मै-च-जै-काक्र-कात-शा-हे-वो×,श

√लम्भ् १/ शब्दे (आ) वो ।
√लम्ब् (लबि) १/ अवस्रंसने, च=शब्दे (आ) ।
√रम्ब् (रबि) १/ शब्दे (आ) ।

√लम्ब् (लबि) १/३७६ अवस्रंसने, च शब्दे (आ) क्षी-मै-सा-हे ।
श

√रम्भ् (रभि) १/ शब्दे (आ) ।

अवस्रंसने—च-काकृ-
कात-शा।
अवसंसे—जै।
शब्दे स्रंसने च—वो
लम्बने—ह्वि.।

√रेभ् (रेभृ) १/ शब्दे (आ)।
√रम्ब् १/४०३a अवस्रंसने (आ) च।

क—लेब्-, लेव्, लॉब-, लोब, लाब्, लूब् = शैथिल्ये, लम्बने। नासिक्यम्—लेम्ब्—: वा. पॉकर्नीः।

ग—तिष्ठेल्लम्बेत वा-शत्रा. ११,१,६,३२। लम्बति-तैआ. १०,११,२; महो. १,१। लम्बते-मभार. १२,३६८०।

घ—लम्बति-महावंस ३२,७०।

ङ—√लंब (सक)=(१) आश्रयणे, आलम्बने, (२) अक.-लम्बने। लंबेइ-महा.।

+√लर्ब् (लर्ब) १/४१४ गतौ (प) सा
क्षी-मै-श-च-जै-काकृ- सा।
कात-शा-हे-वो× स्पृहि—वो।

√लर्द् =भारन्यासे-मॉ.नि. विलि.।

√लल (लल) १/३५५ ईप्सायाम् (प) सा
क्षी-मै-श-च-जै-काकृ- सा।
कात-शा-हे-वो×

√लड् (लड) १/ विलासे (प)।

√लड् विलासे १/३५५ अनन्तरे "लल ईप्सायाम्" इति क्वचित् पठ्यते। तत् क्षीरस्वामिपुरुषकारादयो नानुमन्यन्ते, यद् रलयोर्डलयोश्चैकत्वस्मरणाल्ललयति ललनेत्याहुः-सा १/३५५।

ग—वत्स इव मां ललन्-वा. रा. २,४२,१५; ललस्व, ललन्तु-५,२२,२४। ललन्तु-मभार. १३,३०२९।

ङ—√लल=(१) विलासे, (२) लम्बने। ललइ, ललेइ-सण.; महा.; सुपा. ४०३।

छ—रलना*† (<ललनम्=ईप्सायाम्)=एकत्र सङ्गतौ, मिश्रणे।
छ—ललाना (<ललनम्। <लाला ?)=ईप्सायाम्।

√लप् (लप) १/८७४ कान्तौ (उ)
श-जै× क्षी-मै-सा-च-काकृ-
कात-शा-हे।
स्पृहि—वो।

√लस् (लस) १/ श्लेषण-क्रीडनयोः (प)।
•√लष् (लष) ४/१४६; १५४—श।

√लष् (लष) ४/ स्पृहि (उ) वो।

क—लस्=इच्छुकम् (:), इच्छायाम्, उपद्रवि (न्)—वा. पॉकर्नीः।

ग—अभिलषन्ते-मभार. १३,४३९०; मा. पु. ६३,५७। लषतो बुभुक्षितौ-भा. पु. १०,२३,७।

√लस् (लस) १/७०७ श×	श्लेषक्रीडनयोः (प) क्षी-मै-सा-काक्र-कात-शा-हे। क्रीडायाम्—च। श्लेषक्रीडनयोः—जै। शिलपि क्रीडे—वो।	√लश् (लश) १०/ शिल्पोपयोगे (प)। √लष् (लष) १०/ शिल्पोपयोगे (प) शेषः पूर्ववत्।

क—पूर्ववत्।

ग—लसन्त्०-मभार. ३,१५५३३; कथासरि. ११६,२३ (=द्युतौ); लसद्गर्भ-देवी-२३,५३; लसन्मदविलासा-५२,३०६। मुक्ताहारेण लसता-का. प्रका. १०। सरसलसत्-गीतगो. १०।

ङ—लस (अक)=(१) श्लेषणे, (२) द्युतौ, (३) क्रीडायाम्। वक्र-लसंत-सण.।

ङ—√लास (सक)=गात्रविक्षेपे। लासंति-राय. १०१ (प्रयोज.)

छ—√लसना (<लसनम्)=श्लेषणे।

छ—√लसना (<लसनम्) (अक)=द्युतौ, शोभने, (२) सत्तायाम्।

√लस्ज् (ओलस्जी) ६/११ वो×,श	व्रीडे (आ) क्षी-मै-सा-च-जै-कात-शा-हे। व्रीडायाम्—काक्र।	√लज् (ओलजी) ६/ व्रीडे (आ)। √लस्ज् १/ व्रीडे (आ) वो।

निष्ठायां स्कोरिति सूत्रेण सलोपे सति 'लग्नम्' इत्यस्य साधुत्वार्थं √लस्ज् धातुः। वस्तुतोऽपरेण √लज् (ओलजी) व्रीडे इत्यनेनापि तत्सिद्धेः, एतत्प्रयोगानुपलम्भात् सर्वत्र लकारादिषु 'लज्ज्' इत्यस्यैव वर्तमानाच्च 'लज्ज्' इत्यस्य धातोरुपन्यासौचित्य-मिति वागीशः।

क—[लेस्—:] लूस्=मृदु, शिथिलम्—वा. पॉकर्नीः।

ग—स्नुषा श्वसुराल्लज्जमाना-ऐब्रा. ३,२२। लज्जसे-वा. रा. २,१२,५२; मभार. ३,१५६४०। लज्जते स्म कचैर्विना-कथासरि. ६१,१८०।

छ—√लजाना
छ—√लाजना*† } = व्रीडायाम् ।

√ला २/४७ श	आदाने (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे । ग्रहे—वो ।	√रा २/ दाने (प) ।

ग—लातव्यः-तांब्रा. ८,६,८; गोब्रा. १,१,२५ । लाति—सा. द. ११,१२ ।
ङ—√लय (सक) = ग्रहणे । लएइ, लयंति—उव. ।
ङ—√ले (सक) = ग्रहणे । लेइ—कुमा. ।
छ—√लेना = ग्रहणे ।

+√लाख् (लाखृ) १/१२३ श×	शोषणालमर्थयोः (प) क्षी-मै-सा-जै-काकृ- कात-शा-हे । शोषणे—च । ओखृवत् (=शोषालमर्थयोः)—वो ।	√द्राख् (द्राखृ) १/ शोषणालमर्थयोः (प) । √ध्राख् (ध्राखृ) १/ शोषणालमर्थयोः (प) । √राख् (राखृ) १/ शोषणालमर्थयोः (प) । √राघ् (राघृ) १/ सामर्थ्ये (आ) ।
+√लाघ् (लाघृ) १/११० श×	सामर्थ्ये (आ) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे । शक्तौ—वो ।	पूर्ववत् ।
+√लाज् (लाज) १/२३६ श-जै×	भर्जने, च = भर्त्सने (प) क्षी-शा-हे । भर्त्सने, च = भर्जने— मै-सा । भर्त्सने—च-काकृ-कात । भर्त्सने भर्गे—वो ।	√लज् (लज) १/ भर्त्सने (प) । √लञ्ज् (लजि) १/ भर्त्सने (प) । √लाञ्ज् (लाजि) १/ भर्जने च = भर्त्सने (प) । √राज् (राजृ) १/ दीप्तौ (प) ।

ग—आचारलाजैः-रघुः २,१० । क्षीरस्वामिभानुजिद्दीक्षितौ—√लज् भर्जने इत्यस्माद् व्युत्पादयतः । उभयथैतच्छक्यम् ।

√लाञ्छ् (लाछि) शX — लक्षणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। — √लक्ष् (लक्ष) १०/ दर्शनाङ्कनयोः (उ)। लक्ष्मीः········लाञ्छनाद्वा-निरु. ४,९,१।

ग—लाञ्छनैः-गोउ. ५३। लाञ्छनः-कात्या. श्रौ. २०,१,३३।
घ—लञ्छति-धम्मपद (A) १,३५।
ङ—√लंछ (सक)=छेदने, (२) कलङ्कितत्वे-दसनि. ८,१४।

+√लाज् (लाजि) १/२३७ शX — भर्जने, च=भर्त्सने (प)। द्रष्ट.√लाज् १/२३६। क्षी-शा-हे। भर्त्सने, च=भर्जने—मै-सा। भर्त्सने—च-काकृ-कात। भर्जने—जै। भर्त्सने भर्गे—वो।

√लिख् (लिख) ६/८५ श — अक्षरविन्यासे (प) क्षी-मै-सा-जै-शा-हे। लेखने—च-कात-वो। — √रिख् (रिख) १/ गत्यर्थः (प) सा। √लिख् १/३८ j गतौ (प) काकृ।
(काकृ—√खल् [खल]) काकृ ? त्रुटितो धातुः।

क—राइ=विलेखने, छेदने। विस्तारः—ः राइक् (ह्)। लैति.-रिक्स=कलहः, संख्यम्। पु. उ. ज. रीग। म. उ. ज. रीहे=रेखा (लेखा)-वा. पॉकर्नीः।
ग—अनुपरिलिखति-मै. ३,७,७। लिखति—शत्रा. २,६,१,१२।
घ—लिखति-मज्झिम. १,१२७।
ङ—√लिह (सक)=(१) अक्षरविन्यासे, (२) रेखायाम्। प्रयो.-लिहावेइ, लिहावंति-कुप्र. ३४८; सिरि. १२७८। कर्मणि-लिक्खइ-उव.।
ङ—√लिखाप (सक)-प्रयो.-पि.।
छ—महाराष्ट्रि.-√लिहणें=लेखने।

+√लिङ्ग् (लिङ्ग) १/१५४ शX — गत्यर्थः (प) क्षी-मै-सा-च-कात। गतौ-जै-काकृ-शा-हे-वो। — √इङ्ग् (इगि) १/ गत्यर्थः (प)। √रिङ्ग् (रिगि) १/ गत्यर्थः (प)। √लिङ्ग् १/४१२ kk गतौ (आ) काकृ।

क—(लाइग्-), लीग्=आकृतिः, प्रकारः। सदृशम्।

ख—अवे. ह्मो-इरिङ्ग=कृत्तिकानक्षत्रम्। चारूणां सप्तवस्तूनां निकरः-वा. पॉकर्नीः।

ग—लिङ्गम्-शब्रा. १४, ७, २, ८; गोब्रा. १, १, २४। आलिङ्ग्य–मभार. १२, ६०८९।

ङ—√लिङ्ग (सक)=(१) ज्ञाने, (२) गतौ, (३) आलिङ्गने। कर्मणि-लिंगिज्जइ-संबोध. ५१।

√लिप् (लिप) ६/१५० जै×,श	उपदेहे (उ) क्षी-मै-सा-च-काकृ-कात-शा-हे। लेपे—वो।	√रिप् (रिपि) ६/ गतौ (प) काकृ-कात। √लेप् (लेपृ) १/ गतौ (आ)।

क—लाइप्=लेपे-वा. पॉकर्नीः।

ग—नि लिम्पामि-अ.वे. ११,१०,१३। अलिम्पन्–तैब्रा. २,१,१,१। लिम्पन्ति-गी. ४, १४।

घ—लिम्पति–थेरगाथा २, ३८८।

छ—√लीपना, √लेपना (<लेपनम्)=लेपे।

+√लिश् (लिश) ४/६६ श	अल्पीभावे (आ) क्षी-मै-सा-च-काकृ-कात-शा।	√रिश् (रिश) ६/ हिंसायाम् (प)। √लिट् (लिट) कण्ड्वा.-अल्पार्थे कुत्सायां च (प)।

ग-लेशेन वचनम्-ऋ. प्रातिशा. १४,५। सर्वे स्पर्शा लेशेन……वक्तव्याः-छान्दो. २,२२,५। एतद् वै लेशमात्रेण कथितं ते…—मभार. १३, ५५२९।

√लिश् (लिश) ६/१४० श×	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो। दारणे—ह्वि.।	√लिख् (लिख) ६/ अक्षर-विन्यासे (प)।

क—राइ-विलेखने, छेदने।-राइश्-(संस्कृते)-वा. पॉकर्नीः।

ग—अलिशन्त–मै. १,८,४; काठ. ६,५; क. ४,४।

√लिह् (लिह) २/६ आस्वादने (उ)
श
क्षी-मै-सा-च-जै-काकृ
कात-शा-हे।
स्वादे—वो।

√रिह् (रिह) ६/कत्थनयुद्ध-हिंसादानेषु (प)।

क—लाइघु् =आस्वादे, लेहने–वा. पॉकर्नी:।

श—अवालेट्–मै. ३,१०,६। लेहे–पै. १३,९,७। लिहानाः–वरदोत्तरतापिन्यु. ३,२७; जिह्वया लिहती मुखम्–वा. रा. २,६६,२८। नो मेऽनिमिषो लेढि–भा. पु. ३,२५,३८।

घ—लेहति–जातक. २,४४।

ङ—√लिह (सक)=अवलेहने। लिहइ–कुमा.। वकृ–लिहंत-भत्त. १४२।

√ली (लीङ्) ४/३१ श्लेषणे (आ)
श
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
श्लिषि—वो।

क—लाइ=मसृणमृत्पूर्णम् (:), स्निग्धम् (:); मसृणम् (:)–वा. पॉकर्नी:।

ग—रात्र्यागमे प्रलीयन्ते–गी. ८,१८ = तिरोभवन्ति (म. व्या.); प्रलयं यान्ति (श्री. व्या.)। कालः सूक्ष्मामपि कलां न लीयते–सुश्रु. १८,२० ?

+√ली ९/३१ श्लेषणे (प)
श
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
श्लिषि—वो।

√ल्पी ९/२७ श्लेषणे (प)
कात।
√ल्पी ९/२१ श्लेषणे (प) हे।
√ल्पी ९/श्लिषि–वो।

√लुञ्च् (लुञ्च)१/१८४ अपनयने (प)
च×,श
क्षी-मै-सा-जै-काकृ-
कात-शा-हे-वो।

√लुञ्च् (लुञ्चु) १/१८५ केचित्। तदनार्षम्—सा।
क्षी-मै-श-जै-काकृ-कात अपनयने—च।
शा-हे-वो× अनुपयुक्तापासने—क्षी।
अपनयने=

क—रॉइ=अपनयने, घर्षणे । विस्तारः-रॉइक्—वा. पॉकर्नीः ।

ग—लुलुञ्चुः-वा. रा. ६,३७,५०; मभार. ९,१६३५ । श्मश्रूणि भूगोर्लुलुञ्चे-भा. पु. ४,५,१९ ।

घ—लुञ्चति-जातक १,२४४ ।

च—√लुंच (सक)=केशोत्पाटने, (२) अपनयने । लुंचइ-भवि. ।

छ—√लोंचना=केशोत्पाटने-बुं. ख. ।

+√लुट् (लुट) १/३१० श×	विलोटने (प) क्षी-च-कात-शा-हे । 'विलोडने'इति दुर्गः—क्षी क्षी-मै-सा-जै-काकृ । विलोटविलोडयोः--वो ।	√लुट् (लुट) ४/विलोडने (प) । √लुट् (लुट) ६/विलोडने (प) । √रुट् (रुट) १/प्रतीघाते (प) । √रुठ् (रुठ) १/प्रतीघाते (प) । √लुल् (लुल) १/विलोडने (प) सा । √लुड् (लुड) १/३१० विलोडने (प) ।

ङ—√लोट्ट (अक)=संवेशने, (२) प्रवृत्तौ । लोट्टइ-सूअ. १,१५,१४ ।

छ—√लोटना ।

+√लुट् (लुट) १/७३८ श-कात×	प्रतीघाते (आ) इत्येके-क्षी । क्षी-मै-सा-च-हे प्रतिघाते—जै-काकृ-शा । दीप्तिप्रीतहत्योः—वो ।	पूर्ववत् । लोटते—निघ.२/१४=गतिकर्मा ।
+√लुट् (लुट) ४/१०९ श	विलोटने (प) क्षी-च-कात-शा-हे विलोडने—मै-सा-जै-काकृ । विलोटविलोडयोः-वो ।	√लुड् (लुड) ४/मन्थे (प) वो । शेषः पूर्ववत् ।
+√लुट् (लुट) ६/८७१ मै-श-जै-काकृ-शा-हे-वो×	विलोडने (प) इति दुर्गः-क्षी क्षी । संश्लेषणे--सा-च-कात ।	पूर्ववत् ।

ग—सर्वत्रैव लुटत्सु रत्ननिचयैः–अमे. ओ. सो. जर्न. (तत्र हस्तलेखे) ७,७, २० श्लो.।

घ—लुटति–मिलिन्दपञ्ह २५९ (कर्मणि ?)=विलोडने।

छ—√लुटना (कर्मणि)।

+√लुठ् (लुठ) १/३३५ उपघाते (प) इत्यपि द्रौर्गाः—क्षी
शX जै ?
क्षी-मै-सा-च-काकृ-कात-शा-हे।
विलोडने—जै ?
रादिवत् (=उपघाते)–वो।

√उठ् (उठ) १/उपघाते (प)।
√लुट् (लुट) १/प्रतीघाते (आ)।
√लुठ् (लुठ) १/७४० प्रतीघाते (आ)।
लोठते–निघ. २/१४= गतिकर्मा।

+√लुठ् (लुठ) १/७४० प्रतीघाते (आ) द्युतादिः।
श-चX
क्षी-मै-सा-कात-हे-वो।
प्रतिघाते—जै-काकृ-शा।
रादिवत् (=प्रतीघाते)–वो।

पूर्ववत्।

लुठतीति लक्ष्यदर्शनात् तुदादौ पाठ्यः—क्षी।

√लुठ् (लुठ) ६/८७a संश्लेषणे (प) इत्येके–क्षी
सा-श-च-जै-कात-शाX
क्षी-मै-काकृ-हे।
लोठे—वो।

√द्रष्ट. √लुट् १/३१०।
√लुठ् १/३३५।

ग—लुठतु–महो. ३,२८; कुण्डिको. २४; मां विषाणाग्रेण लुठति–(=संघट्टयति)–भा. पु. ५,८,१८। लुठन्–कथासरि. ७१,५५।

ङ—√लुढ (अक)=लुण्ठने, (श्लेषणे), संवेशने। वकृ–लुढमाण–स. २५४।

ङ—√लुल (अक)=लुण्ठने, श्लेषणे, संवेशने। लुलइ–पिंग.।

ङ—√रुल (अक)=लुण्ठने, श्लेषणे, संवेशने। वकृ–रुलंत—पण्ह. १,३–पत्र. ४५; धर्मवि. ८०।

छ—√लुठना* = भूमिश्लेषणे।

छ—√लुढ़ना * † = स्खलने, भूपाते।

√लुड् (लुड) १/३१० विलोटने (प) इति द्रमिडाः–क्षी।
मै-श-च-जै-काकृ-कात-शा-हेX
क्षी।

<√लुट् (लुट) विलोटने (प)।
√लुल् (लुल) १/३११

	विलोडने—सा ।	विलोडने (प) सा ।
	मन्थे—वो ।	द्रष्ट. √ लुठ् ६/८७ a ।

ग—मृगयूथलोडिता (सरित्)-वा. रा. २,९५,१८; काकेनालोडितां ताम्—२,१०५,३९, लोडयामास दुष्यन्तः-मभार. १,२८३३; बल्लवा लोडयन्ति-शिशु. ११,८ ।

छ—√ लोरना = विलोडने-बुं. ख. ।

+√ लुड् (लुड) ६/१०१ क्षी, श ?-जै-काकृ-कात×	संश्लेषणे (प) इत्येके-मै मै-सा-शा-हे । विलसने—च । संवृत्तौ श्लेषे—वो ।	<√ लुठ् (लुठ) संश्लेषणे (प) । द्रष्ट. √ लुठ् ६/८७ a ।

छ—√ लुड़कना = भूपाते, स्खलने । द्रष्ट. √ लुठ् ६/८७a ।

+√ लुण्ट् (लुटि) १/३२५ श-शा×	स्तेये (प) क्षी-मै-सा--च-जै-काकृ-कात-हे । हृतौ--वो ।	√ रुण्ट् (रुटि) १/ स्तेये (प) । √ रुण्ठ् (रुठि) १/ स्तेये (प) ।

ग—तिलान् विलुण्ट्य-पञ्चत. १२३,१३; लुण्टाक०—पा. अ. ३/२/१५५ ।
ङ—√ लुंट (सक) = स्तेये । लुंटंति-सुपा. ३५२ ।
ङ—√ लूड (सक) = स्तेये । लूडइ, लूडेइ-धर्मवि. ८०; संवेग. २६ ।
छ—√ लूटना = बलादपहरणे ।

√ लुण्ठ् (लुठि) १/३२५ मै-श-च-जै-काकृ-कात-शा-हे×	स्तेये (प) इत्येके-क्षी क्षी-सा । चौर्ये—वो ।	<√ लुण्ट् (लुटि) स्तेये (प) । √ रुण्ट् (रुटि) १/ स्तेये (प) । √ रुण्ठ् (रुठि) १/ स्तेये (प) ।

क—उत्तरधातुवत् ।

ग—द्विषां लुण्ठयता यशः-राजत. ४,१२० । लुण्ठयामासतुः कृत्स्नं पुरम्—कथासरि. ११४,११९ (स्वार्थे णिच्) । विलोडनार्थकोऽप्ययम्—लुण्ठिता क्रीडता तेन नर्मदा-हरिवंश. १८७० । पीडिताः पुनरन्योन्यं लुण्ठन्तो रणमूर्धनि-मभार. ६,१८८२ । लुण्ठाकः-कलाविलासे १,३ = चौरः । लुण्ठतीति ह्वि. । मयैतन्नोपलब्धम् ।

+√लुण्ठ् (लुठि) १/३४३ गतौ (प) √रुण्ठ् (रुठि) १/ गतौ (प)।
शX क्षी-मै-सा-च-जै- √रुण्ठ् (रुठि) १/ स्तेये (प)।
काकृ-कात-शा-हे-वो। लोठते–निघ.२/१४=गतिकर्मा।
क—ऽउएल्=दारणे, विलेखने, घासभक्षणे, स्पर्शे–वा. पॉकर्नीः।

+√लुण्ठ् (लुठि) १/३४५ आलस्ये। गतिप्रतिघातेऽपि √रुण्ठ् (रुठि)१/ आलस्ये
क्षी-श-काकृX वृत्तिरस्य—मै। गतिप्रतिघाते च (प)।
आलस्ये प्रतिघाते च—सा।
आलस्ये—च-जै-शा।
गतिप्रतिघाते आलस्ये च—
कात-हे।
गत्यालस्यस्तेयखोटे—वो।
वस्तुतो √लुण्ठ् (लुठि) धातुरेकोऽर्थभेदात् त्रैविध्यं प्रापितः।

+√लुण्ड् (लुडि) १/३२४ स्तेये (प) शाकटायनः <√लुण्ठ् (लुठि) स्तेये
क्षी-मै-श-च-जै-काकृ- पपाठ—सा- (प)।
कात-हे-वोX सा-शा। √लुण्ड् (लुडि) १०/ चौर्ये
(प) वो।
ग—कक्षातलुण्डीकृतं पटमाकृष्य–मृच्छक० ३४,११। मेषलोमलुण्डिकया घृष्ट्रा—भैषज्यरत्नाव.—लुण्डिका=एकत्रवेष्टितमेषलोमादिः।

+√लुन्थ् (लुथि) १/४३ हिंसासंक्लेशयोः (प)
शX क्षी-जै-काकृ-कात-शा-हे।
हिंसासंक्लेशनयोः—मै-सा।
हिंसायाम्—च।
कुन्थे (=वधे क्लेशे च)—वो।

+√लुप् (लुप) ४/१२४ विमोहने (प) √लुभ् (लुभ) ४/१२५
श क्ष-मै-सा-च-जै-काकृ- गार्द्ध्ये (प)।
कात-शा-हे। √रुप् (रुप) ४/विमोहने
युपि (=विमोहे)—वो (प)।
ग—(लुप्यमान०–मैत्र्युप. ३,२ [६,३०])।

√लुप् (लुप्लृ) ६/१४८ छेदने (उ) √लू (लूञ्) ९/११
जैX,श क्षी-मै-सा-च-काकृ-कात- छेदने (उ)।
शा-हे।
छेदे—वो।

क—रॉउ्प्=भङ्गे, छेदे–वा. पॉकर्नीः ।

ग—अवलुम्पन्ति–तै. ३,२,२,१ । ह्रस्वं लुम्पन्ति–ऋ. प्राति. १४,१३ । लुम्पति–भा. पु. ७,३,२७; शार्ङ्ग सं. १,४,२१ ।

ङ—√ लुंप (सक)=(१) लोपे, (२) उत्पीडने । लुंपइ, लुंपह्रा–सूअ. १,३,४,७ ।

छ—√ लुपना *=निलयने ।

छ—√ लोपना * (अक)=(१) नाशे, (२) निलयने ।

√ लुभ् (लुभ) ४/१२५ श — गार्द्ध्ये (प) । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । — √ लुह् १/ गार्द्ध्ये (प) वो । √ लुभ् (लुभ) ६/२६ विमोहने (प) ।

क—लॉइभ्=इच्छायाम्, याचने–वा. पॉकर्नीः ।

ग—लुभ्यति–ऐब्रा. २,३७; मभार. १३,३०२४ ।

घ—लुब्भति—इतिवुत्तक ८४ ।

ङ—√ लुभ, √ लुब्भ }=(१) लोभे, (२) आसक्तौ । लुब्भइ–कुमा. ।

छ—√ लुहना *=लोभने, गार्द्ध्ये ।

+√ लुभ् (लुभ) ६/२६ श — विमोहने (प) । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । — प्रतिलोभयन्ती–निरु. ९,३३ ।

ग—[कथमिह परिलोभसे धनेन–मृच्छकटि.–भौवादिकः] । आकृतिर्लोभनीया–रघु. ६,५८=आकर्षणीया—(सञ्जी.) ।

छ—√ लोभना*†=मोहने ।

+√ लुम्ब् (लुबि) १/४२७ अर्दने (प) मै । क्षी-श-च-जै-शा× मै-सा-काकृ-कात-हे-वो । मर्दने—काकृ ।

ग—लुम्बिनी–ललित. (कालिकातासंस्क०) ८९,१३; ९०,७; लुम्बनीय०–९२,१३ ।

छ—√ लूमना=लम्बने, दोलने, प्रेङ्खणे (<लम्बनम् इति व्युत्पत्तिर्यद्यप्यर्थसाम्यं धत्ते तथापि नावहति ध्वनिसादृश्यम् इति मयोपेक्षिता । अर्दनं नाम पीडनम् त्य।। ठ:।। र्थः शक्यते वक्तुम् ।

√लुल (लुल) १/३११ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×

विलोडने (प) लान्तोऽपि दृश्यते—सा।

<√लुड् (लुड) विलोडने (प)।

√लुल विमर्दने-सौ. धा.-वो।

√लुट् (लुट) १/ विलोडने (प)।

√लुठ् (लुठ) १/ विलोडने (प)।

ग—लुलिताकुल०—वा. रा. ७,२६,४२; शोकाश्रुलुलिनानना—२,६५,१८; लोलभुज०—शिशु. ३,७२।

ङ—√लोल (सक)=विलोडने। लोलइ—पिंड. ४२२; पिंग., वक्र—लोलंत-कप्प.।

छ—√लोलना * (<लोलनम्)=दोलने।

√लू (लूञ्) ९/११ जै×,श

छेदने (उ)। क्षी-मै-सा-च-काकृ-कात-शा-हे। छिदि—वो।

क—लेउ=छेदने—वा. पॉकर्नीः।

ग—लुनन्तः—शब्रा. १,६,१,३; जैब्रा. १९०। लुनोति—तैब्रा. ३,२,२६।

घ—लुनाति—मिलिन्दपञ्ह ३३।

ङ—√लुण (सक)=छेदने। लुणेप्पि—पि. ५८८।

छ—√लुनना, √लूनना *† =छेदने।

छ—√लुनवौ=लवने—बुं. ख.।

+√लूष् (लूष) १/६६९ मै-श-च-काकृ-कात×

स्तेये (प) इति दुर्गः—क्षी। क्षी-जै-शा-हे-वो। भूषायामिति सुधाकरः—सा। वधे स्तेये च—वो।

√लू (लूञ्) ९/११ छेदने (उ)।

√लूष् (लूष) १०/ हिंसायाम् (प)।

√रूष् (रूष) १/ भूषायाम् (प) सा।

ङ—√लूस (सक) = (१) वधे, (२) पीडने, (३) दूषणे, (४) स्तेये, (५) विनाशे, (६) अनादरे, (७) भङ्गे। लूसंति-सूअ. १,३,१,१४।

+√लेण् (लेणृ) १/४५४	गतिप्रेरणश्लेषणेषु (प)। इति क्वचित् पठ्यते—सा।	√पैण् (पैणृ) १/ गतिप्रेरणश्लेषणेषु (प)।

ग—√उत्ससर्ज बृहल्लेण्डम्-ब्र. वै. पु. श्रीकृष्णजन्मखण्डे धेनुकासुरवधे २२ अध्यायः। लेण्डम् = गूथम्।

+√लेप् (लेपृ) १/३६९ मै-श-च-जै-काकृ-कात-शा×	गतौ (आ) क्षी-सा-हे। गमने—वो।	√रेप् (रेपृ) १/ गतौ (आ)। √ग्लेप् (ग्लेपृ) च = कम्पने, गतौ (आ)।
√लोक् (लोकृ) १/७३ श	दर्शने (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे। लोचने—जै। ईक्षे—वो।	रोचतेर्ज्वलतिकर्मणः-निरु. २, २०,१। रोचते-निघ. १/१६ = ज्वलतिकर्मा। अति रोचसे (= दृश्यसे-दुर्गाचा.) निरु. ३,११,२। अति रोचसे = सन्दृश्यस इति-निरु. ३,११,२।

क—लॉइक् = दीप्तौ, दर्शने-वा. पॉकर्नीः।

ग—लोकेते-ऐब्रा. ४,१५।

ङ—√लोअ (सक) = दर्शने। वकृ—लोअअंत-नाट. कवकृ—लुक्कमाण-उप. १४२ टी.।

छ—√लौकना
छ—√लौंकना*† } (< लोकनम्)-(अक) = दर्शने, (२) दीप्तौ।

√लोच् (लोचृ) १/१६२ श	दर्शने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। ईक्षे—वो।	√लोक् (लोकृ) १/७३ दर्शने (आ)। शेषः पूर्ववज्ज्ञेयः। √लोच् (लोचृ) १०/ भासार्थः (प)।

ग—आलोचयते-मभार. १२,७४१६।

छ—√लोचना †=(१)प्रकाशने, (२) रुचौ।

+√लोड् (लोडृ) १/३५८ क्षी-श-च-कात×	उन्मादने (प) मै। मै। उन्मादे—सा-जै-काकृ-शा-हे-वो।	√लड् (लड) १/ उन्मन्थने (प)। √रोड् (रोडृ) १/ उन्मादने (प) मै। √लोट् (लोटृ) १/१५४ उन्मादने (प) कात। √लोड् (लोडृ) १/ उन्मादे (प)। √लुड् (लुड) १/३१० विलोटने (प)।
+√लोष्ट् (लोष्ट) १/२५६ श×	संघाते (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। संहतौ—वो।	√श्लोण् (श्लोणृ) १/ संघाते (आ)। श्लोण् वर्णविपर्ययेण—लोश्ण् इति (णकारस्य टकारे) √लोष्ट् इति वागीशः।

ग—लोष्टो विध्वंसते-शत्रा. १४,४,१,८।

+√लौड् (लौडृ) १/३५२ मै-सा-श-जै-काकृ कात-शा×	उन्मादे (प) क्षी-च-हे-वो।	√रोड् (रोडृ) १/ उन्मादे (प) मै। √लोड् (लोडृ) १/ उन्मादने (प) मै। √लोट् १/१५४ उन्मादने (प) कात।
+√ल्वी ९/३२ मै-सा-श-च-जै-काकृ-कात×	गतौ (प) क्षी-शा-हे। गत्याम्—वो।	√ल्पी ९/२७ श्लेषणे (प) कात। √ल्पी ९/२१ श्लेषणे (प) हे। √ल्पी ९/ श्लिषि—वो।
+√वंह् (वहि) १/२४७ श× (क्षी-मै-सा-च-	वृद्धौ (आ) जै जै-काकृ-कात-वो।	√वंह् (वहि) १०/ त्विषि (प) वो।

शा-हे-√ बंहू[बहि])
अपाणिनीयो धातुः ।
ग—वंहयन्ते-तांब्रा. २३,१६,५ ।

√वक्ष् (वक्ष) १/६५५	संघाते (प)	√वक्ष् १/५१९ पालने (आ)
श×	क्षी-सा-हे ।	काकृ ।
	रोषे—मै-सा-च-जै-	√मक्ष् (मक्ष) १/ रोषे
	काकृ-कात-शा-हे ।	(प); संघाते रोषे च—वो।
	रोषसंहत्योः—वो ।	√उक्ष् (उक्ष) १/सेचने (प) ।
	वृद्धौ—ह्नि. ।	···वङ्क्षणेषु—सुश्रु.
		३३८,१९ ।

ग—यन्तु वक्षणीः-ऋ. १०,६४,९; वक्षणानि यज्ञैः-ऋ. ६,२३,६; वक्षयम्-१०,४९,८ ।

+√वख (वख) १/१३०	गत्यर्थः (प)	√वङ्ख् (वखि) १/ गत्यर्थः
श×	क्षी-मै-सा-च-कात ।	(प) ।
	गतौ—जै-काकृ-शा-हे ।	√भज् (भज) १/ सेवा-
	सृपि—वो ।	याम् (उ) ।

छ—√ बगना*† (<वखनम्)=भ्रमणे—"खोरिन बगे रहैं"-देवः ।
छ—√ बागना*‡ (<वखनम्)=चलने, भ्रमणे—"देश देश हम बागिया" —कबीरदासः ।

√वङ्क् (वकि) १/८५	कौटिल्ये (आ)	√वञ्च् (वन्चु) १/१८६
श×	क्षी-मै-सा-च-जै-काकृ-	गत्यर्थः (प) ।
	कात-शा-हे-वो	√वेङ्क् १/४१२g गतौ (आ)
√वञ्च्	कुटिलायां गतौ—ह्नि. ।	काकृ ।

ग—वङ्कू, वङ्कु०—ऋ. १,५१,११; यया वणिग्वङ्कुरापा पुरीषम्-५,४५,६ ।
ङ—वंकण (<वङ्कनम्)=कौटिल्ये-ठा. २,१-पत्र. ४० ।
ङ—वंक = अरालम्, जिह्मम्-कुमा.; सुपा. १७२; पि. ७४ ।
छ—√ बाँकना† =कौटिल्ये । बंगा (<वङ्कः)=कुटिलः (मू), मूर्खः, उद्दण्डः ।

√वङ्क् वकि १/९४	गत्यर्थः (आ)	√विङ्क् १/४१२ c.dd गतौ
क्षी-श-च-जै-काकृ-शा×	मै-सा-कात ।	(आ) काकृ ।
	गतौ—हे-वो ।	शेषः पूर्ववत् ।
√वञ्च्	कुटिलायां गतौ—ह्नि. ।	

ग—पूर्वस्यैव प्रपञ्चः ।

+√ वङ्ख् (वखि) १/१३१ गत्यर्थः (प)
शा-च-जै-कात-शा × क्षी-मै-सा ।
गतौ—काकृ ।
हे ?
सृपि—वो ।

√ वख् (वख) १/१३० गत्यर्थः (प) ।
√ वङ्क् (वकि) १/९४ गत्यर्थः (प) ।
√ विङ्क् १/४१२ c.dd गतौ (आ) काकृ ।
√ वेङ्क् १/४१२g गतौ (आ) काकृ ।

छ—बीख ↑ = दीर्घविक्रमः, दीर्घपादन्यासः (—डग-हि.)—तु. √ विङ्क् गतौ-काकृ ।

+√ वङ्ग् (वगि) १/१४६ गत्यर्थः (प)
श × क्षी-मै-सा-च-कात ।
गतौ—जै-काकृ-शा-हे ।
खञ्जे—वो ।

√ त्वङ्ग् (त्वगि) १/ गत्यर्थः (प) ।
√ मङ्ग् (मगि) १/ गत्यर्थः (प) ।
√ वङ्क् (वकि) १/ गत्यर्थः (प) ।

क—उअ-न्-ग् = न्युब्जम्, वेष्टितम्, प्रत्यावर्तितम् । अल्बेनियन्-वंक, वंगु = नेमिः (चक्रवलयम्)—वा. पॉकर्नीः ।

ग—वङ्ग०-वा. रा. ४,४०,२५ । वङ्ग० — मभार. १,१०४,४७-५१ = दीर्घतमस औरसो वलेः क्षेत्रजश्च ।

घ—वग्गति-जातक २,३३५ ।

छ—बँगरी (< वङ्गुरिः) = आभूषणभेदः-बुं.ख. ।

छ—बाँगा = अपृथक्कृतबीजः पिचुः (दे.) ।

छ—बाँगर = उपरि वरूथबद्धो वेणुदण्डः ।

छ—बैंगन् (< वङ्गनः-शब्दरत्नावल्याम्) = भाण्टाकी ।

+√ वङ्घ् (वघि) १/१०६ गत्याक्षेपे (आ)
श × क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
अध्यर्थके (= गते निन्दा-

√ वङ्क् (वकि) १/ गत्यर्थः (आ)
√ वङ्ख् १/ (वखि) गत्यर्थः (प) ।

रम्भजवेषु)—वो।

√वख् (वख) १/ गत्यर्थः (प)।

√वङ्ग् (वगि) १/ गत्यर्थः (प)।

गत्याक्षेपः = वेगगतिः, गमनारम्भो वा—क्षी।

ग—वङ्ग०—अथर्व. कौशि. सू. ७ = वृक्ष०, दण्ड०—इत्यादि।

√वच् (वच) २/५२ श — भाषणे (प) क्षी-मै-च-शा-हे। परिभाषणे—सा-जै-काकृ-कात। वाचि—वो।

√ब्रू (ब्रूञ्) २/ व्यक्तायां वाचि (उ)।
√वल्क् (वल्क) १०/ परिभाषणे (प)।
वोचे (=आह्वयामि—दुर्गाचा.)—निरु. ५,७,१।

पारायणिकैर्नाधीतोऽयम्—क्षी।

क—उऐकु = वचने-वा. पॉकर्नीः।

ग—वक्ति-नाप. ३,६३; शि. ७,४। वच्मि-त्रिता. २,४८; करु. ४२; गणपत्यु. ३; वरा. १,९।

ङ—√वाच (सक) = (१) वचने, (२) वाचने—नाट-मालवि. ६१।

ङ—√वाए (सक) = (१) वचने, (२) वाचने। वाएइ-भग.; कप्प.।

छ—√वंचना
छ—√वाँचना } (< वचनम्) = वचने, पठने।

छ—√बकना *‡(< वचनम्) = प्रलापे।

√वज् (वज) १/२५० श — गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। दार्ढ्ये—ह्वि।

√व्रज् (व्रज) १/२५१ गतौ (प)।
√वज् (वज) १०/ मार्गसंस्कार-गत्योः (प)।

ग—वाजमर्वत्सु-ऋ. ५,८५,२ = बलम्। वाजेभिः-ऋ. ४,२२,३ = अन्नैः (साय.)। वाचस्पतिर्वाजम्-वा. सं. ९,१। विचित्रवाजैर्निशितैः शिलीमुखैः-भा. पु. १०,५९,१६ = शरपक्षैः।

√वञ्च् (वन्चु) १/१८६ श ? — गत्यर्थः (प) क्षी-मै-सा-च।

वञ्चति-निघ. २/१४=गतिकर्मा।

गतौ—जै-काकृ-कात-शा-हे।
गत्याम्—वो।
कुटिलायां गतौ—ह्वि.।

क—उ्अ-न्-ग् = वेष्टितम्, कुटिलम्, नतम्, प्रत्यावर्तितम्-वा. पॉकर्नीः।
क—उ्आइक्-कौटिल्ये-वा. पॉकर्नीः।
ग—वञ्चति-वा. सं. २३,२२। वञ्चति, वञ्चन्ति-शब्रा. १३,२,९,६।
घ—वञ्चति-जातक १,२१४ = गतौ।
ङ—√वंच (सक) = प्रतारणे। वंचइ-महा.।

+√वट् (वट) १/२९७ श	वेष्टने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। वेष्टने—वो।	√वट् (वट) १०/ ग्रन्थे (प)। √वेष्ट् (वेष्ट) १/ वेष्टने (आ)। √वट् (वट) १/१०७ अवयवे (प) काकृ।

ग—वटः-वा. रा. २,५२,९६; हरिवं. ३११४ (वटति = वेष्टयति मूलेन)। वटारका०-मभार. १२,३२९,३९ = रज्जुः। यज्ञवाटं गताः-वा. रा. १,१३,४१।
छ—√वटना (<वटनम्) = वेष्टने, रज्जुनिर्मितौ।

+√वट् (वट) १/७७२ श×(शा√बट् [बट])	परिभाषणे (प) मित्। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। उक्तौ—वो।	√भट् (भट) १/ परिभाषणे (प)। √भल (भल) १०/ आभण्डने (आ)। √भल (भल) १/ परिभाषणहिंसादानेषु (आ)। √वण् (वण) १/४३९ शब्दार्थः (प)।
+√वठ् (वठ) १/३२९ श×	स्थौल्ये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√वढ् आरोहणे—सौ. धा.—त्रो।
+√वण् (वण) १/४३९ श×	शब्दार्थः (प) क्षी-मै-सा-च।	√भण् (भण) १/ शब्दार्थः (प)।

शब्दे—जै-काकृ-कात-शा-हे । √व्रण् (व्रण) १/ शब्दार्थः (प)।

रुति—वो ।

ग—वाणी-मा. पु. ४१,४;=वचनम् । वाणिनीनाम्-रघु.६,७५ ।

छ—वेड़िनी (<वाणिनी)=नर्तकी गायिका च-बुं. ख. ।

√वण्ट् (वटि) १/३६८; ३२३ विभाजने (प) √वण्ड् (वडि) १०/ विभाजने (प)।

सा-श-वो× क्षी-मै-च-काकृ-कात-हे ।

(जै-शा-√वण्ड् [वडि]) विभाजने—जै-शा ।

ग—ज्ञातिभिर्वण्ट्यते नैव विद्यारत्नं महाधनम्-इन्दिशे स्प्रूशे ९८५ ।

छ—√बाँटना=विभागे ।

छ—√बँटना (कर्मणि)=विभागे ।

+√वण्ठ् (वठि) १/२५९ एकचर्यायाम् (आ)

श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।

एकचरे—वो ।

एकचर्यायाम्=एकस्य चर्या=सहायत्वेनागमनम्-क्षी ।

ग—वण्ठरण्डाकल्पः-मभाष्ये ३,३,२०-वण्ठः=मृतभार्यः-नागेशभट्टः ।

√वण्ड् (वडि) १/२६८ विभाजने (आ) >√वण्ट् (वटि) विभाजने (प) इत्येके—क्षी ।

श क्षी-सा ।

'वेष्टने' इति नन्दी-क्षी । √मण्ड् (मडि) १/ च= विभाजने (आ) ।

क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।

विभागे वेष्टे—वो । √वण्ड् (वडि) १०/ विभाजने (प)

विभाजनम्= भागीकरणम्, चर्माभावश्च-क्षी । चर्माभावो नाम शिपिविष्टता (द्विनग्नता)-वागीशः ।

छ—बाँड़ा (<वण्डः)=पुच्छादिहीनः ।

छ—वंडा (<वण्डः)=धान्यरक्षणार्थं कृतः पृथिव्या विभागः-बुं. ख. ।

+√वद् (वद) १/९९३ श — व्यक्तायां वाचि (प) क्षी-मै-सा-जै,-काकृ (उ),-कात-शा-हे। वचने—च। वाचि—वो। — √वद् (वद) १०/ संदेशने (प)। अपि······वतेम-ऋ. [७, ३,१०] गतिसंभक्त्यात्मक-स्यार्थद्वयस्यापि वाचकः-वै. प. को.।

क—अउ-, अऑइद्=वचने-जू. पॉकर्नीः।

क—उ्एद् = वचने-वा. पॉकर्नीः।

ग—अनुवदति-ऋ. २,१३,३; वदामि-ऋ. १,१०५,७। वदति-शब्रा. १,१,१,१; काब्रा. १,२,२,१४; तैआ. १,२३,१।

घ—वदति-अङ्गुत्तर. ४,७९।

ङ—√वद (सक)=कथने। वदसि-उवा.; भग.; कप्प.।

ङ—[√वय (सक) = कथने। वयसि-कस.; कप्प.] (<√वच्?)।

ङ—√वज्ज (अक) = वादने। वज्जइ-सुपा. ३३४।

छ—वदना (<वदनम्)=(१) कथने, वर्णने, (२) स्वीकरणे, (३) निश्चये।

छ—बजना (<वदनम्)=(१) शब्दे, (२) आहतौ, (३) शस्त्रचलने,(४) हठे, (५) ख्यातौ।

√वध् (वध) १/ क्षी-मै-सा-श-च-जै-काकृ-कात-शा-हे× — हतौ (प) वो। — √वध् (बध) १/ बन्धने (आ)।

अपाणिनीयो धातुः।

क—उ्एध्=आहतौ, छेदने।

ख—अवे. वद=छेदने, वधे-वा. पॉकर्नीः।

ग—वधेत्-शब्रा. ५,३,५,२८। वध्यात्-तैब्रा. १,७,३,७। वध्यते-गोब्रा. २,३,९; इ. १०:१५। कैकेयीं च वधिष्यामि-वा. रा. २,९६,२६; वध्यमानौ-२,७४,२० =ताड्यमानौ (तिल.)।

घ—वधेथ-विसुद्धिमग्ग ३१४। वधिस्सति-महावंस २५,६२।

ङ—√वह (सक)=वधे। वहेइ, वहंति-उत्त. १८,३;५; स. ७२८; संबो. ४१। [तुल.-यो वाहयति सौनिकः-मनु. ४,८६ (=व्यापादयति-कुल्लूक.)] इह संस्कृते प्राकृतसंक्रान्तिः!

छ—बधना=मारणे।

√वन् (वन) १/४५१
श×

शब्दे (प)
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
संभक्तिशब्दयोः—वो ।
साफल्येन प्राप्तौ—ह्वि.

√स्वन् (स्वन) १/ शब्दे (प) ।

क—; ख—द्रष्ट. √वन् १/४५७ ।

ग—द्यौर्वना गिरयो वृक्षकेशाः-ऋ. ५,४१,११; नि वो वना जिहते-५,५७,३ । तेनास्मभ्यं वनसे रत्नमा त्वम्-ऋ. १,१४०,११ । वनाम-जैउ. २,२,१,२ । वनेः-ऐब्रा. १,३,८ ।

√वन् (वन) १/४५७
श-च×

भक्तौ (प)
क्षी ।
संभक्तौ—
मै-सा-जै-काकृ-
कात-शा-हे ।
संभक्तिशब्दयोः—वो ।
साफल्येन प्राप्तौ–ह्वि. ।
भक्तिः=भजनम्—क्षी ।

√वेन् १/२२० संभक्तौ (प)
काकृ ।
शेषः √वन्१/७९६ वत् ।
वनुष्यति-निघ. २/१२=
क्रुध्यतिकर्मा ।

क—ऊ्एन्=इच्छायाम्, प्रीतौ ।
ख—अवे. वनैति=जये, साफल्येन प्राप्तौ-वा. पॉकर्नीः ।
ग—वनाम-जैउ. २,२,१,२; वनेः-ऐब्रा. १,२५ । वनते-तैब्रा. ३,५,१०,५ ।
घ—वनति-सुत्तनिपात २४; धम्मसंगणि ३६४ ।

√वन् (वनु) १/७९६
श-च-जै-शा-हे×

च नोच्यते (प) मित्
क्षी-मै-सा-कात ।
नोपलभ्यते (चौ.
सं.)—सा ।
स्मरणे—काकृ ।
व्यापृतौ—वो ।

√वन् (वनु) ८/७ याचने (आ) ।
√वन् (वन) १/४५१ शब्दे (प) ।

ग्लास्नावनुवमाश्च१/८०३
श-जै-शा-हे-वो×

अनुपसर्गान्मित्त्वं वा—
क्षी ।

तथानुकर्षणार्थश्चकारः । यद्वा न केवलं कगे, यावद् वनु च नोच्यते, क्रियासामान्यवाचित्वात्-क्षी १/७९६ ।

ग—वनयति–अ.वे. प्रातिशा. ४,९३ ।
घ—वनयति–खुद्दकपाठ ३ ।

√वन् (वनु) ८/७ श	याचने(आ) क्षी-मै-सा-च-जै,-काकृ (उ),-कात-शा-हे । याचे—वो । साफल्येन प्राप्तौ, जये—ह्वि. ।	पूर्ववत् । वनं वनोतेः (सम्भजनार्थस्य -दुर्गाचा.) निरु. ८,३,१ । वनोति–निघ. २/६=कान्ति-कर्मा ।

क—उ्ऐन्=इच्छायाम्, प्रीतौ ।
ख—अवे.—वनओइति=जये, साफल्येन प्राप्तौ–वा. पॉकर्नीः ।
ग—वनोति—ऋ. १,१३३,७; वनुते ७,१०७,७ ।
घ—वनोति, वनुते–धम्मसंगणि (A) ३६४ ।
ङ—√वण (सक)=याचने । वणेइ–पिंड. ४४३ ।

√वन्द् (वदि) १/११ श	अभिवादनस्तुत्योः (आ) क्षी-मै-सा-काकृ-कात । अभिवादने—च । स्तुत्यभिवादनयोः—जै-शा-हे । नुत्यभिवादयोः—वो ।	√वद् (वद) १/ व्यक्तायां वाचि (प) । √मन्द् (मदि) १/ स्तुति···(आ) ।

क—उ्ऐद्=वचने । नासिक्यं संस्कृते–वा. पॉकर्नीः ।

ग—वन्दे–ऋ. १,१४७,२; अग्ने वन्दे तव श्रियम्–५,२८,४ । वन्दते–ऐब्रा. ८,२६ । वन्देत्–शि. ७,९२ ।

घ—वन्दति–सुत्तनिपात ३६६ ।
ङ—√वंद (सक)=(१) प्रणामे, (२) स्तवने । वंदइ–उव.; महा.; कप्प. ।
छ—√बंदना (सक)=प्रणामे ।

√वप् (डुवप) १/९८७ श	बीजसन्ताने (उ) क्षी-मै-सा-जै-शा-हे । गर्भाधाने—सा । बीजनिक्षेपे—च । बीजतन्तुसंताने—	√उभ् (उभ) १/ पूरणे (प) ।

काकृ-कात ।
छेदने—सा ।
मुण्डबीजोप्त्योः—वो ।

क—उ॒ऍप्=क्षेपे, विकीर्णौ ।

ख—अवे. वि-वापत्=भ्रंशे, विनाशे-वा. पॉकर्नीः ।

ग—वपन्ति-ऋ. ८,७,४; क्षां वपन्ति-६,६,४; संवत्सरे वपत (=नापितकार्यं करोति) एक एषाम्-१,१६४,४४। यत्क्षुरेण वप्ता वपसि केशश्मश्रु-अ.वे. ७,२,१७; शब्रा. ३,१,२,७ ।

घ—वपति-जातक १,१५० ।

ङ—√वव = बीजसन्ताने । ववंति-सत्त. ७२ ।

ङ—√वव=दाने । ववइ-वव १; कर्म. उप्पइ-कुप्र. ४१ ।

छ—√बोना; √बोवना; √बवना *; √बयना *, √बपना * (<वपनम्)=बीजसन्ताने ।

+√वभ्र् (वभ्र) १/५५८ गत्यर्थः (प) मै । √अभ्र् (अभ्र) १/ गत्यर्थः (प)।
(क्षी-श-हे-वो-√बभ्र् (क्षी)-मै-सा-च-कात । [बभ्र])।
(जै-√व्यभ्र् [व्यभ्र])— गतौ-(जै) काकृ-शा-(हे)। गत्याम्—(वो)।

√वम् (टुवम) १/८३३ उद्गिरणे (प)
श-जै-काकृ-कात-शा-वो× क्षी-मै-सा-च-हे ।

√वम् (टुवमु) १/८३३ इत्येके—क्षी ।
मै-श च× क्षी-सा-काकृ-कात-शा-हे ।
उद्गिरणे—जै ।
उद्गिरे—वो ।

ग्लास्नावनुवमां च १/८०३ मित्—क्षी ।
श-जै-शा-हे-वो×

ग—वमन्नित्–ऋ. १०,१०८,८। वमति–शब्रा. ५,५,४,९। वमन्तः–वा. रा. १,४५,१९।

घ—वमति–सुत्तनिपात १९८=जातक १,१४६।

ङ—√वम (सक)=वान्तौ–गउड.; विपा. १,७।

छ—√वमना*† (<वमनम्)=उद्गिरणे।

+√(वय् (वय) १/४७१ गतौ (आ)
शX
क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
गत्याम्—वो।

√पय् (पय) १/४७२ गतौ (आ)।
√वे (वेञ्) १/ तन्तुसन्ताने (उ)।
√व्रज् (व्रज) १/२५१ गतौ (प)।
√वज् (वज) १/२५० गतौ (प)।

ग—वयस्–अ.वे. ३,२१,२। वायसास्तर्कयन्ति–मृच्छकटि. १०,३।

ङ—√वय (सक)=गतौ। वयइ–सुर. १,२४८ (<√व्रज्?)।

+√वर्च् (वर्च) १/१६० दीप्तौ (आ)
शX (काक्र-कात—√चर्च् [चर्च])
क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो।

ग—सं माग्ने वर्चसा सृज–ऋ. १,२३,२४; वर्चो धा यज्ञवाहसे–ऋ. ३,८,३; वर्चः सुवीर्यम्–ऋ. ९,६६,२१–वर्चः=तेजः। वर्चस्क०—मभार. १३,२५,१९=दीप्ति०।

+√वर्फ् (वर्फ) १/४०८ गतौ (प)
मै-सा-जै-काक्र-शाX (च-√बर्फ्)
क्षी-च-कात-हे।
'हिंसार्थः'-इति कण्ठः—क्षी।
वधे गत्याम्—वो।

√वफ् १/२०४ a गतौ (प) काक्र।
√वर्ब् १/६५३ गतौ (प) जै।
√वर्ह् (वर्ह) १/ परिभाषणहिंसादानेषु (आ)।
वर्पस्–निघ. ३/७=रूपनाम।

√वर्ष् (वर्ष) १/६१३ स्नेहने (आ)
क्षी-श-च-काक्र-कात-हे-वोX
मै-सा-शा।
स्नेहे—जै।

√पर्ष् (पर्ष) १/ स्नेहने (आ)।
√वस् (वस) १०/ स्नेहच्छेदापहरणेषु (प)।
√वृष् (वृषु) १/ सेचने (प)।

ग—पुनरेवाभ्यवर्षत-वा. रा. ३,५८,३०; पर्यवर्षत-६,७५,४७। वर्षमाणा घना इव-मभार. १,५४६४। वर्षते देवः-भा. पु, ३,२९,४०।

घ—वस्सति-विनय. १,३२।

+√वर्ह् (वर्ह) १/६३३ श-च-काक्रु×(शा-हे-वो-√बर्ह्)	परिभाषणहिंसादानेषु (आ) क्षी-मै-सा। परिभाषणाच्छादनहिंसासु—जै। प्राधान्यपरिभाषणहिंसादानेषु—कात।	√वल्ह् (वल्ह) १/६४१ परिभाषणहिंसादानेषु (आ) मै। √वर्ह् (वर्ह) १०/११७ वधे (प) जै।
√वल् (वल) १/४८८ श×	संवरणे (आ) क्षी-मै-च-काक्रु-शा-हे। संवरणे संचरणे च—सा। संवृतौ—जै। चलने संवरणे च—कात। स्तृतौ—वो।	√बल् (बल)१/ प्राणने (प) ज्वलादौ। √वल् १/३७८ प्राणधान्यावरोधयोः (प) जै। √वल् १/२४२a निष्पत्तौ (प) काक्रु।
दलिवलि०-भोजसूत्रम् —क्षी१/८०३ मै-श-च-जै-काक्रु-कात-शा-वो×	मित्—क्षी।	शतवल्शो नाम वट०-भा. पु. ५,१६,१५। वल्श०-ऋ. ३,८,११; वा. सं. ५,४३।

क—उऍल्=एकतो दिशि परितो भ्रमणे, वेष्टने-वा. पॉकर्नीः।

ग—वलन्ति-महो. ५,७८ ['वलगन्ति' इति अड्या.]। तस्मिन्नेव पुनर्वलते-गीतगो. ७,४०, ववलिरे (=परिवृत्ताः-मल्लि.)-शिशु. ६,११; ६,३८। विवलति-काव्यप्र. १५४,१०।

च—√वाल (प्रयोज.)=(१) परिवर्तने, (२) प्रतिवर्तने। वालइ, वालेइ-भवि. ४,३३०।

√वल्ग् (वल्ग) १/१४२ श-काक्रु×	गत्यर्थः (प) क्षी-मै-सा-च-कात। गतौ—जै-शा-हे। व्रजे—वो। प्लुतगतौ—भट्टमल्लः।	√वल् (वल) १/ संवरणे (आ)। √वल् (वल) १/ संवरणे संचरणे च (आ) सा। √वल्क् (वल्क) १०/ परि-

भाषणे (प)। वल्गूयति-ऋ. ४,५०,७। वल्गूयति-निघ. ३/१४= अर्चतिकर्मा।

क—कण्ठ्यवर्णविस्तारः—* उअल्ग्=उत्प्लवने-वा. पॉकर्नीः।

ग—अभिवल्गन्ति-अ.वे. १२,३,२९। वल्गन्ति-मुक्तिको. २,२,४० [वलन्ति इति JC.]। वल्गते स्वाहा-वा. सं. २२,७; तै. ७,१,१३,१। वल्गते-मभार. १३,७४८। वल्गन्-भा. पु. १०,४४,११। वल्गु-वा. रा. २,२६,१०=सुन्दरम् (तिल.)।

व—वग्गति-विमानवत्थु (A) २७८;६४=प्लुतगतौ।

ङ—√वग्ग=गतौ, (२) कूर्दने, (३) बहुभाषणे, (४) अभिमानव्यञ्जके शब्दे। वग्गइ-भवि.; सण.; पि. २९६।

+√वल्भ् (वल्भ) १/३८८ श×(काकृ-√वल्ल् [वल्ल]) स्याल्लैपिकी त्रुटिः। भोजने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। मुक्तौ—वो। √वृ (वृङ्) ९/ संभक्तौ (आ)। संभक्तिः=सेवनम्-दुर्गादासः।

+√वल्ल् (वल्ल) १/४८८ श-च× संवरणे (आ) इति दुर्गः—क्षी। क्षी-मै-काकृ-शा-हे। संवरणे सञ्चरणे च—सा। संवृत्तौ—जै। चलने संवरणे च—कात। स्तृतौ—वो। <√वल् (वल) संवरणे (आ)। √वल्ल् १/४७५f गतौ(प)शा। √वल्ल् १/२४२e निष्पत्तौ (प) काकृ।

ग—प्रायेण हि नरश्रेष्ठ ! ज्येष्ठाः पितृषु वल्लभाः-वा. रा. १,६१,१८। वल्लद्विद्याधर०-कथासरि. ११०,८७। वल्लि०-मभार. १२,१८४,१३=लता०। वल्ल्यः-मनु. १,४८।

ङ—√वल्ल (अक)=सञ्चरणे, स्पन्दने—कुप्र. ८४।

√वल्ह् (वल्ह) १/६३९ श×(क्षी-सा-जै-काकृ-√वल्ह्) प्राधान्ये (आ) मै (क्षी)-मै-(सा-च-जै-काकृ)-कात-शा-हे। श्रैष्ठ्ये—वो। आह्वाने—ह्वि.। √वल्ह् (वल्ह) १/ परिभाषणहिंसादानेषु (आ)। वल्श०-ऋ. ३,८,११; वा. सं. ५,४,३ शतवल्शो नामवट०-भा. पु. ५,१६,१५।

वल्हति, ते–ह्वि. । मया नोपलब्धम् ।

√वल्ह् (वल्ह) १/६४१ क्षी-श-च× (काक्ृ-शा-हे-वो–√बल्ह्)

परिभाषणहिंसादानेषु (आ) मै-सा ।
परिभाषणाच्छादनहिंसासु—जै ।
प्राधान्यपरिभाषणहिंसादानेषु—काकृ-कात ।
परिभाषणहिंसाच्छादनेषु—शा-हे ।
श्रैष्ठ्ये—वो ।
आह्वाने—ह्वि. ।

√वर्ह् (वर्ह) १/ परिभाषणहिंसादानेषु (प) ।
√कल्ह् १/५४४ d प्राधान्यपरिभाषणहिंसादानेषु (आ) काकृ ।
√त्रिल्ह् १/५४४ c प्राधान्यपरिभाषणहिंसादानेषु (आ) काकृ ।
√मल्ह् १/५४४ b प्राधान्यपरिभाषणहिंसादानेषु (आ) काकृ ।

ग—(वाह्लिक०–मभार. १,२२२,४९ = तद्देशजाते । व्युत्पत्तिः ?) लह्योः स्याद् वर्णविपर्ययः । पह्ल>पहल (पहलवीत्यादि)>वहल>वह्ल्>√वल्ह् इति स्यात् क्रमः । बल्ख् इत्यारब्यभाषायाम् ।

√वश् (वश) २/६८ श

कान्तौ (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
स्पृहि—वो ।
कान्तिः = इच्छा–क्षी ।

√वश् (वश) १/२४८ गतौ (प) च ।
वष्टि–निघ. २/६ = कान्तिकर्मा ।

क—उएश् = इच्छायाम् ।

ख—अन्–उसन्त्–, उसैते = इच्छायाम्–जू. पॉकर्नीः ।

ग—वष्टि–ऋ. १,३३,३; २,२२,१; ऐब्रा. ६,१८ । उशन्ति—शब्रा. ४,१,३,१९ ।

छ—√बिसाना (<वशनम्) = वशे, बले, अधिकारे ।

+√वष् (वष) १/६८१ श×

हिंसार्थः (प)
क्षी-मै-सा-कात ।
हिंसायाम्—च-जै-काकृ-शा-हे ।
वधे—वो ।

√वष्क् (वष्क) १/१६७ गतौ (आ) जै ।
√वष्क् (वष्क) १०/३६९ दर्शने (प) सा ।

ग—वषड्ढुतेभ्यः–अ.वे. ७,९७,७ । वषट्–ऋ. १०,११५,९ (√वह +डषट् ?) ।

√वस् (वस) १/९८९ श	निवासे (प) क्षी-मै-सा-च-जै,-काकृ -(उ),- कात-शा-हे-वो ।	√वस् (वस) २/ आच्छादने (आ)। √वास (वास) १०/ उपसेवायाम् (प)।

क—उूऍस्=स्थितौ, निवासे।

ख—अवे. वङ्हैति=वसति–वा. पॉकर्नीः। [वङ्हैति=वसति–पी. टी. एस. पालि–इँग्लि. कोशः]

ग—वसति–शब्रा. १,६,४,३; तैब्रा. १,८,५,४; तांब्रा. ५,९,२। वसन्ते–षब्रा. ४,६।

ङ—√वस (अक)=निवासे, (२) सक. बन्धने। वसइ–कप्प.; महा.।

छ—√बसना=निवासे।

√वस् (वस) २/१३ श	आच्छादने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। स्तृतौ—वो।	√वस् (वस) १/ निवासे (प)। विवासति–शब्रा. १,४,१,२७[२]; तैब्रा. ३,५,२,२।

क—उूऍस्=आच्छादने।

ख—अवे. वस्ते, वङ्हैति–वा. पॉकर्नीः।

ग—उताधि वस्ते सुभगा–ऋ. १०,७५,८। अवस्त–वा. रा. २,३७,७=धृतवान् (ति.)।

+√वस् (वसु) ४/१०१ श	स्तम्भे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√वस् (वस) १/ निवासे (प)। √वस् (वस) २/ आच्छादने (आ)।

ग—वस्यति–मभार.५,७०,३=स्तभ्नाति (नील.)–टीकायामेव।

छ—बस=(अलम्), स्तम्भे।

√वस्क् (वस्क) १/९८ श-जै-काकृ-कात×	गत्यर्थः (आ) क्षी-मै-सा-च। गतौ—शा-हे-वो।	√वष्क् (वष्क) १/ गतौ (आ)। √वश् (वश) १/२४८ गतौ (प) च।

[ग—वष्कयणी–पा.अ. २/१/६५=चिरप्रसूता गौः]।

√वह् (वह) १/९८८ श	प्रापणे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	स वाह्यते राजपथः–रघु. १६,१२=गम्यते। वहेरन्यो वहिधातुः (सक्षी.)।

√वर्ध् (वध) १/ हतौ (प) वो।
शेषः पूर्ववत्।
वहते-निघ. २/१४=गति-कर्मा।

क—उऍघ्=प्रेरणे, प्रापणे। [लैति.-वेहो=प्रेरणे-पी. टी. एस्. पालि-इंग्लि. कोशः]

ख—अवे. वज़ैति=वहति-वा. पॉकर्नीः।

ग—रथः सूर्यां वहति-ऋ. ४,४४,१; तैब्रा. २,२,७,४।

ङ—√वह
√वब्भ
√वुब्भ
(सक)=प्रापणे। वहइ-कुमा.; उव.; महा.। कर्म.-वब्भई, वुब्भइ-कुमा.।

ङ—√वह (सक)=व्यापादने। वहेइ, वहंति-उत्त. १८,३,५; स. ७२८; संबो. ४१। द्रष्ट.√वध् १/ हतौ (प)।

छ—√बहना (<वहनम्)।

√वा २/३९
श
गतिगन्धनयोः (प)
क्षी-मै-सा-जै-काकृ-कात-शा-हे।
गतौ—च।
गमनहिंसयोः—वो।

√वै (ओवै) १/ शोषणे (प)।
√वात (वात) १०/ गति-सुखसेवनयोः (प)।
√वह् (वह) १/ प्रापणे (उ)।

ग—अपवाति-ऋ. १,१६२,१०; मा. २५,३३; तै. ४,६,८,४। वाति-शब्रा. ६,१,३,१३।

ङ—√वा (सक)=गतौ, चलने। वाइ-से. ६,५२।

ङ—√वाय (सक)=गतौ, चलने। वायंति-भग. ५,२।

+√वाङ्क्ष् (वाक्षि) १/६५९
श
काङ्क्षायाम् (प)
क्षी-मै-सा-च-जै-काकृ-कात शा-हे।
काङ्क्षे—वो।

√ध्वाङ्क्ष् (ध्वाक्षि) १/ काङ्क्षायाम् (प)।
√वाञ्छ् (वाछि) १/२०५ इच्छायाम् (प)।

√वाञ्छ् (वाछि) १/२०५ श (काकृ-√वाञ्च् [वाचि]) लैपिकी त्रुटिः।

इच्छायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। कामे—वो।

√वन् (वनु) ८/ याचने (आ)। वनोति-निघ. २/६= कान्तिकर्मा। वाञ्छति-निघ. २/६= गतिकर्मा।

क—उएँन्=प्रयत्ने, वाञ्छायाम्। स्कु्-इत्यपि-वा. पॉकर्नीः।

ग—सर्वा वाञ्छन्तु-ऋ. १०,१७३,१। वाञ्छन्ति-शब्रा. ६,७,३,७। वाञ्छति-महो. २,४७।

छ—√वंछना (<वाञ्छनम्)=अभिलाषे।

+√वाड् (वाडृ) १/२८४ श×(सा-च-√वाड् [वाडृ])

आप्लाव्ये (आ) क्षी-मै-सा-च-जै-शा-हे। आप्लावे—काकृ-कात-वो।

√वृ (वृञ्) ५/ वरणे (उ)।

ग—वाडेयीपुत्र०-शब्रा. १४,९,४,३०। वाडः=अश्वः..................? । बालः (वालः)-वा. रा. १,२०,७ (गी. प्रे. सं.)।

छ—बाड़ (<वाडः=वेष्टनम्-इति शब्दमाला)=वेष्टनम्।

[छ—बाढ़ (<वर्द्ध- ?)=आपूरः]।

+√वावृत् (वावृतु) ४/४९ (च×लीवि. सं.) जै-काकृ-कात×, शा ?-श

वरणे (आ) क्षी-मै-सा-हे। वर्तने—च। संभक्तौ वरणे—वो।

√वृत् (वृतु) १/ वर्तने (आ)। वावर्त्तति (वि+आ+√वृत्)-मज्झिम. १,१२।

अन्ये भ्वादेरेव 'वृतोः' वरणे दिवादित्वं वा मन्यन्ते। तेन वरणे द्युतादि-कार्यं न भवति-क्षी।

√वाश् (वाशृ) ४/५२ श, (काकृ-कात-√वास्)

शब्दे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

क—उअग्-, उअकु् (श)=शब्दे, क्रन्दने-वा. पॉकर्नीः।

ग—वाश्यते-ऐब्रा. ५,२७। वाश्यन्ते-जैउ. ३,३,३,२। काका वाश्यन्ति-वा. रा. ७,६,५८। वाशति-ऋ. ५,५४,२ इति भौवादिकोऽपि। चीची कूचीति वाशन्ति सारिकाः-मभार. १६,३८।

च—√वास=तिरश्चामारावे, (२) आह्वाने-वासइ-पउम. ५५,३१ ।

√वाह् (वाहृ) १/६४५ श-शा×, (क्षी-सा-च-√वाह्)	प्रयत्ने (आ) (क्षी)-मै-(सा-च-) जै-काकृ-कात-हे । यत्ने—वो ।	√वेह् (वेहृ) १/ प्रयत्ने (आ) सा । √वेह् (वेहृ) १/ प्रयत्ने (आ) ।

ग—प्रवाहस्व-सुश्रु. १,३६८,१३ ; प्रवाहेथाः शनैः शनैः—१,३६८,१४ ; प्रवाहमाण०—२,४७,४ ।

√विच् (विचिर्) ३/१२ मै-श-च-जै-काकृ-कात-(शा) ×	पृथग्भावे (उ) इति सभ्याः—क्षी । क्षी-सा-हे । पृथक्त्वे—वो ।	<√विज् (विजिर्) पृथग्भावे (उ) ।

क—अउआइक्=विभागे ।

ख—अवे. अव-वएक्=विभागे-वा. पॉकर्नीः ।

ग—अप...वेवेक्ति-अ. कौ. सू. ६१ । अध्यप वेवेक्ति-शत्रा.१,१,४,२२ । धर्माधर्मौ व्यवेचयत्-मनु. १,२६=पृथक्त्वेनाभ्यधात् (मन्वर्थ.) ।

√विच् (विचिर्) ७/५ (श)	पृथग्भावे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । पृथक्त्वे—वो ।

ग—वि विञ्चन्ति वनस्पतीन्-ऋ. १,३९,५ । विनक्तु-वा. सं. १,१६; शत्रा. १,१,४,२२ ।

+√विच्छ् (विछ) ६/१४२ श×	गतौ (प) क्षी-मै-शा-च-जै-काकृ-कात-शा-हे-वो ।

√विज् (विज) १/२१४ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	गतौ (प) इत्येके-क्षी क्षी ।	<√वृज् (वृज) गतौ (प) ।

+√विज् (विजिर्) ३/१२ श (शा)	पृथग्भावे (प) क्षी-मै-सा-च-जै-काकृ-	>√विच् (विचिर्) पृथग्भावे (प) ।

	कात-(शा)-हे-वो । वेके—वो (उ)।	
√विज् (ओविजी) ६/९ श	भयचलनयोः (आ) क्षी-मै-सा-जै-काक्र- कात-शा-हे । उद्वेगे—च । भीकम्पे—वो ।	√विज् (विज) १/ गतौ (प)। √विज् (विजिर्) ३/ पृथग्भावे (प)।

क—उआइक्=, उआइग्=नतौ, न्युब्जे, परिवर्तने ।

ख—अवे. वएग्-(वएजो)=इतस्ततश्चलने, दोलने, स्पन्दने-वा. पॉकर्नीः ।

ग—ऊर्ध्वः समुद्रो विजते-शत्रा. ७,१,१,१४ । विजन्ते-ऐब्रा.३,४; शांत्रा. ३,१ । अपविजमाना-शौ. १२,१,३७ । विग्ना-रघु. १४,६८=भीता (संजी.)।

+√विज् (ओविजी) ७/२३ च×, श	भयचलनयोः (प) क्षी-मै-सा-जै,काक्र (उ),- कात-शा-हे । भीकम्पे—वो ।	
+√विट् (विट) १/३१२	शब्दे (प) इति मल्लः—क्षी क्षी-मै-सा-च-काक्र- कात—हे । आक्रोशे स्वने—वो ।	√पिट् (पिट) १/ शब्दे (प)। √पिड् (पिड) १/ शब्दे (प)। √विड् (विड) १/ आक्रोशे (प)।

ग—वेट्कार०-शत्रा. ९,२,१,७ ; ९,३,३,१४ । विटः-नाट्यशा. १८,४६ । स्त्रिया विटानामिव साधु वार्ता-भा. पु. १०,१३,२ ।

+√विट् (विट) १/३१३ श-जै-कात-शा×, (मै-सा-च-काक्र- √बिट्)	आक्रोशे (प) क्षी-हे-(मै-सा-च-काक्र)। आक्रोशे स्वने—वो ।	पूर्ववत् ।

ग—पूर्ववत् ।

+√विड् (विड) १/३१३ सा-श-च×,(मै-काक्र-	आक्रोशे (प) इति नन्दी—क्षी ।	<√विट् (विट) आक्रोशे (प)।

शा-हे √ विड्)

क्षी-(मै)-जै-(काक्र)-
कात-(शा,-हे ?)।
आक्रुशि—वो।
शब्दे इति मल्लः—क्षी।
(आ. चन्द्रिकायां
नास्ति— वागीशः)।

√ पिट् (पिट) १/ शब्द-
संघातयोः (प)।
√ पिड् (पिड) १/ शब्दे
(प)।

ग—विडालः-हितोपदेशे ६५ पृ.।

छ—वेड़ा (<वेडा=नौका-हेमचन्द्रः)=नौका।

छ—विडरना (<√ विड्=आक्रोशे)=तीर्णवितीर्णतायाम्, (२) पलायने।

+√ विथ् (विथृ) १/ ३२ याचने (आ)।
श × (काक्र-√ वीथ्
[वीथृ])

क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे।
कौशिकस्तु—'यातने'
इत्याह—क्षी।
क्षी-हे।
याचे—वो।

√ व्यथ् (व्यथ) १/ भय-
चलनयोः (आ)।

ग—विथुरेव रेजते भूमिः-ऋ. १,८७,३=भर्तृवियुक्ता नारी। यद्यपि "व्यथेः सम्प्रसारणं किच्च" (उणा. १/३९) इत्यनेन विथुरसिद्धिर्जायते तथापि तत्र √ विथ् इति दर्शनान्मयेहोल्लेखः कृतः। कौशिकहेमचन्द्रमतेन यातनार्थकोऽप्ययम्।

√ विद् (विद) २/५३ ज्ञाने (प)
श

क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे।
मतौ—वो।

क—ऊआइद्=ग्रहणे, ज्ञाने।

ख—अवे. विस्त=वित्तम् (ऋ. १,१०,५,१)=ज्ञातम्-वा. पॉकर्नीः।

ग—स वेद देव आनमं देवान्-ऋ. ४,८,३। वेत्ति-श्वेताश्वतरो. ३,१९; गी. १०,३।

ङ—√ विअ (सक)=ज्ञाने। वियसि-विसे. १६००।

+√ विद् (विद) ४/५९ सत्तायाम् (आ)
श

क्षी-मै-सा-च-जै-काक्र-

√ विद् (विद) ७/विचारणे
(आ)।

काल-शा-हे । विद् (विद)१०/ चेतनाख्यानविवादेषु (आ) ।
भावे—वो । √विद् (विद्लृ) ६/ लाभे (उ) ।

ग—विद्यते-शब्रा. ११,७,१,२; [विन्दतेः कर्मणीत्यर्वाञ्चः]; तैआ. १,५,१; छान्दो. ८,१,२ । दुर्मतेर्विद्यते फलम्-मनु. ११,३०=भवति (मन्वर्थ.) ।

ङ—√विञ्ज (अक)=भावे । विञ्जइ, विञ्जए-भग.; महा.; कस. ।

√विद् (विद्लृ) ६/१४९ जै×, श — लाभे (उ) क्षी-मै-सा-च-काक्र-कात-शा-हे-वो । — विन्धते—ऋ. ८,९,६ । पूर्ववत् ।

क—उआइद्=ग्रहणे ।
ख—अवे. विदैति, वीदैति, विनस्ति, वीनस्ति-वा. पॉकर्नीः ।
ग—ऋते स विन्दते युधः-ऋ.८,२७,१७; शब्रा. ३,३,३,१५; तैब्रा. २,१,५,८ ।

+√विद् (विद) ७/१३ श — विचारणे (आ) क्षी-मै-सा-काक्र-कात-शा-हे । विचारे—च-जै । मीमांसे—वो । — पूर्ववत् ।

ग—तौदादिकः- नैवं विदामो भगवन्-भा. पु. ४,९,८१ ।

+√विधू (विधृ) १/३३ क्षी-मै-श-च-जै-काक्र-कात-शा-हे-वो× — याचने (आ) इति कौशिकः—सा सा । — √विथ् (विथृ) १/ याचने (आ) । अयं हि....विन्धते-ऋ. ८,९,६ ।

√विध् (विध) ६/४६ श — विधाने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे । विधौ—वो । पूजायाम्—ह्वि. । — विधेम-निघ. ३/५=परिचरणकर्मा । √व्यध् (व्यध) ४/ ताडने (प) ।

अनेकार्थत्वाच्छिद्रकरणेऽप्ययम्-दुर्गादासः । निमित्तवेधी-मभार. ५,९६,३०=वेधकर्ता—वागीशः ।

ग—यस्तेऽविधत्–ऋ. २,१,७। विधते–ऋ. ४,२,१३ । वेध्यम्–मार्क. पु. ४२,७।

छ—√वेधना / √बींधना } (<वेधनम्)=छेदनम्।

छ—विधना=प्रापणे, साहचर्ये।

+√विल (विल) ६/७८ संवरणे (प) √विल् (बिल) ६/ भेदने (प)
श-च-काकृ-कात×, क्षी-मै-सा-जै।
(जै-√षिल्) वरणे—शा-हे।
मुद्रणदोषः। स्तृतौ—वो।

ग—अन्तर्विक्षोभितजलाविल०–मभार. १,१२१६। आविलाम्–वा. रा. ५,१८,३।

√विश् (विश) ६/१४३ प्रवेशने (प) √विच्छ् (विछ) ६/ गतौ (प)।
श क्षी-मै-सा-च-काकृ-कात-शा-हे। √विश् ४/५४ प्रवेशने ? (प)
प्रवेशे—जै-चो। काकृ।

क—उ॒एकु (श॒)-, उ॒इश्-, उऑइशॉ=निवासः, गृहम्, व्यवस्थायाम्।
ख—वीसैति=विशति–वा. पॉकर्नीः।
ग—विशति–त्रिवि. ३,७; शाण्डिल्यो. १,७,९; महो. २,६३। विशते–मुण्डकोप. ३,२,४।
ङ—√विस (सक)=प्रवेशे। विसइ, विसंति–वज्जा. २६; सण.; गउड.।
ङ—√विस्स (सक)=प्रवेशे। विस्सामि–सुर. २,१२७।
ङ—√वेस=उपवेशे–ओघ. ५७१।
च—√वइस / √वईस } =उपवेशे–[बेसवुँ–गुर्जरभा.] बइसइ, बईसइ–भवि.।
छ—√बैसना * † (<वेशनम्)=उपवेशने।
छ—√बैठना (<वेशनम्, विष्ट० ?)=उपवेशने।

√विष् (विषु) १/६८९ सेचने (प)। √विश् (विश) ६/ प्रवेशने (प)।
श× क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। √विष् (विष) ९/ विप्रयोगे (प)।
चापल्ये, उद्योगे—ह्वि.।

क—उ॒आइस्=इतस्ततः क्षेपणे, विकीर्णौ, क्षरणे, द्रवीभावे–वा. पॉकर्नीः।

ग—वेषति–ऋ. १,१८१, ६।

√विष् (विष्लृ) ३/१३ श	व्याप्तौ (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। चापल्ये, उद्योगे—ह्वि.।	वेवेष्टि–निघ. २,८=अत्ति-कर्मा।

ग—वेविषत्–ऋ. १०,९१,७। वेवेष्टि यज्ञम्–शब्रा. १,१,२,१; काब्रा. २,१,२,३।

√विष् (विष) ९/५४ श	विप्रयोगे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√विश् (विश) ६/ प्रवेशने (प)। √विष् (विष्लृ) ३/ व्याप्तौ (उ)। √विषु (विषु) १/ सेचने (प)।

ग—विषम्–शांब्रा. २९,१; शब्रा. ९,१,१,१०; साब्रा. २,३,११।
'विष्णाति' इति प्रयोगे समुपलब्धे सत्येव निर्णयो धातोरस्य शक्यः कर्तुम्।

+√विस् (विसृ) १/७०६ क्षी-मै-शा-च-जै-काकृ-कात-शा-हे×	गतौ (प) इत्यपि पठ्यते–सा। सा। इतौ—वो।	√पिस् (पिसृ) गतौ (प)। √पेस् (पेसृ) १/ गतौ (प)। √वेस् (वेसृ) १/ गतौ (प)।
+√विस् (विस) ४/१११ (क्षी-सा-श-च-जै-वो-√बिस् [बिस]) (काकृ-√विश् [विश])	प्रेरणे (प) मै। मै (क्षी-सा-च-जै-काकृ)-कात-शा-हे। इतौ—वो।	

ग—नवविसकिसलय०–कलाविलासे ६,१–विसम्=मृणालम्।

√वी २/३७	गतिप्रजनकान्त्यसनखादनेषु (प) क्षी-मै-सा। गतौ—च।	वेति–निघ. २/६=कान्ति-कर्मा। √ई २/ गतिप्रजनकान्त्यसनखादनेषु (प) सा।

गतिप्रजनकान्त्यशनेषु—जै ।
गतौ प्रजनकान्त्यासन-
खादनेषु च—काक्रु ।
गतौ प्रजनकान्त्यसन-
खादनेषु च—कात-हे ।
गतिप्रजनकान्त्यशन-
खादनेषु—शा ।
कान्तिगतिव्याप्तिक्षेप-
प्रजनखादने—वो ।

क—उ॒आइ-, उ॒आइआx=कान्तौ=इच्छायाम् ।

ग—अति˙˙वेति—ऋ. ५,४४,७; अपवेति—५,६१,१८; शौ. २०,१७,२ । वेति—शांआ. ५,१ । वीते—छागलेयो. २५:९ [गतौ, लटि, प्रपु. १] ।

+√वुङ्ग् (वुगि) १/१५७ मै-श×(काक्रु-कात-शा—√ वुङ्ग्)	वर्जने (प) क्षी-सा-च-जै-काक्रु-कात-शा-हे । त्यागे—वो ।	<भङ्गः ।

छ—बोंग=त्रुटिते दन्ते सत्यवकाशः, त्यागः-बुं. ख. ।

+√वुन्द्(उवुन्दिर्)१/८८० श-च-काक्रु-कात×(क्षी-सा-जै-शा-हे-वो—√ वुन्द्)	निशामने (उ) मै (क्षी-सा-जै-शा-हे-वो) ।	√बुन्ध् (उबुन्धिर्) १/ निशामने (उ) । √चुन्द् (उचुन्दिर्) १/६७४ निशामने (उ)काक्रु । ५८३ निशामने (उ) कात ।

+√वुस् (वुस) ४/११३ (क्षी-सा-श-च-कात-वो—√बुस्) । (काक्रु-√बुश्)	उत्सर्गे (प) मै-जै-शा-हे (क्षी-सा-च-कात-)—काक्रु ।	√प्युष् ४/७३ उत्सर्गे (प) हे ।

छ—√बुसना }
छ—√भुसना } =पर्युषिते, त्याज्ये ।

√वृंह् (वृहि) १/७३९ श, (क्षी-काक्रु-शा—	वृद्धौ (प) (क्षी)-मै-सा-च-जै-	√बृह् (बृह) १/ वृद्धौ (प) । √वृध् (वृधु) १/वृद्धौ (आ) ।

√बृंह् [बृंहि]) 1/७२३ — (काकृ)-कात-(शा)-हे। शब्दे च--मै-सा-जै-हे। शब्दने—सा। वृद्धौ,च=शब्दे—(क्षी-शा)। ध्वने ऋद्धौ—वो। — √बृह् (बृह) ६/ वृद्धौ (प)मै।

ग—वृंहतीति ह्वि.। मया नाप्तम्। वर्हिः-ऋ. ७, ७५, ८=यज्ञम्-साय.। वृंहितम्...............?

√वृ (वृञ्) ५/८ श — वरणे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। वृतौ—वो। — √वर् (वर) १/ ईप्सायाम् (प)। √वृ (वृञ्) १०/ आवरणे (उ)।

क—उऍल्=वेष्टने, वाञ्छायाम्।

ख—अवे. वृरुनवैति=आच्छादने-वा. पॉकर्नीः।

ग—वृणोति-श्वेताश्वतरो. ५, १२। वृणुते-गोब्रा. १,२, २४४; तैब्रा. ३,१,३,२। वृण्वन्-रघु. १८, ३८=गच्छन् (संजी.)।

ङ—√वर (सक)=आच्छादने, (२) याचने, (३) सेवायाम्। वरइ-सुज्ज. १९।

छ—√बरना (<वरणम्)=वरत्वेन वधूत्वेन वाङ्गीकरणे, विवाहे।

√वृ(वृङ्) ९/३८ काकृ×,श — संभक्तौ (आ) क्षी-मै-सा-च-जै-कात-शा-हे-वो। वरणे—ह्वि.।

संभक्तिः=सेवनम्-दुर्गादासः।

ग—वृणीते-कठो. १, १, २९; कौषीतकिब्राह्मणो. ३, १।

+√वृक् (वृक) १/८९ श× — आदाने (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे-वो। जै ? — √वग् १/४१०। आदाने (आ) काकृ। √बृक् १/४१०e आदाने (आ) काकृ। वृकश्चन्द्रमा भवति विवृत-

ज्योतिष्को वा विक्रान्तज्योतिष्को वा–निरु. ५,२०,१। वृकः–निघ. २/२०=वज्रनाम।

ग—वृक०–मनु. ८,२३५—वृकैः=शृगालप्रभृतिभिः—मेधातिथिः। वर्करः–का. श्रौ. ९७६, ६। वृकः–निघ. ३/२४=स्तेननाम। वृको लाङ्गलं भवति विकर्तनात्–निरु. ६, २६, १।

+√वृक्ष् (वृक्ष) १/६०० शX वरणे (आ) क्षी-मै-सा-च-काक्र-कात-शा-हे। वृतौ—जै-वो। (जै–'वृत्तौ'–इति मुद्रण-दोषः)। √व्रश्च् (ओव्रश्चू) ६/ छेदने (प)। √वृच् (वृची) ७/२४ वरणे (प) इति दौर्गाः–क्षी।

ग—वृश्चामि तं कुलिशेनेव वृक्षम्–अ. वे. २,१२, ३। वि वृक्षान् हन्ति–ऋ. २, ८३, २। वैयाकरणाश्छेदनार्थकाद् √व्रश्च् धातोः 'वृक्ष'-शब्दं व्युत्पादयन्ति (उणा. २/६६)। यास्कस्तु व्युत्पत्तिद्वयं प्रस्तौति—'वृक्षो व्रश्चनात्। वृत्वा क्षां तिष्ठतीति वा' –निरु. २, ६, १। यास्कमतेन वरणार्थकत्वमस्य सिद्ध्यति। वस्तुत एकस्य नाम्नो भवन्त्यनेके व्यापाराः। तान् व्यापारानुद्दिश्यैव नामानि प्रख्यायन्ते। यथाऽग्नेर्गत्यर्थकत्व-दाहार्थकत्व-द्युत्यर्थकत्वाद्यनेके सन्ति व्यापाराः।

+√वृच् (वृची) ७/२४ मै-श-च-जै-कातX वरणे (प) इति दौर्गाः- क्षी-सा-शा-हे। हिंसायाम्—काक्र (उ)। वृतौ—वो। <√वृज् (वृजी) वर्जने (प)।

ग—वर्कः.............? (वर्करः–का. श्रौ. ९७६,६)।

+√वृज् (वृज) १/२१४ मै-सा-श-च-जै-काक्र-कात-शा-हे-वोX गतौ (प) क्षी। ><√धृज् (धृज) १/२१६ गतौ (प) मै। √व्रज् (व्रज) १/२१५ गतौ (प) तरङ्गिणीकाश्यपसम्मतास्तु–सा।

मैत्रेयस्य–"ध्रज ध्रजि धृज धृजि ध्वज ध्वजि गतौ" इति दण्डकः "वृज ध्रजि ध्रज ध्वजि गतौ" इति क्षीरस्वामिनो दण्डकाद् युक्ततरो भाति। धकारक्रमके दण्डके क्षीर-

स्वामिनो वकारक्रमको वृज् धातुः कमपि लिपिभ्रंशं संकेतयति। √धृज् धातुगतस्य 'धृ' इत्यस्याधस्तनभागेऽस्पष्टतां गते सति √धृज् इत्यस्य 'वृज' इति पठ्यमानता नैसर्गिकी। √व्रज् १/२५१ गतौ (प) इति धातोर्देशभेदाद् √वृज् इत्यपि शक्यते भवितुम्। प्रयोगालाभाद् वयं किमपि निश्चेतुमनर्हाः।

+√वृज् (वृजी) २/१८ वर्जने (आ) इति दौर्गाः-क्षी।
श-जै-शा×
क्षी-मै-सा-च-काकृ-कात-हे।
त्यागे वृतौ च—वो।

√वृञ्ज् (वृजि) २/१९ वर्जने (आ) सा।

अपिवृक्तम्-ऋ. ६,६२, १०। तन्मे रेतः पिता वृक्ताम्-मनु. ९,२०=शोधयतु-(कुल्लू.)। अत्रार्थो विचारणीयः। सम्पूर्णः श्लोक इत्थम्—

यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता।
तन्मे रेतः पिता वृक्तामित्यस्यैतन्निदर्शनम्॥

√वृज् (वृजी) ७/२४ वर्जने (प)
शा×,श
क्षी-मै-सा-च-जै,-काकृ-(उ),-कात-हे।
त्यागे वृतौ च—वो।
वेष्टने—ह्वि.।

क—ऑइर्ग्=वेष्टने, परिवर्तने। ऑइर्ग्-वा. पॉकर्नीः।
ख—अवे. वीवर्जदवतो=विवृक्तवतः (अधर्मिणः)-अवेस्ता, यस्न ९,३०।
ग—वृणक्ति-ऋ. ४,७,१०। वृञ्जन्ति-ऐआ. १,३,४।
घ—वज्जति-मिलिन्दपञ्ह २२७।
छ—√बरजना, √बरकना (<वर्जनम्)=रोधे, निवारणे।

+√वृञ्ज् (वृजि) २/१९ वर्जने (आ)
क्षी-मै-श-च-जै-काकृ-कात-शा-हे×
इत्यात्रेयादयो दौर्गाश्च—सा।
त्यागे—वो।

ग—इन्द्राग्नी वृङ्क्ते-ऐब्रा. ६,६; शब्रा. १,५,३,९-१३; तैब्रा. १,५,६,५; तांब्रा. ६,५,१५। शाबरभाष्ये-'प्रवृञ्जनम्' इति प्रयुज्यते-सा। गुणान्न वृङ्क्ते-भा. पु. ५,१,१६।

'वृङ्क्ते' इत्यादीनि रूपाणि रौधादिकाद् √वृज् (वृजी) वर्जने इति धातोः साधयितुं नार्हाणि, तस्य परस्मैपदित्वात्। काशकृत्स्नस्य मतेन रौधादिकस्य धातोरुभयपदित्वादस्य

धातोरदादौ पाठो न सध्रीचीनः। आर्धधातुके खल्वेतस्य रूपाणि भवन्ति सनुम्कानि रौधादिकस्य √वृज् धातोश्च विनुम्कानि। अयमेवोभयोर्भेदः। एवं सत्यप्यस्माभिरेतस्य धातोरार्धधातुकरूपाणि (सनुम्कानि) नासाद्यन्ते। शाबरभाष्ये 'प्रवृञ्जनम्' इति प्रयोगोऽवश्यमुपलभ्यते। सायणीयोऽयं निर्देशः। नास्माभिरक्षिसाक्षीकृतः।

+√वृण् (वृण) ६/४९ प्रीणने (प) <√पृण् (पृण) प्रीणने (प)।
क्षी-मै-श-च-जै-काकृ- इत्यप्यत्र पठि-
कात-शा-हे-वो× तव्यः—सा।

"धात्वन्तरे पृणिवृणी" इति भाष्यम्। "धात्वन्तरे इति तौदादिकावित्यर्थः" इति कैयटे-सा।

ग—वृणसे-तैआ. ६,४,२। वृणे-ऐआ. ६,७; जैउ. १,१६,२,६। वृणताम्-अ.वे. ३,४,२,। अनेन धातुनात्मनेपदिनापि भाव्यम्। उभयपदित्वमस्येति स्पष्टोऽर्थः।

√वृत् (वृतु) १/७५० वर्तने (आ)
श क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।
वृतौ—जै।
वर्तनम् = स्थितिः—क्षी।

ग—वर्तते यन्नभि क्षाम्-ऋ. १,१८३,२; शब्रा. ८,४,१,९।

घ—वत्तति-सुत्तनिपात ६५४; पेतवत्थु २,९। वट्टति-संयुत्त. १,१५।

ङ—√वट्ट = वर्तने, (२) आचरणे। वट्टइ, वट्टए, वट्टति-सुर. ३,३९; उव.; कप्प.।

छ—वर्तना, वरतना } (<वर्तनम्) = व्यवहारे, वर्तने

+√वृत् (वृतु) ४/४९ वरणे (आ) अन्ये-क्षी √वृत् ६/३५ ग्रन्थे हिंसायां च (प) काकृ।
श-च× क्षी-मै-सा-जै-काकृ-कात-शा-हे। √वृत् ६/१ हिंसायाम्-कात।
संभक्तौ वरणे—वो।

अन्ये भ्वादेरेव (१/७५०) वरणे दिवादित्वं वा मन्यन्ते। तेन वरणे द्युतादिकार्यं न भवति-क्षी।

√वृध् (वृधु) १/७५१ वृद्धौ (आ) √ऋध् (ऋधु) ४/१३२
श× क्षी-मै-सा-च-जै-काकृ- वृद्धौ (प।

	कात-शा-हे-वो।	√ऋध् (ऋधु) ५/२५ वृद्धौ (प)। √वृध् (वृधु) १०/९६ वर्धने (प) काकृ।

क—ऊएरेध्-, उएरुध् = वृद्धौ।

ख—अवे. वरुद् = ऊर्ध्वम्, उच्चम्—वा. पॉकर्नीः।

ख—वुरुदैति = वर्धते (पी. टी. एस. पालि-इँग्लिश्कोशात्)।

ग—वर्धते—ऋ. २,२५,२; शब्रा. १,६,३,११; वर्धन्ति—१,८,१,२८।

घ—वड्ढति—[संयुत्त. १,१५;] सुत्तनिपात ३२९।

ङ—√वुड्ढ (अक) = वृद्धौ—संक्षि. ३४। वुड्ढन्ति—भग. ५,८।

ङ—√वड्ढ (अक) = वृद्धौ। वड्ढइ—महा.; काल.।

छ—√बढ़ना (<वर्द्धनम्)।

+√वृश् (वृश) ४/११३ काकृ×, श	वरणे (प) क्षी-मै-सा-च-जै-कात-शा-हे। वृत्याम्—वो।	√वृ (वृञ्) ५/ वरणे (उ)। √वृच् (वृची) ७/ वरणे (प)। √वृक्ष् (वृक्ष) १/ वरणे (आ)।
√वृष् (वृषु) १/६९७	सेचने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। हिंसासंक्लेशनयोश्च—सा। हिंसायाम्—शा-हे।	√विष् (विषु) १/ सेचने (प)।

ग—वर्षन्ति वृष्टयः—ऋ. ५,८४,३। अववृष्टेन—काठ. ३५,१९; कठो. ४८,१७। जठर आ वृषस्व—ऋ. १,१०४,९ (तौदादिकः)। वृषणः—तैब्रा. ३,६,९,१।

ङ—√वास = वर्षणे। वासंति—भग.।

छ—√बरसना
छ—√बरखना
छ—√बरषना*†
} (<वर्षणम्) = वर्षणे।

+√वृह् (वृहिर्) १/७२३ मै-श-जै-शा×(क्षी-काकृ—√वृह्)	शब्दने (प) इति चन्द्र-गुप्तौ—सा। सा।

	शब्दे—च-कात-हे । शब्दे, च = वृद्धौ–इति दुर्गः—क्षी । वृद्धौ—काकृ । ध्वने ऋद्धौ—वो ।	
+√ बृह् (बृह) १/७३८ श-कात × (क्षी-काकृ-शा–√ बृह्)	बृद्धौ (प) मै । क्षी-मै-सा-च-जै काकृ-शा-हे-वो । (सा–मैसू. सं.) ।	√ बृंह् (बृहि) १/ बृद्धौ (प) । √ बृध् (बृधु) १/ बृद्धौ (आ) । √ बृद् १/१८८ पालने (प) काकृ ।

ग—केतकबर्हमन्यः–रघु. ६,१७ इति शब्दकल्पद्रुमः । वस्तुतस्तूभयथा पाठो बकारविशिष्टो वकारविशिष्टश्च । वर्हम् = पत्रम् ।

√ बृह् (बृहू) ६/६६ श (क्षी-काकृ-शा–√ बृह्)	उद्यमे (प) मै । क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । उद्यमने—सा-जै-शा ।	

ग—वाबृहाणम्–आर्षेयो. ९ : १९ । (वि) बृहति–शब्रा. १२,९,२,७ । (वि) बृहेत्–जैब्रा. १४०[२] ।

√ वृ (वृञ्) ९/१४ जै-कात ×, श	वरणे (उ) क्षी-मै-सा-च-काकृ-हे । वृत्याम्—वो ।	√ वृ (वृङ्) ९/ संभक्तौ (आ) । √ व्री ९/ वरणे (प) ।
√ वृ (वृञ्) मै-सा-श-च-काकृ-शा ×	'वरणे' इति नन्दी—क्षी । क्षी-जै-कात-हे । वृतौ—वो ।	√ वृ (वृञ्) ५/वरणे (उ) ।

ग—वृणीमहे–वनदुर्गो. ४३९ : १४ । वृणीते–तैब्रा. १,६,९,१ । वृणीष्व–मैत्र्यु. १,२ ।

√ वॄ ९/१९ श-च × (काकृ-शा-हे-वो–√ बॄ) (कात–√ वृ)	भरणे (प) क्षी-शा-हे । वरणे—मै-सा-जै-काकृ-कात-हे ।	√ भॄ ९/ भरणे (प) । √ व्री ९/ वरणे (प) ।

वृत्यां भृत्याम् —वो।
पूर्वस्यैव प्रपञ्चः।

√वे (वेञ्) १/९९० तन्तुसन्ताने (उ)।
श क्षी-मै-सा-च-जै-काकृ-
काल-शा-हे।
स्यूतौ—वो।
√वा,√वि,√उ ४/ ह्वि.।

क—उआइ = वेष्टने, नतौ–वा. पॉकर्नीः।

ग—न यं वयन्ति–ऋ. ६,९,२। वयति–शब्रा. ३,१,२,१९; तैब्रा. २,६,४,१।

घ—विय्यति (कर्मणि)–विनय. ३,२५९।

ङ—√वा (सक)=तन्तुसन्ताने–दसनि. २। क्रु—वाइम।

छ—√बुनना, √बिनना = वयने।

+√वेण् (वेणृ) १/८६२ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु (उ) — √वी २/ गतिव्याप्ति··· (प)।
श× क्षी-मै-सा-शा-हे। — √वेण् १/२१३ e गतिप्रेषणश्लेषणेषु (प) काकृ।
गतौ—च। — √वेन् १/२२० e संभक्तौ (प) काकृ।
गतिचिन्ताज्ञानवादित्रग्रहणेषु—जै।
(काकृ-√वीण्)— गतौ ज्ञानचिन्तानिशामनेषु—काकृ। — वेनति–निघ. २/६= कान्तिकर्मा।
√वेन् (वेनृ)······ भाष्यकारास्तवर्गपञ्चमान्तममुं पेठुः—सा। — वेनति–निघ. २/१४=गतिकर्मा।
अत्यभिलाषे—ह्वि.। — वेनति–निघ. ३/१४= अर्चतिकर्मा।

क—उआइ-, उआइआx=अत्यभिलाषे–वा. पॉकर्नीः।

ग—वेणु०–शब्रा. १,१,४,१९। वेणानां भाण्डवादनात्–मनु. १०,४९; ४,२१५ (वादित्रार्थे); वेणो विनष्टोऽविनयात्–७,४१। 'वेनः' पुस्तकेषूपलभ्यमानेष्वस्ति। वेणोः सुषिरम्–तै. ५,१,१,४ (वादित्रार्थे)। अभिवेनन्तः–ऋ. १०,१२३,६। वेनन्ति–ऐब्रा. १,२०।

+√वेथ् (वेथृ) १/३३ श× | याचने (आ)। क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे। यातने—(क्षी) हे। याचे—वो। | √विथ् (विथृ) १/३२ याचने (आ)। √व्यथ् (व्यथ) १/ भय-संचलनयोः (आ)।

कौशिकस्तु विथुरसिद्धये यातन इत्याह, तन्न, व्यथेः संप्रसारणं किच्च (उणा. १/४०) इति सिद्धेः—क्षी।

√वेप् (टुवेपृ) १/३६३ श× | कम्पने (आ)। क्षी-मै-सा-च-काक्ट। चलने—जै-कात-शा-हे। चले—वो। | वेपः-निघ. २/१ =कर्मनाम।

क—ऊआइप्-ऊआइब्=वेष्टने, उत्तेजने-वा. पॉकर्नीः।

ग—वेपते भियसा मही-ऋ. १,८०,११। वेपन्तीम्-वा. रा. १,६३,१३=वेपमानाम् (तिल.)।

ङ—√वेव (अक)=कम्पने। वेवइ-कुमा.।

ङ—√वेअ (अक)=कम्पने-गा. ३१२ अ.।

+√वेल् (वेलृ) १/५३५ क्षी-श× | चलने (प) मै मै-सा-च-जै-शा-हे-वो। गतौ—काक्ट-कात। | √वल् (वल) १/४१७ a चलने (आ) कात। √वल्ल् (वल्ल) १/४९७b चलने (आ) कात। √क्ष्वेल् (क्ष्वेलृ) १/ चलने (प)। √वेल्ल् (वेल्लृ) १/५३५ चलने (आ)।

ग—उद्वेलन्त्०-मालतीमा. १४०,३, (दोषपूर्णः पाठः ! उद्वेल्लन्त्० इति स्यात् !)।

√वेल्ल् (वेल्लृ) १/५३५ श-च-काक्ट-कात-शा× (मै-√वेल्ल् [वेल्ल]) | चलने (प) क्षी-मै-सा-जै-वो। गतौ—हे। | √वेल्ल् १४३७ गतौ (प) हे। शेषः पूर्ववत्।

क—ऊआइ=वेष्टने, उत्तेजने। ऊआइ-ल्—वा. पॉकर्नीः।

ग—वेल्लद्वीचिर्महानदी-कथासरि. ३९,१४४। वेल्लति नवपरिणया वधूः-काव्यप्र. १५०,१०।

घ—संवेल्लेति-विसुद्धिमग्ग ३२७=संघाते।

ङ—√वेल्ल (अक)=कम्पने, (२) संवेशने, (३) प्रेरणे। वेल्लइ-पि. १०७। वेल्लंति-गउड.।

ङ—√विल्ल (अक)=चलने, दोलने। विल्लंति-रंभा.।

√वेवी (वेवीङ्) २/६६ जै-शा×,श — वेतिना तुल्ये (आ) क्षी-मै-सा-काकृ-कात। गतौ—च। वीसमानार्थे—हे। कान्तिगतिव्याप्तिक्षेप-प्रजनखादने—वो। √वी-ह्वि.। — √वी २/ गतिव्याप्ति····(प)।

छान्दसोऽयमिति भाष्यम् १/१/६।

क—उआइ-, उआइआx=अत्यभिलाषे-वा. पॉकर्नीः।

ग—वेवेति श्रेणिभी रथानाम्-ऋ. ४,३८,६; न वेवेति पलितो दूत आसु-३,५५,९।

√वेष्ट् (वेष्ट) १/२५३ श-काकृ× — वेष्टने (आ) क्षी-मै-सा-च-जै-कात-शा-हे। वेष्टे—वो। — √वी २/ गतिव्याप्तिप्रजन··· (प)। √विष् (विष्लृ) ३/ व्याप्तौ (उ)। √विश् (विश) ६/ प्रवेशने (प)।

वेष्टनम्=ग्रन्थनम्, लोटनम्, परिहाणिश्च (परिणाहश्च-पाठा.) —क्षी।

क—उआइस्= वेष्टने। लिथु. व्युस्तस्=कञ्चुकम्, रोधे-पॉकर्नीः।

ग—मयि ते वेष्टतां मनः-अ. वे. ६,१०२,२।

घ—वेठेति (प्रयोज.)-जातक १,५; मिलिन्दपञ्ह २८२।

ङ—√विंट (सक)=वेष्टने [विंटवुं-गुर्जरभा.]; विंटइ-सुपा. ५७३।

ङ—√वेढ (सक)=वेष्टने। वेढइ, वेढेइ-उवा.।

छ—√वेड़ना
छ—√वेढ़ना } =रोधे, वेष्टने।

+√वेस् (वेसृ) १/७१२ मै-श-च-जै-काक्र-कात-शा-वो×	गतौ (प) इति सभ्याः—क्षी। क्षी-सा-हे।	<√पेस् (पेसृ) गतौ (प)। √पेश् (पेशृ) गतौ (प) इति सभ्याः—क्षी। वेसति—निघ. २/६=कान्तिकर्मा। √विस् (विस) ४/१११ प्रेरणे (प) मै।

ग—प्रणोदितं वेसरयुग्यमध्वनि-शिशु. १२,१९=सङ्कराश्वो वेसरः (सर्वङ्कषा)। [मुद्गादिवेसवाराणाम्—सुश्रु. १,४६-श. क. द्रु.]।

छ—(नक) वेसर = नासाभूषणम्।

+√वेह् (वेहृ) १/६३५ श×	प्रयत्ने (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। यत्ने—वो।	√बाह् (बाहृ) १/ प्रयत्ने (आ)। √एष् (एषृ) १/ प्रयत्ने (आ) सा।
√वेह् (वेहृ) १/६३४	'प्रयत्ने' इत्येके—सा।	

क—उआइक्-, उआइग्=न्युब्जीभावे, वेष्टने। लिथु.-विजगोति=कम्पने, चलने-वा. पॉकर्नीः।

छ—√वेहरना=दीर्णे, द्विधाभावे, ईषद्दीर्णे (देश.-वेहर)।

√वै (ओवै) १/९०६ श×	शोषणे (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। शोषे—वो।	√वा २/गतिगन्धनयोः (प)। √पै १/ शोषणे (प)।
√वा/४	समीरणे, वाते—ह्वि.।	

क—उऐ-, उई=निर्बलम्, शिथिलम्। इच्छा-वा. पॉकर्नीः।

ग—न वायन्ति-ऋ. ७,६७,८। वायति-ऐंआ. ३,२,४।

ङ—√वा (अक)=शोषणे। वाइ-से. ६,५२।

ङ—√वाअ (अक)= शोषणे। वाअइ-संक्षि. ३६।

√व्यच् (व्यच) ६/१३ श×	संभवे (प) क्षी । व्याजीकरणे— मै-सा-च-जै-काकृ-कात-शा-हे । व्याजे सम्भवे—वो ।	वि+√अच् (अचु) १/ गतौ (प)। √विच् (विचिर्) ७/ पृथग्भावे (प)। √विज् (ओविजी) ६/ भयचलनयोः (आ)। √व्यज् (व्यज) ६/ व्याजीकरणे (प)।

ग—विव्याच पृथिवी—ऋ. ३,३६,५; ऐब्रा. ४,१२; ऐआ. १,२,२ ।

√व्यज् (व्यज) ६/१४ मै-सा-च-जै-काकृ-कात-शा-हे-वो×,श	व्याजीकरणे (प) क्षी । व्यजने—ह्वि. ।	वि+√अज् (अज) १/ गतिक्षेपणयोः (प)।

ग—(चर्मैव समविव्यक्तमांसि-ऋ.७,६३,१) । विव्यजुर्व्यजनैः-मभार. ९,४८ ।

√व्यथ् (व्यथ) १/७५६ श ×	भयचलनयोः (आ) क्षी-मै-सा-शा-हे । भयसञ्चलनयोः—सा । 'दुःखचलनयोः'—इति दुर्गः—क्षी,-सा । दुःखे—च । चलभीत्योः—जै । दुःखभयचलनयोः—काकृ । दुःखे चाले भये—वो ।	√विथ् (विथृ) १/३२ याचने (आ)।

क—उद्र्ऐथ्-, उद्इथ् =कम्पने-वा. पॉकर्नीः ।

ग—व्यथते-शब्रा. २, २, २, २; तैआ. १, ११, ७ । व्यथन्ति-गी. २, १५; १४, २ ।

ङ—(√वह=पीडायाम्, प्रहारे-पण्ह. २,१-पत्र. १००) ।

√व्यध् (व्यध) ४/६८ श	ताडने (प) क्षी-मै-सा-च-जै-काकृ-

कात-शा-हे ।
ताडे—वो ।

√व्यध्, √विध् छेदने—ह्वि. ।

क—ऊआइध्-, ऊइध् = विभागे-वा. पॉकर्नीः ।

ग—अति······विध्यति-ऋ. ४,८,८ । अवविध्यति-तै. २,५,५,६ । विध्यति-शत्रा. ३,५,२,८ । आविद्धम्-वा.रा. २,५७,२७ = दुःखाभिहतम् (तिल.) ।

घ—व्यधति—विनय. २, २०२ (पद्ये प्रयुज्यते) ।

ङ—√विद्ध (सक) = वेधने, छेदने । विद्धइ—नाट-रत्ना. ७ ।

ङ—√विंध (सक) = वेधने, छेदने । विंधइ, विंधेज्जा-पि. ४८९; भग. ।

ङ—√विह (सक) = ताडने-उत्त. २७,३; सुख. २७,३ ।

ङ—√ वेह (सक) = वेधने । वेहइ—पि. ४८९ ।

छ—√बीधना, √बींधना, √बेधना } = वेधने, पाशने ।

√व्यय् (व्यय) १/८६६ गतौ (उ)
शा-जै× क्षी-मै-सा-च-काकृ-कात-शा-हे ।
गतौ—वो ।

√वय् (वय) १/ गतौ (आ) ।
वि+√अय् (अय) १/ गतौ (आ) ।
वि+√इ (इण्) २/ गतौ (प)
वि+√अय् (अय) १/ गतौ (प)

ग—व्ययति-ह्वि. । मया न प्रस्तुतम्, लिटि, लङि, लुङि, लृङि च वस्तुत एतज्ज्ञानात् । एतेषु लकारेषु च न रूपाप्तिः । सुबहवो व्ययम्-मभार. १२, १३८८ ।

+√व्युष् (व्युष) ४/८ दाहे (प)
क्षी-श-च-जै-काकृ-कात-शा-हे-वो× मै-सा ।

वि+√उष् (उष) १/दाहे (प)
√प्युष् (प्युष) ४/ दाहे (प) वो ।

ग—व्योषम्-सुश्रु. १/४४ = त्रिकटुः ।

+√व्युष् (व्युष) ४/१०९ विभागे (प)
क्षी-श-च-जै-काकृ-कात-शा-हे-वो× मै-सा ।

√व्युस् (व्युस) ४/१०७ विभागे (प) केचित्—सा ।

√बुस् (बुस) ४/१०७ विभागे (प) अपरे तु —सा।
√व्युष् (व्युष) ४/ विभागे (प)।

ग—(उषसो व्युष्टिषु–ऋ. २,३४,१२ <√उच्छ् विवासे इत्यतो व्युत्पत्तिरिति क्षीरस्वामिभानुजिदीक्षितौ–नामलिङ्गानुशा. ३, ३, ३८)।

√व्ये (व्येञ्) १/९९१ श — संवरणे (उ) क्षी-मै-सा-च-काकृ-कात-शा-हे। जै—भ्रष्टोऽर्थः। वृतौ—वो। — √वी २/ गतिव्याप्तिप्रजन-कान्त्यस........(प)।
√व्या, √वी/४ ? — ह्वि.।

ग—अभि व्ययस्व–ऋ. ३,५३,१९; अप व्ययति–ऋ. ७,८१,१। अव्ययत्–तैब्रा. २,७,१५,२; अव्ययम्–२,४,३,१।

√व्रज् (व्रज) १/२५१ जै×, श — गतौ (प)। क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।
√व्रज् (व्रज) १/२१५ — गतौ—तरङ्गिणीकाश्यप-संमतास्तु—सा। — <√ध्रज् (ध्रज) गतौ (प)।

क—व्रेग् (ज्)-(तथा व्रेर्ग्-?)=प्रेरणे—वा. पॉकर्नीः।

ग—अभिव्रजद्भिः–ऋ. १,१४४,५। व्रजति–षब्रा. १,४। वव्राज–शब्रा. ११,५,१,४। व्रजन्–तैआ. २,१२,१।

घ—वजति–सुत्तनिपात १२१।

ङ—√वज्ज (सक)=गतौ। वज्जइ–नाट–मृच्छ. १९३।

ङ—√वच्च (सक)=गतौ। वच्चइ–महा.।

च—√वुच्च (सक)=गतौ। वुच्चइ–कुमा.।

छ—√भजना, √भगना } (<व्रजनम्)=पलायने, द्रुतगतौ।

छ—√व्रजना* (<व्रजनम्)=गतौ।

√व्रञ्ज् (व्रजि) १/२१६ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	गतौ (प) तरङ्गिणी-काश्यपसंमतास्तु—सा । सा ।	<√ध्रञ्ज् (ध्रजि) गतौ (प)। √धृञ्ज् (धृजि) १/ गतौ (प) सा । √व्रज् (व्रज) १/ गतौ (प)।

क्षीरतरङ्गिण्यां तु √ध्रञ्ज् (ध्रजि) धातुरेव न तु √व्रञ्ज् (व्रजि) इति। समुपलभ्यमानायां तात्कालिक्यां पुस्तकलिपौ ध्रजिगताधोभागस्य घृष्टत्वान्मृष्टत्वाद् वा सायणेन ध्रजिः 'व्रजि' इत्यवबुद्धः स्यात्। यद्ययं कस्मिंश्चित् प्रदेशविशेषे व्यवहृतपूर्वः स्यात् तर्हि नूनं √व्रज् १/२५१ धातौ स्वयम्भ्वनुस्वारद्योतकः।

√व्रण् (व्रण) १/४४३ श-काकृ-कात×	शब्दार्थः (प)। >< क्षी-मै-सा-च । शब्दे—जै-शा-हे । रुति—वो । शब्दे ?—ह्वि. ।	√व्रण् (व्रण) १/ शब्दार्थः (प) क्वचित्—सा । √वण् (वण) १/ शब्दार्थः (प)। √क्वण् (क्वण) १/ शब्दार्थः (प)। √ध्वण् (ध्वण) १/ शब्दार्थः (प)। √भण् (भण) १/ शब्दार्थः (प)। √भ्रण् (भ्रण) १/ शब्दार्थः (प)। √रण् (रण) १/ शब्दार्थः (प);व्+√रण्=√व्रण्।

ग—व्रणतीति व्रणः-सुश्रु. २,२,१ ।

√व्रश्च् (ओव्रश्चू) ६/१२ श	छेदने (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । छेदे—वो ।

क—उ॒र्एर्=छेदने । विस्तारः-उ॒र्एर्क्-(श्र्)-,उ॒र्-क्-ः वा. पॉकर्नीः। उ॒र्स्क्-, (* उ॒र्क्-स्क्), उ॒ऋस्क—ः रसन्. व्रस्क—जू. पॉकर्नीः।

ग—अव॰॰ वृश्च—ऋ. १,५१,७। अपिवृश्च—ऋ. ८,४०,६। वृश्चति—शब्रा. ३,६,४,६; वृड्धि-शांआ. ४,७।

+√व्री (व्रीङ्) ४/३२ श	वृणोत्यर्थे (आ)। क्षी-मै-सा-जै-शा। वरणे—च-काकृ-कात-हे। वृत्याम्—वो।	√वृ (वृञ्) ५/८ वरणे (उ)।
वृणोत्यर्थः=	वरणम्—क्षी।	सैन्धव इव व्लीयन्ते-मैत्र्युप. ६,३५।
+√व्री ९/३३ श×	वरणे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। वृत्याम्—वो।	√व्ली ९/ वरणे (प)। √व्री (व्रीङ्) ४/ वृणोत्यर्थे (आ)। √वृ (वृञ्) ५/८ वरणे (उ)। व्लीनाति-तैत्रा. २,२,५,१।

√व्ली > √व्री इति क्रमः।

√व्रीड् (व्रीड) ४/१९ श	चोदने (प)। क्षी-मै-सा-च-काकृ। चोदने लज्जायां च—कात। लज्जायाम्—जै-शा-हे।	√विल (विल) १०/७१ क्षेपे (प) सा। √वी २/ गति····कान्त्य-सन····(प)। वीळयतिश्च व्रीळयतिश्च
[४/] १/	ह्वि.।	संस्तम्भकर्माणौ पूर्वेण प्रयुज्येते-निरु. ५,१६,१।

चोदनम् = लज्जा—क्षी।

क—ऊराङ्-:-वा. पॉकर्नीः।

ग—व्रीडमाना-मभार. ४,११८५; नातिव्रीडे-भा. पु. ८,२२,७।

ङ—√विल (अक) = लज्जायाम्-स. ३७५॥

√व्रुड् (व्रुड) ६/१०९ श-काकृ× (मै-कात-शा-हे-√ब्रुड्)	संवरणे (प)। क्षी-सा-च-कात। उत्सर्गे—जै। संघाते—मै-शा-हे। भ्रुड्यर्थ (=संवृतिसंहत्योः) -मज्जयोः—वो। मज्जने—ह्वि.।	√बुल (बुल) १०/६६ निमज्जने (प)।

ग—व्रुडित०—ह्वि.। मया नोपलब्धम्।

छ—√बूड़ना; (वर्णविपर्य०)-√डूबना=मज्जने। महाराष्ट्रि.-बूळणे।

अ √व्लङ्ग् १/३८१ व्लगि गत्यर्थः (प) √वल्ग् (वल्ग) १/ गत्यर्थः
पा क्षी-मै-सा-श-जै-काक्र- च। (प)। वर्णवि० √व्लग्।
णि कात-शा-हे-वो× अनुसरणे—ह्वि.।
नी ग—अभिव्लङ्गैः-ऋ. १,१३३,४; अभिव्लग्या-१,१३३,१।
यः √व्लङ्ग् (व्लङ्ग) इति भाष्यम्, √व्लङ्ग् (व्लगि) इत्यसमञ्जसम्, 'अभिव्लग्या' इति वैदिकप्रयोगे (निपातनात्) क्यपि नुम्लोपाभावप्रसङ्गात्। √व्लग् इति धातूल्लेखस्य काप्यसत्त्वात् 'व्लङ्ग्यात्' इति प्रयोगानुपलम्भाच्च।

√व्ली ९/२९ वरणे (प)। √व्री ९/३३ वरणे (प)।
श×(काक्र-कात- क्षी-मै-सा-जै-काक्र- √री ९/२३b गतौ (प) च।
√व्ली) कात-शा-हे।
गतौ—च-हे।
वृत्यां गत्यां च—वो।

ग—नैनं दक्षिणा व्लीनाति-तैब्रा. २,२,५,१। व्लिनाति-शब्रा. १,६,३,३१। प्र····व्लीनः-अ.वे. ११,९,१९।

+√शंस् (आङः शसि) १/६२२ इच्छायाम् (आ)
च-जै-श× क्षी-मै-सा-काक्र-कात-शा-हे।
आशिषि—वो।
√शंस् (आङः शन्सु) ६२० इच्छायाम्-सा-च-जै।
क्षी-मै-श-काक्र-कात-
शा-हे-वो×

ग—आशंसेत भूयाम्-अ.वे. १२,४,४४। आह वा····शंसन्ते-शब्रा. १,६,४,१७। चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्-वा. रा. २,१२,७० (=इच्छायाम्, आशिषि)। इत्याशशंसे करणैरबाह्यैः-रघु. १४,५० (=आशिषि)।

√शंस् (शन्सु) १/७२१ स्तुतौ (प) शंसति-निघ. ३/१४=
श× क्षी-मै-सा-च-जै-काक्र- अर्चतिकर्मा।
कात-शा-हे।
स्तुतौ, च=हिंसायाम्
इति दुर्गः—क्षी।
कथने—मै।

हिंसायाम्—हे
हिंसास्तुत्योः—वो।

क—शेंस् = कथने-वा. पॉकर्नीः।

ख—अवे. संहैति=घोषणायाम्, प्रकाशने-पी. टी. एस. पालि-इँग्लिश्-कोशात्।

ग—देवाय शस्ति शंस-ऋ. ४,३,३। शंसति-शब्रा. ५,५,५,१६। शोंसामः (शंसामः) शांब्रा. १४,३।

घ—संसति-जातक ५,७७।

ङ—√संस (सक)=(१) कथने, (२) प्रशंसायाम्। संसइ-चेइय. ७३७; भवि.।

+√शक् (शक) ४/७४ श — विभाषितो मर्षणे (उ)।
क्षी-मै-सा-जै-शा-हे।
क्षान्तौ—च।
क्षमायाम्—काक्ष-कात।
शक्तौ—वो।

शक्तिः=दिवादिपक्षे क्षमा, स्वादिपक्षे सामर्थ्यम्-दुर्गादा.।

ग—मर्तुं न शक्यामि-मभार. १,६७५४। न शक्यामः प्रवेष्टुं विवरं भुवः-वा. रा. २,५९,२२; मभार. १,८३९५। शक्यसे-गी. ११,८।

घ—सक्कति-नेत्तिपकरण २३।

√शक् (शक्ल) ५/१५ श — शक्तौ (प) क्षी-मै-सा-च-जै,-काक्ष (उ),-कात-शा-हे-वो। — √सप् ४/१७ a शक्तौ (प) काक्ष।

क—शक्-(शेक्?) = सामर्थ्ये-वा.पॉकर्नीः।

ग—यदि शक्नवाम-ऋ. १,२७,१३; ५,४०,९। शक्नोति-काब्रा. १,१,४,२४। शग्धि-[ऋ. ८,६१,१३] तैब्रा. ३,७,११,४। भौवादिकोऽपि—शकेम-मन्त्रब्रा. २,४,४।

घ—सक्कोति-दीघ. १,२४६; विनय. १,३१।

ङ—√सक्क (अक)=सामर्थ्ये। सक्कइ, सक्कए-महा.।

छ—√सकना=शक्तौ।

√शङ्क् (शकि) १/८३ शङ्कायाम् (आ)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
त्रासशङ्कयोः—वो।

क—केंग्, कॅंग्, तथा—केक्-, कॅंक्=(वि) लम्बने, अधीनतायाम्। तालव्य-वर्णेन—शक्, शङ्क्। लैति. शंक्तॉर=संशयः, विलम्बः, दीर्घसूत्रता—वा. पॉकर्नीः।

ग—शङ्केत-शब्रा. ३, ८, ३, ३६। क्षेत्रज्ञो नाभिशङ्कते-मनु. ८, ९६=शङ्केत (मन्वर्थ.)।

घ—संके-जातक ३, २५३।

ङ—√संक (अक)=(१) संशये, (२) भये। संकइ, संकए-संक्षि. ३०।

छ—√सुंकना *† / √सँकाना *† }=संदेहे, (२) भये।

छ—√सनकना (<शङ्कनम्)=भ्रान्तमतौ, उन्मादे।

+√शच् (शच) १/१६३ शच× — व्यक्तायां वाचि (आ)
क्षी-मै-सा-जै-काकृ-कात-शा-हे।
वाचि—वो।

शची-निघ. १/११=वाङ्नाम। शचीर्मदन्तः (=शच्या वाचा स्तुतिभिः-दुर्गाचार्यः)-निरु. १,११,१।

ग—शचीपती शचीभिः-ऋ. ७, ६७, ५; कया शचीनां भवथः शचिष्ठा-४, ४३, ३।

+√शट् (शट) १/२९६ श — रुजाविशरणगत्यवसादनेषु(प)
क्षी-मै-सा-जै-कात-शा-हे।
विशरणे—च।
काकृ—भ्रष्टः पाठः।
सादे शीर्णौ गतौ रुजि—वो।

√शद् (शद्लृ) १/८४० शातने (प)।
√सद् (षद्लृ) १/ विशरण-गत्यवसादनेषु (प)।
√शट् (शट) १/१८७निवासे (प) काकृ।

ग—शटी-भावप्रकाशः (श. क. द्रु.)=कर्चूरः। शाटक०-कथासरि. ५३,३८=पट०। शाट्यायनः=मुनिविशेषः·······

ङ—√सड (अक)=(१) विशरणे, (२) खेदे, (३) रुजायाम्, (४)-(सक) गतौ। सडइ-विपा. १,१-पत्र. १६।

ङ—√झोड (सक)=वृक्षादेः पत्राद्यादिपातने (विशरणे)। झोडइ-पि. ३२६।

छ—√सलसलाना=शनैः कण्डूाम् (रुजायाम्), २–कीटसर्पणादौ ।

+√शठ् (शठ) १/३३७ कैतवे (प)
शX
क्षी-जै-शा ।
कैतवे, च=हिंसासंक्लेश-योः—मै-काकृ-कात-हे ।
कैतवे, च=हिंसासंक्लेश-नयोः—सा ।
हिंसायां कैतवे च—च ।
वधक्लेशकैतवे—वो ।

√शठ् (शठ) १०/असंस्कार-गत्योः (प) ।

ग—वैडालव्रतिकाञ्छठान्–मनु. ४, ३० ।

+√शण् (शण) १/७९१ दाने (प) इत्यपि
श-च-जैX
दुर्गः—क्षी ।
क्षी-मै-काकृ-कात-शा-हे-वो ।
'गतौ' इत्येके—मै ।
दाने, च=गतौ—सा ।

<√श्रण् (श्रण) दाने (प) ।
√शण् १/२०७ q शब्दे (प) काकृ ।
√सन् (षणु) ८/ दाने (उ) ।
√सट्ट् १०/३२ a दाने (प) काकृ ।
√चण् (चण) १/ दाने (प) ।

ग—शण०–अ.वे. २,४,५; शब्रा. ३,२,१,११ । माषैश्चतुर्भिः शाणः स्यात्–भावप्रकाशे (श. क. द्रु.) । शणं तैलं घृतञ्चैव–मभार. १, १४५, ११ । वस्त्राणां प्रवरा शाणी–मभार. ३, १२०२७=शणसूत्रमयी पट्टिका । शाणीप्रायाणि वस्त्राणि–वि. पु. ६ अंशे प्र. अध्यायः ।

+√शण्ड् (शडि) १/२७७ रुजायां सङ्घाते च (आ)
श
क्षी-मै-सा ।
रुजायाम्—च-काकृ-कात ।
संघाते रुजायां च—जै-शा-हे ।
सङ्घरुजोः—वो ।

√शट् (शट) १/ रुजाविश... (प) ।
√सट् १/९२ c संघाते (प) काकृ ।
√शण्ड् १/१८३ k हिंसागत्योः (प) काकृ ।
√झट् (झट) १/ संघाते (प) ।
√जट् (जट) १/ संघाते(प)
√श्लोण् (श्लोणृ) १/ संघाते (प) ।

ग—इन्द्रो हन्ति वृषभं शण्डिकानाम्-ऋ. २,३०,८। शण्ड०-शब्रा. ४,२, १,४; तैब्रा. १,१,१,५। शाण्डिल०-शब्रा..९, १, १, ४३।

√शद् (शद्लृ) १/८४० शातने (प) क्षी-मै-सा-च-काकृ-कात-शा-हे। अवशातने—जै। शाते—वो। पतने--ह्वि.। √सद् शातने १/ गतिविशरण-योश्च (प) जै।
श

शातनम् = तनूकरणम्—क्षी।

ग—शीयते-तैब्रा. ३, १२, ७, २। अवशीयताम्-शौ. १८, ३, ६०. [पाधा० ७/३/७८ इति शीयादेशः, शदेः शितः १/३/६० इति तङानौ]। शशाद······? शत्स्यति······?

ङ—√झड (<√शद्)=(१) विशरणे, गलने, (२) हीनभावे। वक्क-झडंत-कुमा.। कवक्क-झडिज्जंता-आव. १।

+√शद् (शद्लृ) ६/१४५ शातने (प) क्षी-मै-सा-च-काकृ-कात-हे।
श-जै-शा-वो ×

√शप् (शप) १/९८४ आक्रोशे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। क्रोशे--वो।
श ×

क—कुप्-वा.पॉकर्नीः।

ग—(यद्वा शेप उतानृतम्-ऋ. १, २३, २२) शपति-शब्रा. १४, ९, ४, ११; शपामहे; ३, ८, ५, १०। शपे-वा. रा. २, ११, १३=शपथपूर्वकं कथयामि (तिल.)।

घ—सपति-जातक ५, १०४।

ङ—√सप(सक)=(१) आक्रोशे, (२) आह्वाने। सपइ-विसे.२२२७।

ङ—√सव (सक)=(१) आक्रोशे, (२) आह्वाने। सवइ-गा. ३२४; ४००।

छ—√सापना * † =शपने, आक्रोशे।

[+]√शप् (शप) ४/५७ आक्रोशे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। क्रोशे—वो।
श

√शम् (शमु) ४/८८ उपशमे (प)
श
क्षी-मै-सा-च-काकृ-
कात ।
उपशमने—जै-शा-हे ।
शमे—वो ।

√शम् १/८०३cc···· अदर्शने (प) मित् ।
श-जै-शा-हे-वो ×

क—कॅम् (आx)=श्रान्तौ–वा. पॉकर्नीः ।

ग—कस्ते गात्राणि शम्यति–वा. सं. २३,३९ । शाम्यति–शब्रा. १,२,५,२६ । शमयति–शांब्रा. ३,३ । शमयते–शब्रा. १,७,४,१७ । प्रशाम्यति–मनु. ४,१८६ = विनश्यति (मन्वर्थ.) ।

ङ—√सम (अक)=(१) शान्तौ, (२) नाशे, (३) आसक्तौ । समइ, समंति–कुमा. ।

ङ—√सम (सक)=उपशमे, नाशे–धर्मा. ३ ।

+√शम्ब् (शम्ब) १/४१७ गतौ (प) <√शर्ब् (शर्ब) गतौ (प) ।
मै-श-च-जै-काकृ- (क्षी-हे)-वो ।
कात-शा ×

अर्बेत्यादौ रेफस्थाने नकारं कौशिको मन्यते—क्षी ।

+√शर्ब् (शर्ब) १/४१७ गतौ (प) √शव् (शव) १/ गतौ (प) ।
श×(काकृ-√शर्ब्) क्षी-मै-सा-च-जै-काकृ- √शब् १/३०८b गतौ (उ)
शा-हे । काकृ ।
गतौ हिंसायां च— √चर्ब् (चर्ब) १/ गतौ (प) ।
कात । √सर्ब् (षर्ब) १/ गतौ (प) ।
गतौ हिंसे च—वो ।

+√शर्व् (शर्व) १/५८१ हिंसायाम् (प) √शॄ ९/१६ हिंसायाम् (प) ।
श×(काकृ-कात- क्षी-मै-सा-च-काकृ-
√शर्व्) कात-शा-हे ।
हिंसने—जै ।
हिंसे—वो ।

ग—शर्व०–अ.वे. ६,९३,१; तैआ. १०,१६; रघु. ११,९२। यद्यपि (उणा. १/११५ इति) √शॄ धातुतः शर्वशब्दो व्युत्पाद्यते तथापि पाणिनेर्मूर्धन्यत्वादयमुदाहरणत्वेन प्रस्तूयते। अति ष्कन्दति शर्वरी–ऋ.५,५२,३। अयं शब्दोऽपि कॄशॄ० २/१२१ इत्युणादिसूत्रेण सिद्ध्यति, इहापि पूर्वोक्तो हेतुः प्रस्तुतौ। पाणिनिर्ज्यायानुणादिकारात्।

+√शल् (शल) १/४८७ श-जै×	चलनसंवरणयोः (आ) क्षी-जै-सा। चलने—च-काकृ। चलने संवरणे च— कात-शा-हे। स्तृतौ चलने च—वो।	√शल् (शल) १/५४८ आशुगमने (प)। √शल् (शल) १/८२७ गतौ (प)। √शलङ्क् १/४९४ c चलने (आ) काकृ।

ग—अभक्ष्या ब्राह्मणैर्मत्स्याः शल्कैर्ये वै विवर्जिताः–मभार. १२,३६,२३ (=संवरणे)।

छ—√सलना = पङ्काद्यन्तर्गतौ–बुं. ख.।

+√शल् (शल) १/५४८ मै-सा-श-जै-काकृ- शा×	आशुगमने (प) क्षी-च। आशुगतौ—कात-हे। वेगे—वो।

ग—शल०–मभार. १,५७,५=वासुकिवंशीयसर्पविशेष०। शला दोषणी कृणुतात्–तैब्रा. ३,६,६,३ (शल्याँ अशनिभिर्दिहानः–ऋ. १०,८७,४)।

√शल् (शल) १/८२७ श	गतौ (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो। गमने—जै। उच्छलने—हि.।	√क्षल् (क्षल) १/ सञ्चये, च=सञ्चलने (प)।

ग—स्वच्छोच्छलदुद्या०–कथासरि. २५,९; उच्छलद्भिः–५०,७। चलद्वारिवीचिच्छटोच्छलच्छ०–शिशु. ३,३७।

+√शल्भ् (शल्भ) १/३८७ श× (काकृ–√शल्)	कत्थने (आ) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो। कत्थने—जै-काकृ-कात। त्रुटिः ? 'कत्थने' इति भाष्यम्।	√शाल् १/ कत्थने (आ) वो।

+√शव् (शव) १/७१७ शX(च–√वश् [वश]) गतौ (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। गतौ विकारे च—वो।

√शु १/९२४ गतौ (प)। शवति–निघ. २/१४=गतिकर्मा। √शब् १/३०८ b गतौ (प) काक्र। √श्वि (टुओश्वि) १/ गतिवृद्ध्योः (प)।

शवतिर्गतिकर्मा काम्बोजेष्वेव भाष्यते। विकारमस्यार्येषु भाषन्ते शव इति–निरु. २,८ तुल. महाभाष्ये ५२ पृ.। श्वा शुयायी शवतेर्वा स्याद् गतिकर्मणः–निरु. ३,१८,९। शूरः शवतेर्गतिकर्मणः–निरु. ३,१३,१।

ग—आ भर शूर शवः–ऋ. ६,१९,६। शवः–शब्रा. १,८,३,१८; १३,८,३,१८।

√शश् (शश) १/७१८ शX प्लुतिगतौ (प) क्षी-जै-हे। प्लुतगतौ—मै-सा-च-काक्र-कात-शा। प्लवने—वो। प्लवने—ह्वि.।

ग—शशति–ह्वि.। मया नाधिगतम्। शशः क्षुरं प्रत्यञ्चं जगार–ऋ. १०,२८,२। शश उल्कुषीमान्–अ.वे. ५,१७,४। शश आस्कन्दमर्षति–वा. सं. २३,५६। द्विरंशे च शशो महान्–मभार. ६,१९२।

+√शष् (शष) १/६८० शा-च-काक्र-कातX हिंसार्थः (प) क्षी-मै-सा। हिंसायाम्—जै-शा-हे। वधे—वो।

√शस् (शसु) १/ हिंसायाम् (प)।

ग—शष्पम्–का. श्रौ. १९,१,२३; ऐब्रा. ८,५; शब्रा. १२,७,२,८।

√शस् (शसु) १/७२० शX हिंसायाम् (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। वधे–वो।

क—कुस्=छेदने–वा. पॉकर्नीः।

ग--यच्छसने न गावः-ऋ. १०,८९,१४ = शसने = विशसनस्थाने-सायणः। वि शसन्ति-शब्रा. ३,८,१,१४। विशशास-वा. रा. १,१३,३५।

+√शाख् (शाखृ) १/१२६ व्याप्तौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
शX

√श्लाघ् (श्लाघृ) १/१२७ व्याप्तौ (प)।
√श्राख् १/३७ b व्याप्तौ-(प) काकृ।
शाखाः खशयाः शक्नोतेर्वा—निरु. १,४,१९।

ग--शाखा-ऋ. १,८,८;७,४३,१; १०,९४,३; अवे. ३,६,८ (शाखति=गगनं व्याप्नोतीति)। साङ्गाः सशाखाः-मनु. ९,७६। कतमां शाखामधीषे-कथासरि. ४९,१५६।

+√शाड् (शाडृ) १/२८६ श्लाघायाम् (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। श्लाघे—वो।
शX (जै-च-√श्लाड्) (कात-√शाट्)

√शल्ल (शल) १०/ श्लाघायाम् (आ)।
√शठ् (शठ) १०/ श्लाघायाम् (आ)।
√शट् (शट) १०/ श्लाघायाम् (आ)।

ग--शालते-मल्लि. (किरा. ५,४४)। शालयः-वा. रा. ३,२२, १७। मनु. ९,३९। निसर्गशालीनः स्त्रीजनः—मालतीमा. ४। (लडयोश्चैकत्वात्)।

+√शान् (शान) १/९८० तेजने (उ)
शX

क्षी-मै-सा-च-जै-शा-हे।
अवतेजने—काकृ-कात।
तेजे—वो।

ग—शीशांसति-अ. वे. प्राति. १,८७-टीका.।
ङ—√साण (सक)=तेजने। साणिज्जदि-शौ., नाट.।

+√शास् (आङः शासु) १/६२२ इच्छायाम् (आ) दुर्ग <√शंस् (आङः शसि) इच्छायाम् (आ)।
मै-सा-श-च-जै-काकृ-शा-हेX

इत्याह—क्षी।
क्षी-कात।
आशिषि—वो।

√शास् (आङः शासु) २/१२ इच्छायाम् (आ)
श-कात × क्षी-मै-सा-च-जै-
काक्ट-शा-हे ।
आशिषि—वो ।

√शास् (आङः शास)··· इच्छायाम् (आ)
मै-श-च-जै-काक्ट-शा-वो × इति दौर्गाः-क्षी ।
क्षी-सा-कात-हे ।

क—वयमाशास्महे-ऋ. १,३०,११ । आशास्ते-तैब्रा. १,१,८,४ । आशास्य-वा. रा. २,६,३ = प्राथ्यं । सङ्कल्प्येत्यर्थः (तिल.); देवानां कच्चिदाशास्ते प्रसादम्-५,३३,३२ । योऽस्माकं नित्यमाशास्ते महत्त्वम्-मभार. ३,१२४३० । आशास्यमन्यत्पुनरुक्तभूतम्-रघु. ५,३४ = आशीःसाध्यम् आशंसनीयं वा-(संजी.) ।

√शास् (शासु) २/६४ अनुशिष्टौ (प)
श क्षी-मै-सा-च-जै-काक्ट-
कात-शा-हे ।
शासने—वो ।

क—शास्-, शूस्=आज्ञायाम्, अनुशासने ।

ख—अवे. सस्न = प्रतिमा, आदर्शः । शासनम्, आदेशः-वा. पॉकर्नीः ।

ग—शास्ति-शब्रा. १३,१,६,१; मनु. ७,१८ = आज्ञां करोति (मन्वर्थ.) । शाधि-वा. रा. २,१०५,१० = शिक्षयसि (तिल.); १,२८,१३ = आज्ञापय-(तिल.) ।

ङ—√सास (सक)=दण्डने, (२) शिक्षायाम्, (३) आज्ञायाम् । कर्म. सासिज्जइ, सासइ-नाट-मृच्छ. २००; कुप्र. ३९९ ।

ङ—√साह (सक) = कथने । साहइ, साहेइ-उव.; काल.; महा. ।

छ—√साँसना* † (<शासनम्) = शासने, (२) तर्जने, (३) दुःखने ।

+√शि (शिञ्) ५/३ निशाने (उ) √शो ४/३६ तनूकरणे (प) ।
श (जै-√श्रि [श्रिञ्]) क्षी-मै-सा-च-जै-
काक्ट-कात-शा-हे-वो ।
निशातने—हे ।
३/ ह्वि. ।

निशानम् = तनूकरणम्-क्षी ।

ग—(निशित०-कठो.३,१४; मभार. ३,२३८९-√शो ४/३६ धातुतो व्युत्पाद्यते-शाच्छोः ७/४/४१) ।

√शिक्ष् (शिक्ष) १/६०१
शX

विद्योपादाने (आ)
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
शिक्षणे—वो ।

√शक् (शक्लृ) ५/ शक्तौ (प)
√शक्+सन् =शिक्षते–ऐब्रा.
१,१३ ।

ग—यत्र नार्युपच्यवं शिक्षते–ऋ. १,२८,३ । अशिक्षितास्त्रं पितुरेव मन्त्र-वित्–रघु. ३,३१=अभ्यस्तवान् (संजी.) ।

ङ—√सिक्ख (सक)=शिक्षणे, अभ्यासे । सिक्खइ–गा. ४७७; ५२४ ।
छ—√सीखना (<शिक्षणम्) ।

+√शिङ्घ् (शिखि) १/१३९
क्षी-मै-श-च-जै-काकृ-
कात-शा-हे-वोX

गत्यर्थः (प) सम्मतायां
तु—सा ।

√शीक् (शीकृ) १/७८
गत्यर्थः (आ) ।
√सिङ्घ् १/३८w गतौ (प)
काकृ ।
√शेखृ १/४१२x गतौ (आ)
काकृ ।
√शिखण्ड् १/१९२ निर्बीजे
(प) काकृ ।

ग—शिङ्खप०–N. pr. eines Mannes Tāran. 87 fg. शेखर०–कुमारसं. ७,३२ । वशिष्ठहनुः शिङ्गीनि कोश्याभ्याम्–वा. सं. ३९,८ । √शिङ्घ्>शिङ्ग् ?

√शिङ्घ् (शिघि) १/१५९
शX

आघ्राणे (प)
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो ।

गं—शिङ्घाणिकः–आपस्त. १,१६,१४ ।
छ—√सूँघना=आघ्राणे ।

√शिञ्ज् (शिजि) २/१७
श (काकृ–√सिञ्ज्
[सिजि])

अव्यक्ते शब्दे (आ)
क्षी-मै-सा-जै-काकृ-
कात-शा-हे ।
शब्दे—च ।
अस्फुटध्वनौ—वो ।

√शिञ्ज् १०/ अस्फुटध्वनौ
(आ) वो ।
√पिञ्ज् (पिजि) २/ अव्यक्ते
शब्दे (आ) ।
शिङ्क्ते–निरु. २,९,१;
९,१८,१ ।

ग—अयं स शिङ्क्ते-ऋ. १,१६४,२९; योषेव शिङ्क्ते वितताधिधन्वं ज्या-६,७५,३। हयशिञ्जितनिर्घोष०-वा. रा. २,४०,१९; (पद्मिन्यः) भ्रमरैः परि-शिञ्जिताः-४,४८,१०। भूषणानां तु शिञ्जितम् (१,५,१६) इत्यमरसिंहो न्यक्कृतः।

ङ—√सिंज (अक)=अस्फुटशब्दे-सुपा. ५०; सण.।

+√शिट् (शिट) १/२९९ श — अनादरे (प) क्षी-मै-सा-च,जै (आ), काकृ-कात-शा-हे-वो। — √सिट् (षिट) १/ अनादरे (प)। √शिण्ड् १/१८३ हिंसागत्योः (प) काकृ।

+√शिल् (शिल) ६/८३ श — उञ्छे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। — √सिल् (षिल) ६/ उञ्छे (प)। √शिल्ल् १/१७७ गतौ (प) च। शिला=शिरा-महानारायणो. (इन्दिरेशे स्तु. २,९३)।

उञ्छः=उद्धृतशस्यशेषाहरणम्-दुर्गा.

ग—शिला०=पाषाण०-मनु. २,२०४। परिगणितोञ्छशिलाशन०-मभार. १२, १३९४३। प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते-मनु. १०,११२; शिलानप्यु-ञ्छतः-३,१००।

+√शिष् (शिष) १/६७७ श× — हिंसार्थः (प) क्षी-मै-सा-कात। हिंसायाम्—च-जै-काकृ-शा-हे। वधे—वो।

√शिष् (शिष्लृ) ७/१४ श — विशेषणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। विशेषे—वो। — √शास् (शासु) २/ अनुशिष्टौ (प)। √शिस्त् १०/४८ मर्यादायाम् (प) काकृ।

विशेषः=उपरञ्जनम्-दुर्गादासः।

ग—शिनष्टि-ह्वि.। मया नावाप्तम्। शिष्यते-गोब्रा. १,२,४। तल्लोकं शिंषति-तैब्रा. ३,३८,२ (तौदादिकः ?)। शिष्यति-पै. ३,४; यो. ३,३५ (दैवादिकः ?)।

√शी (शीङ्) २/२१ — स्वप्ने (आ)
श — क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।

क—शाइ=शयने ।
ख—अवे. सएते=शेते–वा. पॉकर्नीः ।

ग—उप शेषे–ऋ. १०,१८,८; अशयत्–१,३२,७ (भौवादिकः ?) । शेते–शब्रा. १,१,१,११ । शयते–तैब्रा. २,५,४,३ (भौवादिकः) ।

ङ—√सय (अक)=शयने । सयइ, सए, सएज्जा–कप्प.; आचा. १,७,८,१३ ।

+√शीक् (शीकृ) १/७२ — सेचने (आ)
श (काकृ-कात-√सीक् [सीकृ]) — क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
सर्पे सेके च—वो ।

क—शिक्-, शीक्=बिन्दुशो वर्षणे, सेके–वा. पॉकर्नीः ।
ग—पक्षैः सजलशीकरैः–वा. रा. ४,५१,३८ ।

+√शीक् (शीकृ) १/७८ — गत्यर्थः (आ)
मै-श-च-जै-काकृ-कात-शा× — क्षी-सा ।
गतौ—हे ।
सर्पे सेके च—वो ।

>√सेक् (सेकृ) गत्यर्थः (आ) अन्ये–क्षी ।
√सेक् (सेकृ) १/ गत्यर्थः (आ) ।
√सेक् (सेकृ) १/ गत्यर्थः (आ) ।

शीकेरर्थभेदात् पुनः पाठः । अत एव चन्द्रो नैनमध्यैष्ट–क्षी । पूर्वधातोरभिन्नोऽयमर्थभेदार्थं पार्थक्यं नीतः ।

+√शीभ् (शीभृ) १/३८० — कत्थने (आ)
श× — क्षी-मै-सा-च-काकृ-कात-शा-हे-वो ।
कथने—जै ।
'कथने' इति त्रुटिः, 'कत्थने' इति भाव्यम् ।

√चीभ् (चीभृ) १/ कत्थने (आ) ।
शीपालमिव–ऋ. १०, ६८,५ ।
√शल्भ् (शल्भ) १/ कत्थने (आ) ।

ग—शीभ्याय च नम ऊर्म्याय–वा. सं. १६,३१ । "शीभो जलप्रवाहो वा शीभः क्षिप्रो वा" इति तट्टीकायां महीधरः । प्र यात शीभमाशुभिः–ऋ. १,३७,१४; ३,३३, १२; १०,४४,२ ।

+√शील् (शील) १/५२३ समाधौ (प)। क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो। श

√शील् (शील) १०/ उपधारणे (प)। तत्पुरुच्छेपस्य शीलम्-निरु. १०,४२,२।

समाधिः=सेवानुभावनं प्रवृत्तिर्वा—दुर्गादासः।

ग—स्वप्नशीलज्ञाः-वा. रा. २,६५,१४=स्वप्नभावज्ञाः (तिल.)। शीलति-नैष. ८,६४=करोति (प्रका.)।

+√शु १/९२४ गतौ (प)। मै-काक्र-कात-वो× क्षी-सा-च-जै-शा-हे।

'शुवादीनां दीर्घश्च' इति शवतेः क्वनि शूरशब्दो व्युत्पाद्यते-१/९२२ सा। √श्वि (टुओश्वि) १/ गतिवृद्धयोः (प)। √शव् (शव) १/ गतौ (प)।

ग—यदश्वत् तन्मेध्यमभूत्-शब्रा. १०,६,५,७।

+√शुक् (शुक) १/११८ गतौ (प)। सा-श-जै-शा× क्षी-मै-च-काक्र-कात-हे। सर्पे—वो।

पूर्ववत्।

ग—शुकेषु मे हरिमाणं रोपणकासु दध्मसि-ऋ. १,५०,१२; वा.सं. २४,३३।

√शुच् (ईशुचिर्) ४/५४ पूतिभावे (उ)। क्षी-च-जै-कात-शा-हे। पूतिभावे—मै-सा-काक्र। शौचे विशरणे क्लेदे—वो। श

√शुच्य् (शुच्यी) १/ अभिषवे (प)। √शुच् १/२३१ a अभिषवे (प) काक्र।

पूतीभावः=क्लेदः—क्षी।

क—उत्तरधातुवत्।
ग—यदुपनद्धस्य संशुच्यति-शब्रा. ६,४,४,२०।
छ—√सौंचना (<शोचनम्)=शौचे, (२) हस्तपादादिप्रक्षालने।

√शुच् (शुच) १/१८० श× | शोके (प)। क्षी-मै-सा-च-काकृ-कात-शा-हे-वो। पाके—जै। 'पाके' इति पाठो मुद्रण-दूषितः ? प्रकाशे—ह्वि.। | शोचति-निघ. १/१७=ज्वलतिकर्मा।

क—शॉइक् (च्)=द्युतौ।

ख—अवे. उप-सुक्स्त। न. पर्सि. सोक्सतन=प्रकाशने-वा. पॉकर्नीः।

ग—शोचति-शब्रा. १,४,१,२६; गी. १२,१७।

ङ—√सोच (सक)=नाट-मृच्छ १८१; णाया. १,१-पत्र. ४७।

ङ—√सोअ (सक) = (१) शोके, (२) शुद्धौ। सोअइ, सोएइ, सोयंति-से. १,३८; आचा.।

+√शुच्य् (शुच्यी) १/५१४ मै-सा-श-जै× (काकृ-√शच्। शुच्यतीति व्याख्यातः) | अभिषवे (प)। क्षी-च-काकृ-कात-शा-हे-वो। | <√चुच्य् (चुच्यी) अभिषवे (प) इति दुर्गः-क्षी। √शूच् (शूच) १/२३१ b अभिषवे (प) काकृ।

√शुच्य् (शुच्य) १/५१४ क्षी-श-च-जै-काकृ-कात-शा-हे-वो। | अभिषवे—मै। मै-सा। | √सु (षु) ५/१ अभिषवे (प)।

+√शुठ् (शुठ) १/३३८ .च×, श | गतिप्रतिघाते (प) इति दुर्गः—क्षी। क्षी-मै-सा-जै-काकृ-शा-हे। गतिप्रतीघाते—कात। खोटने—वो। | <√शुण्ठ् (शुठि) गतिप्रतिघाते (प)। √शुण्ठ् (शुठि) १/ शोषणे (प)।

√शुण्ठ् (शुठि) १/३२२ | खण्डप्रमर्दनयोः (प)। इति क्वचिद् धातुकोशे पठ्यते—सा। | शुण्ड०—सभार. ७,१५,७३।

√शुण्ठ् (शुठि) १/३३८ मै-श-च-जै-काकृ-कात-शा ×	गतिप्रतिघाते (प)। क्षी-सा-हे। खोटने—वो।	<√शुण्ठ् (शुठि) गति-प्रतिघाते (प)। √शुण्ड् १/१८३ m गतौ (प) काकृ।
+√शुण्ठ् (शुठि) १/३४१ श×	शोषणे (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√गुण्ठ् १/१२१ c शोषणे (प) च। √हिण्ट् १/१०१ शोषणे (प) काकृ।

ग—शुण्ठी-का. श्रौ. २५,१३,२०। शुण्ठ०-तै. १,८,१७,१; ५,६,१६,१; काठ. १३,५; का. श्रौ. २२,११,२९। तस्मिन् गतार्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे-आर्यासप्तश. २७१।

√शुध् (शुध) ४/७८ जै×, श	शौचे (प)। क्षी-मै-सा-च-काकृ-कात-शा-हे-वो।	√शुन्ध् (शुन्ध) १/ शुद्धौ (प)। √शुन्ध् (शुन्ध) १०/ शौचकरणे (प)।

क—शॉइ=प्रकाशे, द्युतौ, स्पष्टम्। शु-ध्—:

ख—अवे. सुद्धु=शुद्धम्, पवित्रीकरणम्-वा. पॉकर्नीः।

ग—शुध्यति-तांब्रा. १४,११,२८; जाबालदर्शनो. ४,५४। (पापम्) वेदाभ्यासेन शुध्यति—मनु. ११,४६=नश्यति (मन्वर्थ.)।

ङ—√सुज्झ (अक)=शौचे। सुज्झइ-महा.।

ङ—√सोह (प्रयोज.)=(१) शौचे, (२) गवेषणे, (३) शोधने। सोहेइ-उव.।

छ—√शोधना (<शोधनम्)=(१) शौचे, (२) व्यवस्थितौ, (३) अन्वेषणे।

+√शुन् (शुन) ६/५६ श	गतौ (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।	√शु १/ गतौ (प)। शुनम्-निघ. ३/६= सुखनाम। शुण्ड० = करिकर०-मभार. ७,३५,३५।

ग—शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्-ऋ. ४,५७,४; शुनं हुवेम मघवानमिन्द्रम्—३, ३०,२०। कुक्कुटं शुनकं तथा-मभार. १३,१२७,१६। इन्द्राय शुनासीराय पुरोडाशम्-तै. १,८,७,१।

√शुन्ध् (शुन्ध) १/७१ श×	शुद्धौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हें-, वो (उ) ।	√शुध् (शुध) ४/शौचे (प) । √शुन्ध् (शुन्ध) १०/ शौचकरणे (प) ।

क—, ख—द्रष्ट.√शुध् ४/७८ ।

ग—सूर्याया रूपाणि ब्रह्मा शुन्धति—ऋ. १०,८५,३५ । शुन्धति—तैब्रा. ३,२,३,१ । शुन्धन्ते—काब्रा. २.१,३,७ ।

+√शुभ् (शुभ) १/४३२ क्षी-श-च-जै-कात । शा-हे-वो×	भाषणे हिंसायां च (प) मै भाषणे—सा-काकृ । हिंसायाम् इति—दैवमैत्रे-. यादयः—सा ।	√शुभ् (शुभ) १/ दीप्तौ (आ) ।

उत्तरधातोः प्रपञ्चः । अत्र 'भाषणे' इत्यस्य स्थाने 'भासने' इति भाव्यम् ।

√शुभ् (शुभ) १/७४१ श	दीप्तौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । दीप्तौ हिंसने च—वो ।	√शुभ् (शुभ) १/ भाषणे हिंसायां च (प) ।

ग—बभ्रू यामेषु शोभेते—ऋ. ४,३२,२३; सं देवैः शोभते वृषा—९,२५,३; ऐब्रा. ३,१० ।

ङ—√सोभ (अक)=द्युतौ । सोभंत—सुज्ज. १९ ।
छ—√सोभना * † (<शोभनम्)=शोभने ।
छ—√सोहना, छ—√सोहाना } (<शोभनम्)=शोभने, सज्जने ।

+√शुभ् (शुभ) ६/४२ श	शोभार्थे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । दीप्तौ (हिंसने च)—वो ।

ग—(शुभयति—तैब्रा. ३,३,१,५) ।
ङ—√सुह (अक)=द्युतौ । सुहइ—वज्जा. १४ ; पिंग. ।
छ—√शुभाना, छ—√सुहाना, छ—√स्वहाना * } =शोभने ।

+√शुम्भ् (शुम्भ) १/४२६ श×

भाषणे हिंसायां च (प)।
क्षी-मै-सा-जैं-कात-शा-हे।
भाषणे—च-काक्र।
हिंसार्थः--कात।
दीप्तौ हिंसने च—वो।
'भासने' इति दुर्गः-क्षी।
क्षी-सा।

>√सुम्भ् (षुम्भ) भाषणे हिंसायां च (प) इति गुप्तः-क्षी।
√सुम्ब् १/२०६ r मर्दने (प) काक्र।

ग—निशुम्भः-मालतीमा. ५,२२=हिंसायाम्; महावीरच. २,३३=कुब्जीभावे। शुम्भः प्रतापवान्-मार्क. पु. ८८,२।

√शुम्भ् (शुम्भ) ६/४३ श

शोभार्थे (प)
क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
दीप्तौ हिंसने च—वो।

√शुभ् (शुभ) १/ दीप्तौ (आ)।
√शुभ् (शुभ) ६/ शोभार्थे (प)।
निशृम्भा निश्रथ्यहारिणः-निरु. ६,४,१ (=शीघ्रहारिणः-दुर्गाचार्यः)।

ग—शुम्भत स्वाः-ऋ. १०,९५,९। परि शुम्भति (अग्निम्)-अ.वे. १३,१,५१।

√शुष् (शुष) ४/७० श

शोषणे (प)
क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
शोषे—वो।

√श्वस् (श्वंस) २/५८ प्राणने (प)।
√श्वि (टुओश्वि) १/ गतिवृद्धयोः (प)।
√उष् (उष) १/ दाहे (प)।
√व्युष् (व्युष) ४/८ दाहे (प) मै।

क—सौस्-,सुस्=शोषणे। लिथु. सुसु; सुस्ति=रूक्षभावे। लेट्टिश्. सुस्त=शोषणे।

ख—अवे. हुस्क=शुष्कम्, शोषणे। न. पर्सि. उस्क=शुष्कम्, शोषणे-वा. पॉकर्नीः।

ग—प्रति शुष्यतु यशो अस्य–ऋ. ७,१०४,११ । शुष्यति प्राण ऋतेऽन्नात्–शब्रा. १४,८,१३,१।

ङ—√सूस (अक)=शोषणे । सूसइ, सूसंति–कुमा. ३७४ ।
ङ—√सुक्ख (अक)=शोषणे—गा. ४१४; वज्जा. १४६ ।
ङ—√सुक्क (अक)=शोषणे । सुक्कइ–विसे. ३०३२; पव. १७ ।
छ—√सूकना } =शोषे।
छ—√सूखना }

+√शूर् (शूरी) ४/४६ श — हिंसास्तम्भनयोः(आ)। क्षी-मै-सा। हिंसास्तम्भयोः—जै-शा। हिंसायाम् —च। हिंसायां स्तम्भे च—काक्र कात-हे। स्तम्भे हिंसे—वो। — √शॄ ९/ हिंसायाम् (प)। √सूर् ४/ स्तम्भे हिंसे (आ) वो।

ग—शूरणः=मूलविशेषः (अर्शोघ्नः)।
छ—सूरन (<शूरणः)।

+√शूल् (शूल) १/५२६ श× — रुजायाम् (प) क्षी-च-जै-काक्र-कात-शा-हे-वो। रुजायां संघाते च—मै-सा। — √शूर् (शूरी) ४/ हिंसास्तम्भनयोः (आ)। √शॄ ९/हिंसायाम् (प)।

ग—शूल०–ऋ. १,१६२,११; शब्रा. ६,७,१४ । ततस्ते शूल आरोप्य–मभार. १, १०७,१२ । शूलः=रोगविशेषश्च ।

छ—सूर (<शूलः)=उदररोगः–बुं. ख.।
छ—√सूलना (<शूलनम्)=पीडने, कुन्तेन छेदने ।

+√शूष् (शूष) १/६७० मै-श-च-काक्र-कात-शा× — प्रसवे (प) इति चरकः–क्षी। क्षी-सा-जै-हे-वो। — <√सूष् (षूष) प्रसवे (प)। √शुष् ४/७० शोषणे (प)। √सु (षु) १/प्रसवैश्वर्ययोः (प)। √शूय् १/ प्रसवे—वो।

√श्वस् (श्वस) २/ प्राणने (प)।
शूषम्–निघ.२/९=बलनाम;
३/६=सुखनाम।

ग—इन्द्राय शूषमर्चति–ऋ. १, ९, १०;=(बलम्); प्रमन्महे शूषम्–१,६२,१। इन्द्रियं शूषमिन्द्रे वयोऽदधत्–वा. सं. २८, ४१। (शूषा=शाकम्–क्षी)।

√शृध् (शृधु) १/७५२ श — शब्दकुत्सायाम् (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। पर्दे—वो। औद्धत्ये, साहसे—ह्वि.।

√शृध् (शृधु) १/८५८ उन्दे (आ)।
√कर्द् १/३९४b कुत्सिते शब्दे (आ) काकृ।
√गर्द् १/३९४c कुत्सिते शब्दे (आ) काकृ।
√शर्द् १/३९४d कुत्सिते शब्दे (आ) काकृ।
शर्द्धस्–निघ. २/९=बलनाम।

क—शेर्ध् (ऑ)=समूहः, आदेशः। गॉथि. हैर्द; पु. आइस्. ह्जोर्द; एँग्लो-सै. हेरॉद्; पु. उ. जं. हेर्त्=मिथः, परस्परम्।

क—(शेर्द्)–, शृद्–, श्रेद्=बलम्, साहसम्।

ख—अवे. सर्द=पतिर्वा पत्नी वा। पु. पर्सि. सर्द=पतिर्वा पत्नी वा–वा. पॉकर्नीः।

ग—शर्ध०–ऋ. ४, १,.१२; ५, ८७, १=उद्धत०, धृष्ट०। शर्धांसि स्तुकाविनाम्–ऋ. ८, ६३, १३=बलानि। शर्धति; ते–ह्वि.। मया नाप्तम्। शर्धाय गृणानः–ऋ. १०, १४७, ५ (=मरुते ?)। अवशर्धयतो गुदम्–मनु. ८, २८२–शर्धनम्=कुत्सितो गुदशब्दस्तेनावमानयतः (मन्व.)।

√शृध् (शृधु) १/८५८ शX(जै-काकृ–√सृध्) — उन्दे (उ) पूर्ववत्।
क्षी-च-जै-काकृ-शा-हे।
उन्दने—मै-सा-कात।
रुन्धे—काकृ। (लैपिकी त्रुटिः 'उन्दे' इति भाव्यम्)
क्लेदने—वो।

पूर्वस्यैव प्रपञ्चः। अर्थभेदाद् विभक्तः।

√शॄ ९/१६	हिंसायाम् (प)	√सॄ ९/१५b हिंसायाम् (प)
श	क्षी-मै-सा-च-जै-काक्-	काक्र ।
	कात-शा-हे ।	√चिरि ५/ हिंसायाम् (प) ।
	हिंसने—वो ।	

क—शेर् (शेर्)-तथा-* शेरा=शीर्णौ-वा. पॉकर्नीः ।

ग—शृणाति-ऐत्रा. ४,१३ । शृणीयात्-शब्रा. १,७,३,१९ । दैवादिकोऽप्ययम्-विशीर्यन्तीं नावमिव-मभार. ३, १५७१३; शीर्येत्-३, ५९१ । विशीर्यति-मनु. २,७४ ।

छ—√झड़ना (<शरणम् ? क्षरणम् ?) ।

+√शेल् (शेलृ) १/५४२	गतौ (प)	√शल् (शलृ) १/ गतौ (प) ।
श-काक्र×	क्षी-मै-सा-जै-कात-शा-हे ।	
	चलने—च ।	
	केल्वत् (=चालगत्योः)--वो ।	

ग—शेलु०-सुश्रु. ४, ३८=बहुवारकवृक्षः (श. क. द्रु.) । शेलुं गव्यं च-मनु. ५, ६=बहुवारकवृक्षफलम् ।

+√शेव् (शेवृ) १/४९८	सेवने (आ)	√सेव्(षेवृ) १/ सेवने (आ) ।
श-कात-शा-हे-वो×	क्षी-च-जै ।	√खेव् (खेवृ) १/ सेवने (आ)।
	सेचने—मै-सा-काक्र ।	शेवम्-निघ.३/६=सुखनाम ।
		शेवधिः (=सुखनिधानम्)-निरु. २, ४, १ ।

ग—शेवारे वार्या पुरु-ऋ. ८,१,२२; शेवलं शुने-अ. वे. १, ११,४ । शेवधिम्-ऋ. २, १३, ६; मित्रं न शेवं दिव्याय जन्मने-ऋ. १, ५८, ६ ।

उणादौ (१/१५०) शेवशब्दः शीङ्धातोर्निष्पाद्यते, निरुक्ते (१०,१७,१) तु √शिष् धातोः । तद्यथा—"शेव इति सुखनाम शिष्यतेर्वकारो नामकरणोऽन्तस्थान्तरोपलिङ्गी" इति ज्ञायते यद् व्युत्पत्तिरव्यवस्थिता कल्पिता च भवति । शेवादौ शेवदर्शनात् सेवनार्थकः √शेव्धातुर्निश्चेयः । शेव्यते इति शेवम्=सुखम् ।

+√शै १/१०२	पाके (प)	√श्रै १/ पाके (प) ।
क्षी-मै-श-च-जै-काक्र-	सा ।	√स्रै १/ पाके (प) ।
कात-शा-हे-वो×		

√शो ४/३६ तनूकरणे (प)
श क्षी-मै-सा-च-जै-काक्र-
कात-शा।
तक्ष्णे--हे।
निशाने--वो।
६/ ? ह्वि.।

क—शोइ (: शाइ-) तथा शो (: शू-) = निशाने-वा. पॉकर्नी:।
ग—श्यति-शब्रा. ४,३,२,३।

+√शोण् (शोणृ) १/४४७ वर्णगत्योः (प)
श× क्षी-मै-सा-जै-काक्र-
कात-शा-हे।
वर्णे—च।
गते वर्णे—वो।

ग—शोण०-ऋ. १, ६, २; १, १२६, ४; १, ३, ३५; वा. रा. ५, १२, ३५। शोणितम्-मनु. ११, २०८=रुधिरम्। भागीरथीं शोण इवोत्तरङ्गः-रघु. ७, ३६=गतौ।

+√शौट् (शौटृ) १/२८७ गर्वे (प)
श-काक्र-शा-हे× क्षी-मै-सा-च-जै-कात-
वो।

√शौण्ड् १/८० गर्वे (प)
काक्र।
√शौड् १/३७० गर्वे (प)
शा। २३३—हे, वो।

ग—शौटीर्यम्-वा. रा. २, ७३, २३ = गर्वः (तिल.); शौटीरः-मभार. ५, १२६, ३१; १२, ८३, ४३ = गर्वान्विते।

√श्चुत् (श्चुतिर्) १/४० क्षरणे (प) कौशिकस्तु-
श-च-जै-काक्र-कात× क्षी।
क्षी-मै-सा-शा-हे।
क्षरे--वो।

<√श्च्युत् (श्च्युतिर्)
क्षरणे (प)।
श्चोतति-निघ. २/१४=
गतिकर्मा।
√चुत् (चुतिर्) १/ क्षरणे
(प) द्रमिडाः—क्षी।
√च्युत् (च्युतिर्) १/३९
आसेचने (प.)।

क्षरणम् = स्रवणम्-क्षी।

ग—श्चोतन्ति-ऋ. ३, १, ८; ३, २१, २; तैब्रा. ३, ६, ७, १। श्चोतति-शब्रा. ४, ५, २, ६।

+√श्च्युत् (श्च्युतिर्) १/४० शX — क्षरणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। क्षरे—वो। — >√श्चुत् (श्चुतिर्) क्षरणे (प)। पूर्ववत्।

ग—भल्लातकनिश्च्युतितः स्नेहः-सुश्रु. २,५१,१७। लोचनेनामृतश्च्युता-कथासरि. १०१, ३०४; गिरा प्रेममधुश्च्युता-१०३, ६४। निश्च्योतन्ते सुतनु कबरीविन्दवो यावदेते-मालतीमाध. ८, २ (इति मालत्यां गणकृतानित्यत्वम् इति दुर्गादासः)। एतास्ता मधुनो धाराश्च्योतन्ति सविषास्त्वयि-उत्तरराम. ३, ३४। श्च्योतद्भिः समधिकम्-शिशु. ८, ६३।

√श्नथ् (श्नथ) १/५३६ a क्षी-मै-सा-श-जैX (कात-हे-√स्नथ्) (सा-√श्नथ्-मैसू.-संस्करणे) — हिंसायाम् (प) च-काकृ-कात-हे हिंसार्थः—शा। वधे—वो। — ><√श्रथ् (श्रथ) १/७९२ हिंसार्थः (प) मित्।

अपाणिनीयः ?
क—शन्त्=छेदने, प्रवेशने।
ख—अवे.स्नत् (थ्)=ताडने; स्नत् (थ्) न्ति-वा. पॉकर्नीः।
ग—अभिश्नथः-ऋ. १०, १३८, ५। श्नथत्—तैब्रा. २, ८, ५, १।

+√श्मील् (श्मील) १/५१९ च-जै-X, श — निमेषणे (प) क्षी-मै-सा-काकृ-कात-शा-हे-वो। — √मील् (मील) १/ निमेषणे (प)। √क्ष्मील् (क्ष्मील) १/ निमेषणे (प)। √स्मील् (स्मील) १/ निमेषणे (प)।

निमेषणम्=सङ्कोचः—क्षी।
स्पष्टो विकासो वर्णोपजनत्वात्।

√श्यै (श्यैङ्) १/९४८ शX — गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। — श्यामं श्यायतेः-निरु. ४, ३, २।

ग—बलिष्ठं श्यायति-शब्रा. ४, ३, १, १९। यावन्नाश्यायते वेदिः-रघु. १७, ३७=शुष्यति (संजी.)। हिमो यच्च शीयते—तैब्रा. ३, १२, ७, २ (कर्मवा.)।

+√श्रङ्क् (श्रकि) १/८१
शा-च×

गत्यर्थः (आ)
क्षी-मै-सा-कात।
गतौ—जै-काकृ-शा-हे।
सर्पे—वो।

√श्रक् १/३३८ c गत्यर्थः (आ) च।
√श्लङ्क् (श्लकि) १/ गत्यर्थः (आ)।
√श्रङ्ग् (श्रगि) १/ गत्यर्थः (प)।

+√श्रङ्ग् (श्रगि) १/१५०
शा-जै-काकृ-कात-शा×

गत्यर्थः (प)
क्षी-मै-सा-च।
गतौ—हे।
व्रजे—वो।

√श्लङ्ग् (श्लगि) १/ गत्यर्थः (प)।
√सिङ्ग् १/३८ w गतौ (प) काकृ।

+√श्रण् (श्रण) १/७९१
शा-च×

दाने (प)
क्षी-मै-च-जै-काकृ-कात-शा-हे-वो।
'गतौ' इत्येके—मै।
दाने, च = गतौ—सा।

ग—विश्राणनात्-रघु. २,५४=दानात्-संजी.।

+√श्रथ् (श्रथ) १/७९२
शा-च-जै-काकृ-कात-शा-हे-वो×
(सा-√श्रथ्-मैसूर-संस्क.)

हिंसार्थः (प) मित्
क्षी-मै-सा।

श्रथति-निघ. २/१९=वध-कर्मा।
√श्नथ् (श्नथ) १/ हिंसायाम् (प) च।
√श्रथ् (श्रथ) १०/ दौर्बल्ये (प)।

ग—अनु श्रृथिताः-ऋ. १०,९४,११ [√श्रथ् > < श्रृथ्]।

+√श्रन्थ् (श्रथि) १/३४
शा×(काकृ√श्रृन्थ्)

शैथिल्ये (आ)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

√श्रथ (श्रथ) १०/३१७ दौर्बल्ये (प)।
√श्लथ् (श्लथ) १०/ दौर्बल्ये (प)।

ग—श्रन्थति ? पाशान्-अ. वे. १४,१,५७।

√श्रन्थ् (श्रन्थ) ९/३९ च×,श	विमोचनहर्षयोः (प) क्षी। विमोचनहर्षणयोः— मै। विमोचनप्रतिहर्षयोः—सा। प्रतिहर्षविमोचनयोः —जै। विमोचनप्रतिहर्षणयोः —काकृ (उ), -हे। मोचनप्रतिहर्षणयोः —कात-शा। मोक्षे प्रतिहृषि—वो।	√श्रथ (श्रथ) १०/ दौर्बल्ये (प)। √श्रन्थ् (श्रथि) १/ शैथिल्ये (आ)।

ग—अश्रथ्नन्-ऋ. २,२४,३; श्रथ्नीते-९,६९,३।

√श्रन्थ् (श्रन्थ) ९/४२ क्षी-श-जै-काकृ-कात-शा-हे-वो×	सन्दर्भे (प) मै मै-सा-च।	पूर्ववत्।

पूर्ववत्। अर्थभेदात् पृथगुपन्यस्तः।

√श्रम् (श्रमु) ४/९१ श	तपसि खेदे च (प) क्षी-मै-सा-काकृ-कात-शा। खेदे—च। क्लेशने—जै। खेदतपसोः—हे। तपःखेदयो—वो।	√क्लम् (क्लमु) ग्लानौ (प)। √ग्लै १/ हर्षक्षये (प)। √श्राम् (श्राम) १०/ मन्त्रे (प) वो।

क—क्लेम्-, क्लेम्-, क्लृम्=श्रान्तौ, शैथिल्ये-वा. पॉकर्नीः।

ग—सिन्धवो न श्राम्यन्ति-ऋ. २,२८,४; ९,२२,४। श्राम्यति-शब्रा. १४,४,३,३१[३]।

ङ—√सम्म (अक)=(१) खेदे, (२) श्लथे। सम्मइ-उत्त. १,३७।

√श्रम्भ् (श्रन्भु) १/३९० मै-श-जै-काकृ-कात-शा-हे-वो×	प्रमादे (आ) क्षी-सा-च। विश्वासे—ह्वि.।	√स्रम्भ् (स्रन्भु) १/ प्रमादे (आ)।

क—श्रभ्=विश्वासे–वा. पॉकर्नीः ।
ग—कामेषु विश्रम्भेत–भा. पु. ३,३,२३; विश्रभ्य–१,१९,२४ ।

√श्रा १/८०३ पाके (प) मित्त्वार्थः
श× पाठः ।
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो ।
स्वेदे—वो ।
प्रयोज. ह्वि. ।

ग—श्रपयति–वा. सं. १,२२; शब्रा. ३,८,३,२० । श्रपयामास–वा. रा. १,१४,३६ ।

+√श्रा २/४२ पाके (प) √श्रै १/ पाके (प) ।
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो ।

ग—यदि श्रातो जुहोतन–ऋ. १०,१७९,१ । श्रातम्–शब्रा. १४,३,१,३०[२] ।

√श्रि (श्रिञ्) १/८८२ सेवायाम् (उ) ।
श (काकृ √श्री) क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
सेवने—वो ।

क—श्लाइ=नतौ, आश्रये ।
ख—अवे. स्रित (: स्रय्)=(आ) श्रितम्–वा. पॉकर्नीः ।

ग—शिश्राय मघवा कामम्–ऋ. १०,४२,६ । श्रयते–ऐब्रा. २,२; शब्रा. १,६,४,७ । श्रयति–अक्षु. ११ ।

ङ—√सय (सक)=सेवायाम् । सयंति–भग. १३,६–पत्र. ६१७ ।

+√श्रिभ् (श्रिभु) १/४३० हिंसार्थः (प) <√स्रभ् (षृभु) हिंसार्थः
इत्यन्ये—मै । (प) ।
बा. ग. पलसुले-महाशयो विस्मृतवान् ।

√श्रिम्भ् (श्रिभि) १/४३१ हिंसार्थः (प) <√स्रम्भ् (षृम्भु) हिंसार्थः
इत्यन्ये—मै । (प) ।
बा. ग. पलसुले-महाशयो विस्मृतवान् ।

√श्रिष् (श्रिषु) १/६९२
शX

दाहे (प)।
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
वेष्टने, आलिङ्गने—ह्वि.।

√श्लिष् (श्लिषु) १/
दाहे (प)।

ग—कस्येमां हृदि श्रेषाम सुष्टुतिम्-ऋ. ४,४३,१; अभिश्रिषः-८,१,१२; कौ. १,२४४।

छ—√सेंकना (<सेंखना<सेखना<श्रेषणम्)=भर्जने (दाहे)।

√श्री (श्रीञ्) ९/३
श

पाके (उ)।
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
पचे—वो।

√श्रा २/ पाके (प)।

क—शेरX-, शेरXइ=मिश्रणे-वा. पॉकर्नीः।

ग—अभिश्रीणन्ति-ऋ. ९,९३,३; कौ. २,७५०। श्रीणाति-शब्रा. ४,१,४,८[३]; तांब्रा. ८,२,११। श्रितः-वा. रा. २,५६,२८=पक्वः (तिल.)। (शृतम्-तै. ६,५,९,१)।

√श्रु १/९२५
श-च-जै-शा-हे-वोX

गतौ (प)।
क्षी।
श्रवणे—मै-सा-काकृ-कात।

√श्रु ५/१६····
क्षी-मै-सा-काकृ-कातX,श

श्रवणे—च-जै-शा-हे।
गतौ—जै-हे।
गतौ श्रुतौ—वो।

क—श्लॉइ=श्रवणे-श्लेउ्ए-, श्लू-वा. पॉकर्नीः।

ख—अवे.-सुरुनओइति=शृणोति।

ग—रेवन्तं हि त्वा शृणोमि-ऋ.८,२,११; १,१०९.५। शृणोति-शब्रा.१,४,३,४। शृणुते-तैब्रा. ३,१,५,७।

ङ—√सुण (सक)=श्रवणे। सुणइ, सुणेइ-महा.।

छ—√सुनना = श्रवणे।

+√श्रेक् (श्रेकृ) १/८१
क्षी-श-कात-हे-वोX
(च-√श्रक्)
(जै-√शेक्)

गत्यर्थः (आ) मै।
मै-सा-च।
गतौ—जै-काकृ-शा।

√सेक् (सेकृ) १/ गत्यर्थः (आ)।
√स्रेक् (स्रेकृ) १/ गत्यर्थः (आ)।

√श्रै १/९०४ शX	क्षी-मै-सा-च-जै-काकृ-शा-हे । पचने—वो । स्वेदे—वो ।	√श्लेक् (श्लेकृ) १/ ३३३० गतौ (आ) जै । √स्रै १/ पाके (प) । √श्रा १/ पाके (प) मित्त्वार्थः पाठः ।

क—शेराX–, शेरXइ = मिश्रणे–वा. पॉकर्नीः ।

ग—श्राय–तैआ. ४, २, ६ ।

+√श्रोण् (श्रोणृ) १/४४८ शX	संघाते (प) क्षी-मै-सा-च-जै-काकृ-काव-शा-हे-वो ।	√श्लोण् (श्लोणृ) १/ च = संघाते (प) ।

ग—प्रतिश्रोणः स्यात्–ऋ. २, १५, ७ । यदश्लोणत् तच्छ्रोणा–तैब्रा. १, ५, २, ९; ३, १, २, ५ । श्रोणिः–बृहत्संहि. ५६, ७ = कटिः । उज्ज्वलदत्तः श्रोणशब्दसिद्ध्यर्थमुणादि-(३/६)-टीकायां √श्रु श्रवणे बाहुलकात् 'नः' इत्युक्तवान्, तन्न सङ्गतम् "यदश्लोणत् तच्छ्रोणा" इति तैत्तिरीयब्राह्मणात् । उणादौ श्रोणिशब्दोऽपि√श्रुधातोः "वहिश्रिश्रुष्विति" उणा. ४/५१–साध्यते तदपि न मनोरमम्, "श्रोणिः श्रोणतेर्गतिचलाकर्मणः ।श्रोणिश्चलतीव गच्छतः"–इति ४, ३, २, निरुक्तवचनसत्त्वात् ।

+√श्लङ्क् (श्लकि) १/८२ श-चX	गत्यर्थः (प) क्षी-मै-सा-कात । गतौ—जै-काकृ-शा-हे । सर्पे—वो ।	√स्रङ्क् (स्रकि) १/ गत्यर्थः (आ) मै । √स्लङ्क् १/४१२ee गतौ (आ) काकृ ।
+√श्लङ्ग् (श्लगि) १/१५१ श-जै-काकृ-कात-शाX	गत्यर्थः (प) क्षी-मै-सा-च । गतौ—हे । व्रजे—वो ।	√श्रङ्ग् (श्रगि) १/१५० गत्यर्थः (प) ।
√श्लथ् (श्लथ) १/८०४ क्षी-सा-श-च-जै-काकृ-कात-शा-हे-वोX	हिंसार्थः (प) मित् मै । शैथिल्ये—ह्वि. ।	√श्लथ (श्लथ) १०/ दौर्बल्ये (प) ।

ग—श्लथद्दुकूलं संनह्यती–भा.पु. ८,१२,२१; श्लथद्वसन०–१०,१६,३१; १०,३३, ११ । दृढ आश्लथेत–भा. पु. ५,५,९ । श्लथ०–शिशु. ७,६२ = शिथिल० ।

√श्रिष् (श्रिषु) १/६९२
शX

दाहे (प)।
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
वेष्टने, आलिङ्गने—ह्वि.।

√श्लिष् (श्लिषु) १/
दाहे (प)।

ग—कस्येमां हृदि श्रेषाम सुष्टुतिम्-ऋ. ४,४३,१; अभिश्रिषः-८,१,१२; कौ. १,२४४।

छ—√सेंकना (<सेंखना<सेखना<श्रेषणम्)=भर्जने (दाहे)।

√श्री (श्रीञ्) ९/३
श

पाके (उ)।
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
पचे—वो।

√श्रा २/ पाके (प)।

क—शेराx-, शेरxइ=मिश्रणे-वा. पॉकर्नीः।

ग—अभिश्रीणन्ति-ऋ. ९,९३,३; कौ. २,७७०। श्रीणाति-शब्रा. ४,१,४,८[3]; तांब्रा. ८,२,११। श्रितः-वा. रा. २,५६,२८=पक्वः (तिल.)। (शृतम्-तै. ६,५,९,१)।

√श्रु १/९२५
श-च-जै-शा-हे-वोX

गतौ (प)।
क्षी।
श्रवणे—मै-सा-काकृ-कात।

√श्रु ५/१६....
क्षी-मै-सा-काकृ-कातX, श

श्रवणे—च-जै-शा-हे।
गतौ—जै-हे।
गतौ श्रुतौ—वो।

क—श्लॉइ=श्रवणे-श्लेउ्‌ए-, श्लु-वा. पॉकर्नीः।

ख—अवे.-सुरुनओइति=शृणोति।

ग—रेवन्तं हि त्वा शृणोमि-ऋ.८,२,११; १,१०९.५। शृणोति-शब्रा.१,४,३,४। शृणुते-तैब्रा. ३,१,५,७।

ङ—√सुण (सक)=श्रवणे। सुणइ, सुणेइ-महा.।

छ—√सुनना = श्रवणे।

+√श्रेक् (श्रेकृ) १/८१
क्षी-श-कात-हे-वोX
(च-√श्रक्)
(जै-√शेक्)

गत्यर्थः (आ) मै।
मै-सा-च।
गतौ—जै-काकृ-शा।

√सेक् (सेकृ) १/ गत्यर्थः (आ)।
√स्रेक् (स्रेकृ) १/ गत्यर्थः (आ)।

√श्रै १/९०४ श×	क्षी-मै-सा-च-जै-काक्र- शा-हे। पचने—वो। स्वेदे—वो।	√श्लेक् (श्लेकृ) १/ ३३३० गतौ (आ) जै। √स्रै १/ पाके (प)। √श्रा १/ पाके (प) मित्त्वार्थः पाठः।

क—शेरा x-, शेर x इ = मिश्रणे-वा. पॉकर्नीः।

ग—श्राय-तैआ. ४, २, ६।

+√श्रोण् (श्रोणृ) १/४४८ श×	संघाते (प) क्षी-मै-सा-च-जै-काक्र- कात-शा-हे-वो।	√श्लोण् (श्लोणृ) १/ च = संघाते (प)।

ग—प्रतिश्रोणः स्यात्-ऋ. २, १५, ७। यदश्लोणत् तच्छ्रोणा-तैब्रा. १, ५, २, ९; ३, १, २, ५। श्रोणिः-बृहत्संहि. ५६, ७=कटिः। उज्ज्वलदत्तः श्रोणशब्दसिद्ध्यर्थ-मुणादि-(३/६)-टीकायां √श्रु श्रवणे वाहुलकात् 'नः' इत्युक्तवान्, तन्न सङ्गतम् "यदश्लोणत् तच्छ्रोणा" इति तैत्तिरीयब्राह्मणात्। उणादौ श्रोणिशब्दोऽपि√श्रुधातोः "वहिश्रिश्रुष्विति" उणा. ४/५१-साध्यते तदपि न मनोरमम्, "श्रोणिः श्रोणतेर्गतिचला-कर्मणः।श्रोणिश्चलतीव गच्छतः"-इति ४, ३, २, निरुक्तवचनसत्त्वात्।

+√श्लङ्क् (श्लकि) १/८२ श-च×	गत्यर्थः (प) क्षी-मै-सा-कात। गतौ—जै-काक्र-शा-हे। सर्पे—वो।	√स्रङ्क् (स्रकि) १/ गत्यर्थः (आ) मै। √स्लङ्क् १/४१२ee गतौ (आ) काक्र।

+√श्लङ्ग् (श्लगि) १/१५१ श-जै-काक्र-कात-शा×	गत्यर्थः (प) क्षी-मै-सा-च। गतौ—हे। व्रजे—वो।	√श्रङ्ग् (श्रगि) १/१५० गत्यर्थः (प)।

√श्लथ् (श्लथ) १/८०४ क्षी-सा-श-च-जै-काक्र- कात-शा-हे-वो×	हिंसार्थः (प) मित् मै। शैथिल्ये—ह्वि.।	√श्लथ (श्लथ) १०/ दौर्बल्ये (प)।

ग—श्लथद्दुकूलं संनह्यती-भा. पु. ८,१२,२१; श्लथद्वसन०-१०,१६,३१; १०,३३, ११। दृढ आश्लथेत-भा. पु. ५,५,९। श्लथ०-शिशु. ७,६२=शिथिल०।

+√श्लाख् (श्लाखृ) १/१२७ शX	व्याप्तौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√श्राख् १/३७b व्याप्तौ (प) काकृ। √शाख् (शाखृ) १/ व्याप्तौ (प)।

सुस्पष्टो विकासः—√शाख् >√श्राख् >√श्लाख् इति।

√श्लाघ् (श्लाघृ १/११४ श	कत्थने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√शाल् १/ कत्थने (आ) वो।
कत्थनम् =	उत्कर्षाख्यानम्-क्षी।	

ग—भूयिष्ठं श्लाघेत-शब्रा. ११,३,३,७। श्लाघते ज्ञातिमध्ये स्म-मभार. ५,२६९५; स्वयं श्लाघति कथितेन-३,१३३०६।

ङ—√सलाह (सक)=प्रशंसने। वकृ-सलाहमाण-गा. ३४६; सम्म. १५९।

ङ—√सलह (सक) = प्रशंसने। कर्म.-सलहिज्जइ-पि. १३२।

छ—√सराहना (<सलाहणा<श्लाघनम्)=प्रशंसायाम्।

√श्लिष् (श्लिष) ४/७३ श	आलिङ्गने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। श्लेषे—वो।	√श्रिष् (श्रिषु) १/ दाहे (प)। √श्लिष् (श्लिषु) १/ दाहे (प)।

ग—श्लिष्यन्तु-मन्त्रब्रा. १,८,३। श्लिष्यति कामपि-गीतगो. १,४४; ६,७।

ङ—√लिस् (सक)=आलिङ्गने-सूअ. २,७,१०।

ङ—√लिस्स (सक)=आलिङ्गने। लिस्संति-सूअ. १,४,१ (२)।

+√श्लिष् (श्लिषु) १/६९३ शX	दाहे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√श्रिष् (श्रिषु) १/६९२ दाहे (प)।

सुस्पष्टो विकासः—√श्रिष् >√श्लिष्। हिन्द्यां √सेकना (<श्रेषणम्) इति प्रयोग उपलभ्यत एव।

+√श्लोक् (श्लोकृ) १/७४ शX	संघाते (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। संघाते वर्जने सर्जने—वो।	श्लोकः—निघ. १/११= वाङ्नाम। श्लोकः शृणोतेः—निरु. ९,९,१।
संघातः =	ग्रन्थः—सा १/७७	

ग—हंसा इव कृणुथ श्लोकमद्रिभिः–ऋ. ३,५३,१० । श्लोकाय–शब्रा. ८,२,३,३ ।

+√श्लोण् (श्लोणृ) १/४४९ श-च×	संघाते (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो ।	√शूल्र (शूल) १/५२६ रुजायां संघाते च (प) मै । √श्रोण् (श्रोणृ) १/४४८ संघाते (प)।

ग—यदश्लोणत् तच्छ्रोणा–तैब्रा. १,५,२,८, ।

+√श्वङ्क् (श्वकि) १/९२ श× (काकृ-कात-√स्वङ्क्	गत्यर्थः (आ) क्षी-मै-सा-च-कात । गतौ—जै-काकृ-शा-हे । सर्पे—वो ।	√स्वङ्क् १/४१२dगतौ (आ) काकृ । √ष्वक्क् (ष्वक्क) १/ गत्यर्थः (आ)।
+√श्वङ्ग् (श्वगि)१/१४६ क्षी-सा-श-च-जै-काकृ-कात-हे-वो×	गत्यर्थः (प) मै । गतौ—शा ।	√श्वङ्क् (श्वकि) १/९२ गत्यर्थः (आ)। √स्वङ्क् १/४१२dगतौ (आ) काकृ । √स्वङ्ग् १/४५९ गतौ(प)जै । ३८p गतौ (प)कात, वो ।
+√श्वच् (श्वच) १/१६४ श-च×(कात-√स्वच्)	गतौ (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे । गत्याम्—वो ।	√शु १/ गतौ (प)। √शुक् (शुक) १/ गतौ (प) √श्वञ्च् (श्वचि) १/ गतौ (आ)।

ग—मर्यायेव कन्या शश्वचै ते–ऋ. ३, ३३, १० ।

√श्वञ्च् (श्वचि) १/१६५ श×(कात-√स्वञ्च्)	गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । गत्याम्—वो ।	√श्वङ्क् (श्वकि) १/९२ गत्यर्थः (आ) । √श्वच् (श्वच) १/१६४ गतौ (आ)।

क—शुएेक्-(नासिक्यम्-शुऐङ्क्-) : शुक्=जृम्भणे, प्रसारणे–वा. पॉकर्नीः ।

ग—उच्छ्वञ्चस्व पृथिवि–ऋ. १०, १८, ११।

+√श्वल् (श्वल) १/५५० आशुगमने (प) √शल् (शल) १/ चलन-
क्षी-श-च-कात× मै-सा-जै-शा। संवरणयोः (आ)
(काकृ--√स्खल्) आशुगतौ--काकृ-हे। √शल् (शल) १/ आशुगमने
वेगे--वो। (प)।

ग—श्वल्०-सुश्रु. १, ९६, ७।

+√श्वल्ल् (श्वल्ल) १/५४९ आशुगमने (प) √शल् (शल) १/ आशुगमने
श×(काकृ-√स्खल्ल्) क्षी-मै-सा-च-जै-शा। (प)।
आशुगतौ—काकृ-कात- √श्वल् (श्वल) १/ आशु-
हे। गमने (प)।
वेगे—वो।

√श्वस् (श्वस) २/५८ प्राणने (प) श्वसिति–निघ. २/१९=
श क्षी-मै-सा-च-जै-काकृ- वधकर्मा।
कात-शा-हे। √सस् (सस) २/ स्वप्ने (प)।
प्राणे—वो।

क—शुएस् =श्वसने-वा. पॉकर्नीः।

ग—श्वसित्यप्सु हंसो न सीदन्–ऋ. १,६५,९। श्वसति–छागलेयो. २५:१३।

ङ—√सस (अक)=श्वसने। ससइ–रयण. ६।

छ—√सुसाना * †=सगद्गदं रोदने।

छ—√सुसाना=निद्रागतस्य श्वसने, श्वसनशब्दे–बुं. ख.।

√श्विं (टुओश्वि) १/९९४ गतिवृद्धयोः (प)
श क्षी-मै-सा-जै, काकृ (उ)-
कात-शा-हे-वो।
गतिवृद्धौ—च।

क—शॉइ=उच्छ्रयने, वर्द्धने-वा. पॉकर्नीः।

ग—विश्वयन्त्०–ऋ. ७,५०,१। अश्वयत्–शब्रा. ४,२,१,११।

छ—√सूजना (<श्वयनम्)–शोथरूपवृद्धौ।

√श्वित् (श्विता) १/७३३ श×	वर्णे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। शौक्ल्ये—वो।	√श्विन्द (श्विदि) १/ श्वैत्ये (आ)।

क—शुआइत्=द्युतौ। लिथु.-स्विन्नुओति=श्वेतम्, स्वच्छम्।

ख—अवे. स्पएत् (सुएत्)=द्युतौ—वा. पॉकर्नीः।

ग—स (अग्निः) श्वितानस्तन्यतू रोचनस्थाः-ऋ. ६,६,२; अशिश्वितत्-८,५,१; नाज्ञिभिर्येश्वितन्-१०,७८,७।

+√श्विन्द् (श्विदि) १/१० श× (काकृ-√स्विन्द्) (कात-√स्विन्द् ? -√स्विद्)	श्वैत्ये (आ) क्षी-मै-सा-च-काकृ-शा-हे। शैत्ये—जै-कात। शौक्ल्ये—वो।	√श्वित् (श्विता) १/७३३ वर्णे (आ)।

क—शुआइत = द्युतौ;-द्—वा. पॉकर्नीः

+√ष्ट्यै १/८९५ श×	शब्दसंघातयोः (प) क्षी-मै-सा-काकृ-कात। शब्दे संघाते च—च-शा-हे। जै ? संहतौ ध्वनौ—वो।	स्त्रियः स्त्यायतेरपत्रपणकर्मणः-निरु. ३,२१,२।

"ष्ट्यै स्त्यै" उभयोरुपदेशे उपादानाद् "धात्वादेः षः सः" (६/१/६४) नास्ति इति स्वामी। सायणस्तु मतमिदं स्मृत्वा निरास्थत्—१/८९५। पुरुषकारोऽप्येवमेव कृतवान् (१६ पृ.)।

ग—निष्ट्यायताम्-वा. सं. ६,१५;३८,१८। उत स निष्ट्याय सह वसति-तै. ६,२४,१।

√ष्ठिव् (ष्ठिवु) १/५५९ श (काकृ-द्वि·√ष्ठीव्)	निरसने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। निरासे—वो। थूत्कृतौ—भट्टमल्लः।	√क्षीव् (क्षीवु) १/ निरसने (प)। √क्षेव् (क्षेवु) १/ निरसने (प)। √ष्ठीव् १/ निरासे (प)
√स्थिव् (ष्ठिवु)···	'निरसने' इत्येके—क्षी।	वो।

श-च-जै-काकृ-कात-शा×(हे) क्षी-मै-सा (द्र. काशि. ६/१/६४)।

ष्ठिवेरभ्यास्य तो वेति तन्त्रान्तरीयम्-मै १/५६१। अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः-सा १/५५३। आचार्येण शिष्येभ्य उभयथा प्रतिपादनादुभयमपि प्रमाणमिति व्याख्यातारः—सा १/५५३।

क—स्प्(ह्) इएउ-: स्पिऊ—,स्पिऊ=(निरसने) थूत्कृतौ, वान्तौ—वा. पॉकर्नीः।

ग—ष्ठीवति-जैत्रा. १५७। अवनिष्ठीवतो दर्पात्-मनु. ८, २८२=श्लेष्मणाऽपमानयतः (मन्वर्थ.)। ष्ठीवन्त्यस्य च मूर्धनि-भा. पु. ११,२३,३५। तेन यत्राहमष्ठीवमभूत् तत्र तत् काञ्चनम्-कथासरि. १०८, ७८।

+√ष्ठिव्(ष्ठिवु) ४/४ क्षी-जै-शा-(काकृ-√ष्ठिव् [ष्ठिवु]) तुल. ष्ठिवेरभ्यासस्य तो वेति तन्त्रान्तरीयम्—मै १/५६१। — निरसने (प) मै। मै-सा-च-काकृ-कात-हे। निरासे—वो।

+√ष्वक्क्(ष्वक्क) १/९७ सा-श-च-जै-काकृ-कात-हे-वो×(शा-√स्वस्क्) — गत्यर्थः (आ) क्षी-मै। शा ? — ष्वःकति-निघ. २/१४=गतिकर्मा। √ष्वष्क्(ष्वष्क)१/ गत्यर्थः (आ) सा। √ष्वस्क् १/३४६ गत्यर्थः (आ) च; १/६६ गतौ (आ) जै। महाभाष्येऽपि-"ष्वस्कतीनां प्रति०" (६/१/६४) इति पठ्यते।

घ—ओ सक्कति (<अवष्वक्कते) चरियापिटक-१ a।

ङ—√सक्क (सक)=गतौ। सक्कइ-पि. ३०२।

+√ष्वष्क्(ष्वष्क) १/१०० क्षी-मै-श-च-जै× — गत्यर्थः (आ) सा-कात। गतौ—काकृ-शा-हे। सर्पणे—वो। — पूर्ववत्।

परिष्वस्कित०
ग—परिस्वस्कित० } –हालसात० परिशिष्टे ५१,५९।
परिषष्कित०

+√संस्त् (षस्ति) २/७० क्षी-श-च-काक्रु-कात×	स्वप्ने (प) मै। मै-सा-जै-शा-हे-वो।	सम्+√स्था=संस्थ>√संस्त् इति वागीशः।
√संस्त् (सस्ति) २/६७ मै-सा-श-च-जै-काक्रु-कात-शा-हे-वो×	ससने (प) इति चैके—क्षी। क्षी।	√सस् (षस)२/ स्वप्ने (प)।

+√सग् (षगे) १/७८३ श×	संवरणे (प) इति दुर्गः—क्षी। क्षी-मै-सा-च-जै-काक्रु-कात-शा-हे। संवृतौ—वो।	<√स्थग् (ष्ठगे) संवरणे (प)।

√सघ् (षघ) ५/२२ श (काक्रु√सिघ्) (कात √सग्)	हिंसायाम् (प) क्षी-मै-सा-च-जै-शा-हे। जिघांसायाम्—काक्रु-कात। हिंसे—वो। साहच्ये—ह्वि.।	>√चषघ् (चषघ) हिंसायाम् (प) इत्येके—क्षी। √सङ्घ् १/२०४ गतौ (प) काक्रु। √सह् (षह) १/ मर्षणे (आ)।

क—सेघ्-, सेंगुह्-नासिक्यम्-सेंगुह्=पराजये, जये।

ख—अवे. अज्गत=अजेयम् (:)-वा. पॉकर्नीः।

ग—असघ्नोत्-जैब्रा. १७९[२]; सघ्नुयात्-जैब्रा. १७९। सघ्यासम्-तैआ. ४,३,३। असघ्नोर्भारम्-ऋ. १,३१,३; गिरः सघत्-ऋ. १,५७,४।

√सच् (षच) १/१६१ श×	सेचने (आ)। क्षी-मै-सा-च-काक्रु-कात-हे। सेवने—शा-वो। सेवायाम्—जै। साहचर्ये—ह्वि.।	सिषक्तु सचत इति सेवमानस्य—निरु. ३,२१,५। साक्षतिराप्नोतिकर्मा—निरु. ११,२१,२

क—सेकु=अनुसरणे, संघटने। लिथु.-सेक्ति; लैति. सेकुऑर्-ई=साहचर्ये।

ख—अवे. हचैते=सचते—वा. पॉकर्नीः।

ग—ताभिः सचते गोपितिः सह-ऋ. ६,२८,३; पुष्यन् रयिं सचते-४,१२,२।

√सच् (सच) १/३९८ मै-श-काक्र-कात-शा×	समवाये (प) इति चन्द्रः—क्षी। क्षी-सा-च-जै-हे। सम्बन्धे—वो। साहचर्ये—ह्वि.। समवाये—मै। (क्षी) मै-सा।	<√सप् (षप) समवाये (प)। सचति-निघ. २/१४=गतिकर्मा।
√सच् (षच) १/१००५ (क्षी १६१) श-च-जै-काक्र-कात-शा-हे-वो×		

क—, ख-पूर्ववत्।

ग—सचते-शब्रा. २,३,२,९; काब्रा. २,१,३,१७। सिषक्ति-शांब्रा. २४,७। सिषक्तु-शब्रा. २,३,४,३५।

√सञ्ज् (षन्ज्) १/९७२ श	सङ्गे (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो।	√सज् १/६४f गतौ (प) काक्र। √सञ्ज् १/३१३i हिंसागत्योः (प) काक्र।

क—सेज् (ग्)-नासिक्यम्-सेंग् (ज्)=बन्धने-वा. पॉकर्नीः। लिथु.-सृग्ति=बन्धने--जू. पॉकर्नीः।

ग—सजन्ति-तैब्रा. १,६,१०,५।

ङ—√सज्ज (अक)=आसक्तौ, (सक) आलिङ्गने। सज्जइ-उत्त. २५,२०। सज्जह-णाया. १,८-पत्र. १४८।

+√सट् (षट) १/३०९ श (काक्र-√वट्) लैपिकी त्रुटिः।	अवयवे (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। अंशके—वो।	√सट् १/९२८ (प) काक्र।

ग—संटास्तस्य पञ्च चक्रे-मभार. ३,१५७८५।

√सद् (षद्लृ) १/८३९ वो×, श

विशरणगत्यवसादनेषु (प)
क्षी-मै-सा-काक्र-
कात-शा-हे ।
विशरणे—च ।
शातने गतिविशरणयोश्च—जै ।
उपवेशने—ह्वि. ।

√शट् (शट) १/ रुजाविशरणगत्यव…(प)।
√शद् (शद्लृ) १/ शातने (प)।

क—सेद् = उपवेशने-वा. पॉकर्नीः ।
ख—अवे. हिदैति = (नि) सीदति, उपवेशने-जू. पॉकर्नीः ।
ग—अभि…………सीदति-ऋ. ९,७,५ । सीदति-शब्रा. ६,२,१,५ ।
ङ—√सीअ (अक) = (१) विषादे, (२) श्रान्तौ, (३) पीडायाम्, (४) फलने । सीअइ-पि. ४८२ ।

+√सद्(षद्लृ) ६/१४६ श×

विशरणगत्यवसादनेषु (प)
क्षी-मै-सा-काक्र-कात-
शा-हे ।
अवसादे—च ।
शातने गतिविशरणयोश्च—जै ।
विषादे शरणे गतौ—वो ।
शरणम् = हिंसा-दुर्गादासः ।

√सन् (षण)१/४३८ श×

भक्तौ (प) क्षी ।
संभक्तौ—
मै-सा-च-जै-काक्र-
कात-शा-हे-वो ।

√सन् (षण) ८/२ दाने (उ)।

ग—सनेम सनन्तः-ऋ. ७,५२,१ । सनेम्-तैब्रा. १,२,१,१५; मना. २,५० ।

√सन् (षणु) ८/२ श

दाने (उ)
क्षी-मै-सा-च-जै-काक्र-
कात-शा-हे-वो ।

क—सेन् = प्रापणे, दाने-वा. पॉकर्नीः ।
ग—अग्निः सनोति वीर्याणि-ऋ. ३,२५,२ । सनोति-ऐब्रा. १,१३; शब्रा. ६,४,३,१० ।

√सप् (षप) १/३९८ समवाये (प)
श×(च-जै—√सच्) क्षी-मै-सा-च-जै-काकृ-
कात-शा-हें।
सम्बे—वो।
√सच् (सच)........ समवाये इति चन्द्रः—क्षी।

वस्तुतश्चान्द्रे धातुपाठे √सच् (षच) १/१४० समवाये (प) इति षोपदेशः पाठो विद्यते।

क—सेप्=प्रेरणे।
ख—अवे. हप् (हप्सु, हप्ती)=ग्रहणे, धारणे, आश्रये-जू. पॉकर्नी।
ग—अभि......सपन्ते-ऋ. ७,३८,५; सपेम-६,१५,१०; शब्रा. १४,१,४,१६।

+√सम् (षम) १/८१३ अवैक्लव्ये (प) √स्तम् (ष्टम) १/ अवैक्लव्ये (प)।
श-जै× क्षी।
वैक्लव्ये—मै-सा-च-काकृ-कात-शा-हे-वो। √सम १०/ वैक्लव्ये (प) वो।
√क्षम्प् १०/३५० क्षान्तौ (प) काकृ।
वैक्लव्यम्=विह्वलीभावः-दुर्गादा.।

+√सय् (षय) १/४७६ गतौ (आ) इति क्वचित् <√नय् (णय) गतौ (आ)।
क्षी-मै-श-च-जै-काकृ- —सा।
कात-शा-हे-वो× सा।
ग—सय० (विशेषण.)-ऋप्रा. १४,१५।

√सर्ज् (सर्ज) १/२२० अर्जने (प) √सर्ज् १/४२५f गतौ (आ) काकृ।
मै-सा-श-काकृ× क्षी-च-कात-शा-हे-वो।
सर्जने—जै।
कर्कशशब्दे, क्रन्दने—ह्वि.।
√सर्ज् (षर्ज) १/१२२ अर्जने—मै।
क्षी-श-च-जै-कात-शा-हे× मै-सा-काकृ।

ग—शकटीरिव सर्जति-ऋ. १०,१४६,३। प्रारब्धं न सर्जन्ति (?)-पञ्चव्रत. २००,२१।

+√सर्ब् (षर्ब) १/४१८ गतौ (प)
श×(काकृ–√सर्व् [सर्व]) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
सर्पणे—वो।

√सब् (सबै) १/४१९ गतौ (प)।

+√सर्ब् (षर्ब) १/५८६ हिंसायाम् (प)
क्षी-श-च-जै-काकृ-कात-शा-हे-वो× मै-सा।

√शर्व् (शर्व) १/ हिंसायाम् (प।

+√सल् (सल) १/५४६ गतौ (प)
श-जै-काकृ-कात× (च–√पल्) क्षी-मै-सा-च-शा-हे-वो।
√षल् इति भाष्यम्।
छ—सलना (बुं. ख.)=पङ्के मज्जनम्।

√शल् (शल) १/ गतौ (प)।
√स्त्र १/ गतौ (प)।

√सश्च् (षश्च) १/१९९ गतौ (प) इति शिवः—क्षी
मै-श-च-जै-काकृ-कात-शा× क्षी-सा-हे-वो।
साहचर्ये—ह्वि.।

<√सस्ज् (षस्ज) गतौ (प)।
√सश्च् १/५२३ गतौ (प) जै।
√सच् (षच) १/ समवाये (उ) मै।

क—सेचु=अनुसरणे।

ख—अवे. हचैते, हचैति=सश्चति वा. पॉकर्नीः।

ग—सश्चत्–ऋ. २,२२,१। सश्चसि-शत्रा. २,३,४,३८। अप…सश्चिरे-ऋ. ५,२०,२।

√सस् (षस) २/६७ स्वप्ने
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
स्वापे—वो।

सस्ति–निघ.३/२२=स्वपिति-कर्मा।

ग—अचित्रे अन्तः पणयः ससन्तु–ऋ. ४, ५१, ३। सस्ति-ऋ. १,२९,३; ४, १, १०३

+√ सस्ज् (षस्ज) १/१९९ गतौ (प)
श-जै-काकृ-शा × क्षी-मै-सा-च-कात-हे ।
सर्पणे—वो ।
१/२०० भाष्यप्रयोगादयमात्मनेपद्यपि-सा ।

>√ सश्च् (षश्च) गतौ (प)
इति शिवः-क्षी ।
√ सज् १/६४ f गतौ (प)
काकृ ।

ग—सज्जति-तैआ. १,११,८; नाप. ३,६३ । सज्जते-१ संन्यासो. २,९०; पिण्डब्रह्माण्डो. ३, ६३ ।

ङ—√ सज्ज (अक)=तत्परतायाम्, (२)-सक.-सज्जने । सज्जेइ, सज्जेंति-कुमा. ।

छ—√ सजना, √ साजना*†, √ सँजोना =सज्जने ।

छ—√ छजना=सज्जने, शोभने; (२) उपयुक्तत्वे ।

√ सह् (षह) १/८३७ मर्षणे (आ)
श × क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
शक्तौ—वो ।

√ सह् (षह) ४/ सम्भक्तौ (प) ।

क—सेघु्=ग्रहणे, धारणे-वा. पॉकर्नीः ।

ग—सहध्यै-ऋ. ६, १, १; ७, ३१, १२ । सहते-शांआ. १२, ४; शब्रा. ७, ४, २, ३३ ।

ङ—√ सह=मर्षणे । सहइ, सहंति=उव.; महा.; कुमा. ।

छ—√ सहना=मर्षणे ।

√ सह् (षह) ४/२१ संभक्तौ (प)
श-च-जै-शा × इति दुर्गः—क्षी
शक्यार्थे—मै ।
'चक्यर्थे' आत्रेयमैत्रेयदुर्गाः—सा ।
शक्तौ—काकृ-कात-हे-वो ।

<√ सुह (षुह) शक्यर्थे (प) ।

सहेरिह पाठो न्यासकारहरदत्तरामदेवादीनामप्यनभिमतः, यत् तत्र तत्र भौवादिकमेवाहुः—सा ४/२१ ।

ग—सह्यामि-मै.-इति ह्वि. । मया नोपलब्धम् । साह्याम-वनदुर्गा. ४५९:२२ [ऋ. १०, ८३, १] ।

[+]√साध् (षाध) ५/१७ संसिद्धौ (प)
श-मै ×
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
सिद्धौ—वो ।

√साध् (साध) 'संसिद्धौ' इत्येके—क्षी ।
श-च-जै-काकृ-
कात-शा ×

क—से (इ)ध्-: सीध्-तथा : सेध्=निमीलने, बन्धने ।
ख—अवे. हाद्=आदेशे, परिवर्तने-जू. पॉकर्नीः ।
ग—भौवादिकः—साधति-ऋ.६, ७०, ३; साधन्-६, ६६, ७ ।

ङ—√साह (सक)=(१) सिद्धौ, (२) वशीकरणे । साहइ, साहेइ-भग.; कप्प.; उव.; प्रासू . २७; महा. ।

छ—√साधना=सिद्धौ, (२) संधाने (लक्ष्ये), (३) मापने, (४) अभ्यासे, (५) शोधे, (६) सत्यप्रमायाम्, (७) निर्धारणे ।

√सि (षिञ्) ५/२ बन्धने (उ)
श
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
बन्धे—वो ।

ग—असिनोत्-जैब्रा.-ह्वि. । पाठस्तु-असिनात्-जैब्रा. १६० इत्युपलभ्यते ।

√सि (षिञ्) ९/५ बन्धने (उ)
श
क्षी-मै-सा-च-जै-काकृ-कात-
शा-हे ।
बन्धे—वो ।

क—साइ-, सुइ-, सि-,सी=बन्धने ।

ख—अवे. हा (य्)=बन्धने (वर्तमा.-हयेइति, हित=सितम्), हित्= युगनद्धौ द्वौ ततोऽधिका वाश्वाः-वा. पॉकर्नीः ।

ग—उत्सिनाति-ऋ. १, १२५, २ । सिनीतः-कठो. २, १ । सिनीथः-ऋ. ७, ८४, २ ।

√सिच् (षिच) ६/१५१ जै×,श | क्षरणे (उ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। | √सिक् सेचने-सौ. धा.-वो।

क—साइक्=क्षरणे-वा. पॉकर्नीः। लैति. सिअत्; पु. उ. ज., म. उ. ज.-साइच्=मूत्रम्-जू. पॉकर्नीः।

ख—हएक्-,हिञ्चुँति (हिचैति)=सिञ्चति, सेचने, क्षरणे-वा. पॉकर्नीः।

ग—सिञ्चति-ऐआ. २,५,१; शब्रा. ६,३,१,७; काब्रा. १,३,४,१२। सेचते-तैब्रा. २,४,३,१०।

ङ—√सिंच (सक)=सेचने, विकिरणे। सिंचइ-महा.।

छ—√सींचना (<सिञ्चनम्)=सेचने, (२) क्लेदने।

+√सिट् (षिट) १/३०० श | अनादरे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

ग—षिङ्गैरगद्यत ससम्भ्रममेव काचित्-शिशु. ५,३४=विटैः (सर्वङ्कषा)।

छ—√सिट (पिटाना)=नम्रीभावे, सङ्कोचे, सम्पिण्डे।

छ—√सीटना=विकत्थने, मुधा प्रशंसने।

√सिध् (षिधु) १/४५ श | गत्याम् (प) क्षी-मै-सा-च-काकृ-कात-शा-हे-वो। गतौ—जै। | सेधति-निघ. २/१४=गतिकर्मा।

√सिध् (षिध)··· श-च-जै-काकृ-कात-शा× | गत्याम् (प) निरनुबन्धपाठे तु-क्षी। क्षी-मै-सा-हे-वो।

ग—अपसेध-ऋ. ६,४७,२९। सेधति-तैब्रा. २,४,१६; ते सेधन्ति पथो वृकम्-ऋ. १, १०५,११।

छ—√सेझना (<सेधनम्)=दूरीभावे, अपसारणे।

छ—√सिधाना *=गमने, प्रस्थाने।

+√सिध् (षिधू) १/४६ श× | शास्त्रे माङ्गल्ये च (प) क्षी-मै-सा-काकृ-कात। शिष्टौ—च। शास्त्रमाङ्गल्ययोः—जै-शा-हे। शिवे शास्त्रे—वो।

शास्त्रम् = शास्त्रविषयं शासनम् ।
माङ्गल्यम् = मङ्गलविषया क्रिया—क्षी ।

पूर्वस्यैव धातोरर्थान्तरे प्रपञ्चः ।
ङ—द्रष्ट. √सिध् ४/७९ ।

√सिध् (षिधु) ४/७९ शकेचिदूदितं पठन्ति तदसत्—सा ४/८४	संराद्धौ (प) क्षी-मै-सा-च-काकृ-कात-शा-हे । सिद्धौ—वो ।	

क—सा×(इ)ध्-, सिध्-, सीध् तथा : सूध् = निमीलने, साफल्ये-वा. पॉकर्नीः ।

ग—यस्माद्दते न सिध्यति यज्ञः-ऋ. १,१८,७ । सिध्यति–साम्रा. ३,४,७ ।

ङ—√सिज्झ (अक) = (१) निष्पत्तौ, (२) पाके, (३) मुक्तौ, (४) माङ्गल्ये, (५) गतौ, (६) शासने । सिज्झइ–भग.; महा. ।

छ—√सीझना } = पाके ।
छ—√सिझाना }

+√सिन्व (षिवि) १/५८२ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	सेचने (प) अन्ये-सा सा ।	<√निन्व् (णिवि) सेचने (प) ।
√सिभ् (षिभु) १/४३० क्षी-श-च-काकृ-कात-शा-हे-वो×	हिंसार्थः (प) इत्येके —मै,-सा । हिंसायाम्—जै ।	<√सृभ् (षृभु) हिंसार्थः (प) । √श्रिभ् (श्रिभु) १/ हिंसार्थः (प) इत्यन्ये—मै ।
+√सिम्भ् (षिम्भु) १/४३१ क्षी-श-च-काकृ-कात×	हिंसार्थः (प) इत्येके–मै मैसा । हिंसायाम्—जै-शा-हे । हिंसने—वो ।	<√सृम्भ् (षृम्भु) हिंसार्थः (प) । √श्रिम्भ् (श्रिम्भु) १/ हिंसार्थः (प) इत्यन्ये—मै ।

ग—सिम्भुक०–पञ्चत. १९१,२४ ।

+√सिल् (षिल) ६/८४ श | उञ्छे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। | √शिल् (शिल) ६/ उञ्छे (प)।

ग—सिलाची-अ.वे. ५,५,१;८। सिलक०-इन्दिशे स्तू. १,१९३; २५५।

√सिव (षिवु) ४/२ | तन्तुसन्ताने (प)। क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। तन्तुततौ--वो। ऊतौ--हे (उतौ—किर्स्ते-संस्क.)।

√सीव्, √स्यू···· | ह्वि.।

क–सुऊ, सीऊ=सीवने-वा. पॉकर्नीः।
क—सीऊ, सिऊ=सीवने। (लिथु. सिउतस्=स्यूतम्)–जू. पॉकर्नीः।
ग—सीव्यत्वपः सूच्या-ऋ. २,३२,४। सीव्यति–ऐब्रा.३,७; तैब्रा. ३,१०,११,७।
ङ—√सिव्व (सक)=सीवने। सिव्वइ–विसे. १३६८।
ङ—सीव (सक)=सीवने-आचा.।
छ—√सीवना } =युतौ, सीवने।
छ—√सीना }

+√सीक् (षीकृ) १/७५ क्षी-मै-श-च-जै-शा-हे× | सेचने (आ) इति धनपालकाश्यपौ—सा। सा-काकृ-कात। सेके गत्याम्—वो। | <√शीक् (शीकृ) सेचने (आ)।

स चायं पक्षः 'शीकरः' इति प्रयोगाननुगुणः—सा।
ग—स नर्मदारोधसि सीकरार्द्रैः--रघु. ५,४२।

√सु (षु) १/९२६ श× (जै-√सु) मुद्रणदोषः स्यात् | प्रसवैश्वर्ययोः (प) क्षी-मै-सा-जै-शा-हे। प्रसवे—च-काकृ-कात। ऐश्वर्यप्रसवयोः—जै-शा-वो।

क—सॉइ–, सु–, सू=प्रसवे-वा. पॉकर्नीः।
ग—सवति–ह्वि.। मया नाधिगतम्। सोष्यति–छान्दो. ३,१७,५। सोष्यन्ती–शब्रा. १४,९,४,२२।

+√सु (षु) १/९४४ क्षी-श-च-जै-शा-हे× (काक्र-√सू)	गतौ (प) मै-सा-काक्र-कात-, वो (उ)।	√स्रु १/ गतौ (प)।

पूर्वस्यैव प्रपञ्चो धातोः।

√सु (षु) २/३० च×, श	प्रसवैश्वर्ययोः (प) क्षी-मै-सा-जै-शा-हे। ऐश्वर्यप्रसवयोः— (जै-शा)—वो। प्रसवे—काक्र-कात।	√सु (षु) १/ प्रसवैश्ययोः (प)।

ग—सुसाव–ऋ. ४,१८,१०; १०,८७,२३; सुवे–१०,१२५,१०।

√सु (षुञ्) ५/१ श	अभिषवे (उ) क्षी-मै-सा-च-जै-काक्र- कात-शा-हे। सन्धाक्लेदपीड- मन्थे—वो।	√सु (षु) १/ प्रसवैश्वर्ययोः (प)। √सु (षु) २/ प्रसवैश्वर्ययोः (प)।

क—सॉइ-, सेउए-ः सू=क्षरणे, श्च्योते, द्रुतगतौ, प्रवाहे।
ख—अवे. हुनओइति=सुनोति–जू. पॉकर्नीः।
ग—सुनु सोमम्–ऋ. १,२८,६। सुनोति–शब्रा. १२,८,२,१२; तांब्रा. १२,९,१२

+√सुम्भ् (षुम्भ) १/४२६ मै-श-च-जै-काक्र- कात-शा× ९/	भाषणे हिंसायाञ्च (प) इति गुप्तः—क्षी। क्षी-सा-हे। दीप्तौ हिंसने च—वो। 'सुम्भनाद्यर्थे' इत्येके– क्षी ६/४३। श्वासावरोधे—ह्वि.।	<√शुम्भ् (शुम्भ) भाषणे हिंसायाञ्च (प)।

ग—सावष्टम्भनिषुम्भसम्भ्रम०–मालतीमाध. ५,२२। कुसुम्भम्…?
छ—सुम्ह (<सुम्भः)=जातिविशेषनामधेयम्।
छ—सुंभी=अयश्छेदनोपकरणमग्निविहीनम्।

+√सुर् (षुर) ६/६० मै-सा-श-च-जै- काक्र-कात×	ऐश्वर्यदीप्त्योः (प) क्षी-हे। दीप्तैश्वर्ययोः—शा।	√सु (षुञ्) ५/१ अभिषवे (उ)। सुरा सुनोतेः–निरु. १,११,२

भैश्ययोः—वो ।

√सुर् (षुर)··· ऐश्वर्यदीप्त्योः (प)
श-शा× इति दुर्गः—क्षी ।
क्षी-मै-सा-जै-काकृ-
कात-हे ।
ऐश्वर्ये—च ।
दीप्तैश्वर्ययोः—जै ।
भैश्ययोः—वो ।

ग—सुरा इत्यभिविश्रुताः-वा. रा. १,४५,४८ । (दुर्मदासो न सुरायाम्-ऋ. सं. ५,७,१९,१) ।

+√सुह् (षुह) ४/२१ शक्यर्थे (प)
श क्षी-सा ।
'संभक्तौ' इति दुर्गः—क्षी ।
शक्यार्थे—मै ।
चक्यर्थे—सा ।
शक्तौ—च-काकृ-कात-हे ।
शकने—जै ।
शक्तौ तृपि च—वो ।
शक्यर्थः=तृप्तिः—क्षी ।
चक्यर्थः=तृप्तिः इति स्वामिधनपालशाकटायनाः-क्षी ।

ग—अहेरिव गणाद् भीतः सौहित्यान्नरकादिव ।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥ मभार. १२,२४४, १३ ।
छ—सुह्म-गौडदेशात् पश्चिमस्यां प्राचीनः प्रदेशः, (२) यवनानां जातिविशेषः ।

√सू (षूङ्) २/२० प्राणिगर्भविमोचने (आ)
श क्षी-मै-सा-जै-काकृ-
कात-शा-हे ।
प्रसवे—च ।
सूतौ—वो ।

√सु (षु) २/३० प्रसवैश्वर्ययोः (प) ।

क—सॉइ-,(सेउए-)-, सु-, सू=जनने-वा. पॉकर्नीः ।
ग—असूत पूर्वो वृषभः-ऋ. ३,३८,५ । सूते-तैब्रा. १,८,६,४; त्रिपुरातापिन्यु. १,२०' । आयुष्मन्तं सुतं सूते-मनु. ३,२६३ ।

√सू (षूङ्) ४/२४ श — प्राणिप्रसवे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । सूतौ—वो । — √सू (षूङ्) २/ प्राणिगर्भविमोचने (आ)। पूर्ववत् ।

क—सॉइ–, (सेउ्रए्–) सु–, सू=जनने–जू. पॉकर्नीः ।
ग—सूयते–मन्त्रिको. ४; गी. ९,१० । सूयन्ते–मैत्र्यु. ६,१६ ।

√सू (षू) ६/१२७ श — प्रेरणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । क्षेपे—वो ।

क—सॉइ–, सु–; सेउ्रए्=प्रेरणे । हित्ती. शुउ्आइ=प्रेरणे, उत्क्वथने ।
ख—अवे. हव=सवः—जू. पॉकर्नीः ।
ग—सविता सुवाति–ऋ. ७,४०,१; (सुष्यन्ती–५,७८,५) । सुवत्–तैआ. ३,११ । अभिषुवति–काठ. १३,२ । सुवति–शब्रा. ५,३,३,४ ।

√सूद् (षूद्) १/२४ श× — क्षरणे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । निरासे—वो । हिंसायामपि वर्तते—सा । आदेशे—ह्वि. ।

क—सूआद्=मधुरम् । लिथु. सूय्रूति (गॉथि. सूट्स्)—वा. पॉकर्नीः । इँग्लि. सूद् (=भुशुण्ड्यादिप्रयोगेण मारणे)—वागीशः । तुल. सायणीयेनार्थेन ।
ग—असुषूदन्त–तैब्रा. १,७,४,४ । सूदः–शब्रा. ८,७,३,२१ ।
ङ—√सूड (सक)=छेदने, विनाशे, । कर्म.–सूडिज्जंतु–पण्ह. १,२–पत्र.२९ ।
छ—√सूँटबौ (बुं.ख.)=ताडने ।

√सूर्क्ष् (सूर्क्ष) १/६५७ मै-श-कात-शा× — अनादरे (प) इति चन्द्रः—क्षी क्षी-च-जै-काकृ-हे । आदरे—सा । 'अनादरे' इति क्वचित् पठ्यते तदसत्—सा । नादरे—वो । ध्याने अवधाने—ह्वि. । — <√सूर्क्ष्य् (सूर्क्ष्य) अनादरे (प)।

√सूर्क्ष् (षूर्क्ष) १/६६९ अनादरे (प) मै।
क्षी-सा-श-च-जै-काकृ- नादरे—वो।
कात-शा-हे ×

क—सूऍर्घ् = व्याकुलम्, उद्विग्नम्, चिन्तितम्। दुःखे। गॉथि. सउर्घ् = दुःखम्। पु. आइस्., ऍंग्लो-सैक्सॉ. सॉर्ग्; पु. सैक्सॉ., पु. उ. ज. सॉर्ग = दुःखम्—वा. पॉकर्नीः।

ग—सूर्क्षति-गोत्रा. २, ३, ९; सूर्क्षत-२,२,१०। सूर्क्षेत्-आपस्त. २,२८,९।

+√सूक्ष्र्य् (सूक्ष्र्य) १/५१० ईर्ष्यार्थः (प)
मै-सा-श-च × क्षी-जै-कात-शा-हे।
ईर्ष्यायाम्—काकृ।
ईर्ष्ये—वो।

√सूर्क्ष् (सूर्क्ष) १/ अनादरे (प)।
√सूक्ष्र्य् (सूक्ष्र्य) १/ अनादरे (प)।

√सूक्ष्र्य् (षूक्ष्र्य) १/५१० ईर्ष्यार्थः—मै।
क्षी-श-जै-काकृ-कात-शा × मै-सा-च-हे।
(च-√सूक्ष्म्) ईर्ष्ये—वो।

ग—असूक्ष्र्येत्-काठ. १०,६; मा सूक्ष्र्येत-३४,१७। नर्तून् सूक्ष्र्येत्-न्यायमालाव. २४८।

+√सूक्ष्र्य् (सूक्ष्र्य) १/६५७ अनादरे (प)
मै-सा-श-च-जै-काकृ × क्षी-कात-शा-हे।
(हे) अनादरे ईर्ष्ये—वो।
पूर्वस्यैव धातोः प्रपञ्चः।

>√सूर्क्ष् (सूर्क्ष) अनादरे (प) इति चन्द्रः—क्षी।

+√सूष् (षूष) १/६७० प्रसवे (प)
श-जै-शा × क्षी-मै-सा-च-काकृ-कात-हे-वो।

√सूष् (सूष) १/६६६ 'प्रसवे' केचित्, तदनार्षम्;
क्षी-मै-श-च-जै-काकृ- षोपदेशलक्षणविरोधात्—
कात × सा,-शा।
प्रसवे—वो।

√शूष् (शूष) प्रसवे (प) इति चरकः—क्षी।
(सूष्यन्ती—ऋ. ५,७८,५)

ग—सूषणा—अ.वे. १,११,३; सूषा—१,११,३।

√सृ १/९१९ गतौ (प) √सृप् (सृप्लृ) १/ गतौ (प)।
श
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वों।

क—सेर्=प्रवाहे, द्रुतगतौ।
ख—(अवे. सरैति)-जू. पॉकर्नीः।
ग—सरन्नाप०-ऋ. ४,१७,३; ससार-४,३०,११। असरत्-तैआ. १,३०,१।
ङ—√सर (सक)=(१) सर्पणे, (२) अवलम्बने, (३) अनुसरणे।
कृ-सरणीअ-चउ. २७।
छ—√सरना (<सरणम्)=चलने, (२) भ्रमणे, (३) निर्वाहे।

√सृ ३/१७ गतौ (प)
श-जै×(शा) क्षी-मै-सा-च-जै-काकृ-कात-
शा-हे-वो।

क—पूर्ववत्।

+√सृज् (सृज) ४/६५ विसर्गे (आ)
श
क्षी-मै-सा-च-जै-काकृ-कात-
शा-हे-वो।

ग—संसृज्यन्ते परस्परम्—मभार. १२,९३६२। (वायुः) संसृज्यते सरसिजैर-रुणांशुभिन्नैः—रघु. ५,६९=संगच्छते (संजी.)।

√सृज् (सृज) ६/१३३ विसर्गे (प)
श
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो।

क—सेल्ज् (गू)=क्षेपणे, विसर्गे।
ख—अवे. हरेजैति, हरेजैति=सृजति—जू. पॉकर्नीः।
ग—अवसृजन्ति—ऋ. ५,३०,१३। सृजति—ब्रह्मो. १; नृपू. २,८; त्रिता. ४,९। सृजते-मुण्डको. १,१,७; शब्रा. २,५,१,११।
छ—√सृजना* } =रचनायाम्।
छ—√सिरजना* }

√सृप् (सृप्लृ) १/९६८ गतौ (प) सर्पति-निघ. २/१४=गतिकर्मा।
श (जै√सृ) भ्रष्टः पाठः। क्षी-मै-सा-च-जै-
काकृ-कात-शा-हे।
गत्याम्—वो।

क—सेर्प् = रिङ्गणे, सर्पणे । (लैति. सेर्पो)-जू. पॉकर्नीः ।
ग—उप सर्प मातरं भूमिमेताम्-ऋ. १०,१८,१० । सर्पति-शब्रा. ७,४,१,२७ ।
ङ—√ सप्प (सक)=गतौ, (२) आक्रमणे । सप्पंति-सुर. २,२४३ ।

+√ सृभ् (सृभु) १/४२४ मै-श-जै-काकृ-शा × (कात √ शृभ्) — हिंसार्थः (प) क्षी-सा-च-कात । हिंसायाम्—हे । हिंसे—वो । — √ सृम्भ् (सृन्भु) १/ हिंसार्थः (प) ।

√ सृभ् (षृभु) १/४३० क्षी-श-च-जै-कात-शा-हे-वो × — हिंसार्थः—मै-सा । भर्त्सनहिंसयोः—काकृ ।

सृवर्जम्—६/१/६४ इति भाष्येणाषोपदेशस्यापि ग्रहणात्-क्षी ।

+√ सृम्भ् (सृन्भु) १/४२५ मै-श-जै-काकृ-शा × — हिंसार्थः (प) क्षी-सा-च-कात । हिंसायाम्—हे । हिंसे—वो ।

√ सृम्भ् (षृन्भु) १/४३१ क्षी-श-च-जै-कात-शा-हे-वो × — हिंसार्थः—मै-सा । भर्त्सनहिंसयोः—काकृ ।

+√ सेकृ (षेकृ) १/७८ मै-श-च-जै-काकृ-कात-शा × — गत्यर्थः (आ) इत्यन्ये-क्षी । क्षी-सा । गतौ—हे । गत्याम्—वो । — <√ शीक् (शीकृ) गत्यर्थः (आ) । √ सीक् १/४२ गतौ (आ) । काकृ । अत्र क्वचित् √ सीक् (सीकृ) दन्त्यादिरपरो धातुः पठ्यते, तदनार्षम्-१/८१ सा । √ स्रेक् (स्रेकृ) १/ गत्यर्थः (आ) । √ शेख् १/४१२ x गतौ (आ) काकृ ।

√ सेक् (सेकृ) १/७९ — गत्यर्थः—क्षी-मै-सा-च-कात । गतौ—जै-शा-हे । गत्याम्—वो ।

(ग—गोर्न सेके-ऋ. १,१८१,८—√ सिच् ?) ।

√सेल् (षेल) १/५४२ मै-श-काक्ठ-कात ×(क्षी.यु. मी. सं.×)	गतौ (प) क्षी-सा-च-जै-शा-हे । केल्वत् (=चालगत्योः) वो ।	√शेल् (शेलृ) १/ गतौ (प)।
+√सेल् (सेलृ) १/५४२ मै-श-च-जै-शा ×	गतौ—क्षी-सा-काक्ठ-कात-हे-वो ।	

सेलतेस्तु दन्त्यादेः पाठः षोपदेशपर्युदासवाक्येऽनुपादानादनार्षः। मूर्द्धन्यादिस्तु सेलुः श्लेष्मान्तक इत्यादिदर्शनाद् ग्राह्यः ?–सा १/५३५ ।

ग—सेलु०–सुश्रु. १,२३७,२१ (सेलग०–ऐब्रा. ७,१;८,११; शब्रा. १३,४,३,१०; आश्व. श्रौ. १०,७,६) ।

√सेव् (षेवृ) १/४९९ श×	सेवने (आ) क्षी-च-जै-शा-हे-वो । सेवने—मै-सा-काक्ठ-कात । सेवे—वो ।	√खेव् (खेवृ) १/ सेवने (आ)। √केव् (केवृ) १/ सेवने (आ)।
√सेव् (सेवृ) १/५०० श-च-जै-काक्ठ×	सेवने—क्षी-शा-हे,वो (उ)। सेचने—मै-सा-कात । सेवे—वो।	√शेव् (शेवृ) १/ सेवने (आ)।

ग—अश्वः श्वेतः स्थाणौ सेवते–शब्रा. ३,६,२,४; गी. १४,२६।

ङ—√सेव (सक)=(१) आराधनायाम् , (२) आश्रये, (३) उपभोगे। सेवइ, सेवए–आचा.; उव.; महा. ।

+√सै १/९०० मै-श-च-जै-काक्ठ-कात× √सै(षै) १/९१९	क्षये (प) क्षी-सा-शा-हे-वो । क्षित्याम्—वो । क्षये—मै-सा-च-जै-काक्ठ-कात-वो ।	√क्षै १/ क्षये (प) √सो (षो) ४/ अन्तकर्मणि (प) ।
√सो (षो) ४/३८ श	अन्तकर्मणि (प)। क्षी-मै-सा-जै-काक्ठ-कात-	

शा-हे ।
अवसाने—च ।
नाशे—वो ।
√सा ६/ ? बन्धने—ह्वि. ।

क—साइ-, सुइ-सि-,सी=बन्धने-वा. पॉकर्नीः । लिथु. सिएँति; लेट्टिश्-सिऐत् =बन्धने-जू. पॉकर्नीः ।

ग—अवस्यति-ऋ. १०,६१, २०; तै. २,५,६,१; मै. ४,६,५ ।

√स्कन्द् (स्कन्दिर्) १/९६४ शोषणे (प) क्षी ।
शX
गतिशोषणयोः—
मै-सा-जै-काकृ-कात-
शा-हे ।
गतौ—च ।
शोषणे गत्याम्—वो ।
कूर्दने—ह्वि. ।

√कन्द् (कदि) १/६७ आह्वाने रोदने च (प) ।
√स्कुन्द् (स्कुदि) १/ आप्रवणे (आ) ।
√स्कन्ध (स्कन्ध) १०/ समाहारे (प) ।

क—स्कन्द्=बन्धने, वेष्टने, पाशने । लैति. स्कन्दो,-एरे=आरोहणे—बा. पॉकर्नीः ।

ग—अतिस्कन्दति-ऋ. ५,५२,३ । स्कन्दति-शब्रा. ४,१,१,२६ ।

+√स्कम्भ् (स्कभि) १/३८४ प्रतिबन्धे (आ)
शX
क्षी-मै-सा-च-काकृ-कात ।
स्तम्भे—जै-शा-हे-वो ।

√स्कम्भ् १/३१९ b स्तम्भने (प) काकृ ।
√कम्भ् १/३५९ स्तम्भने (प) काकृ ।

ग—स्कम्भथुः स्कम्भनेन-ऋ. ६,७,२,२ ।

छ—√खटाना (<प्रा. खड्ड ? <स्कब्धम्) =स्तम्भे, निर्वाहे ।

√स्कम्भ् (स्कम्भु) ५/४ सौ. धा. स्तम्भार्थः (प) सा ।
९/
क्षी-मै-श-च-जै-काकृ-कात- सा ।
शा-हेX

क—स्कभ्-, स्कम्भ्=आश्रये, स्थितौ । लैति. स्कभ्नुम् (*स्कभ्नोम्)-जू. पॉकर्नीः ।

ग—स्कभ्नुवन्तः-शब्रा. ५,१,५,१७। स्कभ्नाति-ह्वि.। मया नावाप्तम्।

ङ—√खंभ (सक)=(१) क्षोभणे, विचलने। खंभेज्जा, खंभाएज्जा-ठा. ५,१-पत्र. २९२।

√स्कु (स्कुञ्) ५/६ सौ.धा. ९/ आप्रवणे (उ) क्षी-मै-श-च-जै-कात-शा-हे।
श, (काक्र-√स्कू) आच्छादने—काक्र। उद्धृतौ—वो। दारणे—ह्वि.।

चोष्कूयते-निघ. ४/३=दानार्थः, व्युदसनार्थश्च-देवराजयज्वा। निरु. ६,२२।

क—स्केउ-(तृ-)=छेदने-जू. पॉकर्नीः।

ग—यो गोः कर्णावास्कुनोति-अ.वे. १२, ४,६। स्कुनाति-इत्यपि ह्वि.। मया नोपलब्धम्।

+√स्कुन्द् (स्कुदि) १/९ आप्रवणे (आ) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
शX आप्लाव उद्धृतौ उत्प्लुत्य-गत्याम्—वो।

√स्कन्द् (स्कन्दिर्) १/ गतिशोषणयोः (प)।

क—(स्) कॉइद्=प्रक्षेपणे, उत्प्लुतौ। लिथु. स्कुद्रुस्=तीव्रम्, चपलम्। पु. बुल्गा. इस्-क्यदति=प्रक्षेपणे, उद्धरणे-वा. पॉकर्नीः।

छ—√कूँदना(<स्कुन्दनम्)=उत्प्लवने।

छ—√खूँदना(<स्कुन्दनम्)=उत्प्लवने, (२) पदाघातैर्मर्दने।

+√स्कुम्भ् (स्कुन्भु)५/५ सौ.धा. ९/ धारणार्थः (प) सा। रोधने—वो।
क्षी-मै-श-च-जै-काक्र-कात-शा-हेX

ग—स्कुब्ध्वा (स्कुब्ध्वा, स्कुप्त्वा)-आपस्त. १,३१,२४।

छ—√खुभना=प्रवेशने।

छ—√खोंपना (प्रयोज.)=प्रवेशने।

छ—√गोपना=कण्टकादिनिशितोपकरणप्रवेशने-बुं. ख.।

+√स्खद् (स्खद) १/७६१ खदने (आ) √खद् (खद) १/ स्थैर्ये (प)।
शX क्षी-शा-हे।
स्खदने—मै-सा-च-
काकृ-कात।
जै ?
विदारे—वो।

√स्खद् (स्खदिर्)१/८०३ee अपपरिभ्यां च मित्—क्षी।
श-जै-शा-हे। अवेति भोजः।
न मित्—सा १०५।
खदनम्=विदारणम्-क्षी। विद्रावणमिति स्वामी-सा ७५६।

क—(स्)क्(ह्)ऐद-, (स्)क्(ह्)ऐ-न्-द्=विदारणे। लिथु. स्केदेव्=तनीयस्याः पट्टिकाया दारणे। केदेति, केदेन्ति=दारणे। पु. च. स्ला. स्कॉन्द।

ख—अवे. स्कन्दयेइति=विनाशे-जू. पॉकर्नीः।

√स्खल् (स्खल) १/५४३ चलने (प) √खल् (खल) १/ सञ्चलने (प) मै।
शX क्षी-च-जै-कात-शा-हे।
सञ्चलने—मै-सा। √क्षर् (क्षर) १/ सञ्चलने (प)।
चलने चञ्चले च—काकृ।
चये चले—वो। √क्षल् (क्षल) १/ सञ्चलने (प)।
सञ्चये—कात। √स्वल्ल् १/२४७ b चलने चञ्चले च (प) काकृ।

√स्खल्(स्खलिः) १/८०३ मित्-इति भोजसूत्रम्-क्षी।
मै-श-च-जै-काकृ-कात-शाX

क—स्खेद्=स्खलने। अर्मे. स्खलेम्, स्खलिम्=स्खलने- जू. पॉकर्नीः।
ग—स्खलन्ति-आर्षेयो. ७:१८। स्खलते-ऐब्रा. ७,५।
ङ—√खल (अक)=स्खलने, (२) रोधे। वकृ-खलंत, खलमाण-से. २,२७; गा. ५४६।

ङ—√खस (अक)=स्खलने। खसइ-पिंग.।
छ—√खसना=स्खलने। "ख़सी माल मूरति मुसकानी"-तुलसीदासः।

छ—√खिसलना }
छ—√खसलना } =स्खलने-बुं. ख. ।

छ—√सक्लिलना (<स्खलनम्)=स्खलने, (२) सङ्कोचे, (३) पूर्णे ।

+√स्तक् (ष्टक) १/७७६ शा-शा ×,(काक्र-√कष्ट) वर्णविपर्ययतया	प्रतिघाते (प) क्षी-सा-काकृ । प्रतीघाते—मै-च-कात-हे-वो । लोटने—जै ।	√स्तक् (स्तक) १/७७७ प्रतिघाते (प) ।

क—स्ताक्=स्थितौ, व्यवस्थापने-वा. पॉकर्नी: ।

+√स्तक् (स्तक) १/७७७ मै-श-च-जै काकृ-कात ×	प्रतिघाते (प) क्षी-सा-शा । प्रतिघाते—हे-वो ।	√स्तक् (ष्टक्) १/७७६ प्रतिघाते (प) । √स्थग्(ष्ठगे) १/ संवरणे (प) । √स्था (ष्ठा) १/ गतिनिवृत्तौ (प) ।

पूर्वस्माद् धातोरभिन्नः ।

√स्तन् (स्तन) १/४५५ श × √स्तन् [ष्टन]	शब्दे (प) क्षी । मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√स्तूण् १/२०७mmशब्दे (प) काकृ । √स्त्वन् १/२०७००शब्दे (प) काकृ ।

अज्दन्त्यपराः सादयः षोपदेशाः (६/१/६४) इति भाष्यात् षोपदेश एवायम् ।

क—उत्तरधातुवत् ।

ग—अस्तानीत्-ऋ. १०, १२, ८ । निष्टनन्ति च मातङ्गाः-मभार. ५,४८४४ । सदा निष्टनसे उदन्वन्-भा. पु. १०, ९०, १७ ।

ङ—√थण (सक)=गर्जने, (२) आक्रन्दे, (३) आक्रोशे । वक्र-थणंतगा. २६० ।

√स्तन् (स्तन) १/८११ मै-श-च-जै-काकृ-कात-शा-वो ×	शब्दे (प) मित् क्षी-सा-हे ।
√स्तन् (ष्टन) १/८११ मै-श-च-जै-काकृ-कात-शा-वो ×	शब्दे इति चन्द्रः—क्षी । क्षी-सा-हे ।

क—स्तेन्-, तेन्=मेघशब्दे, गर्जने। लिथु. स्तेनु=स्तनति-वा. पॉकर्नीः। लैति. तॉनो; एँग्लो-सैक्सॉ. स्तेनन्; म. नि. ज. स्तेनेन्; रसन्-स्तॉन्=आर्तस्वरे-जू. पॉकर्नीः।

ग—स्तनयति-शब्रा. २,२,३,८।

+√स्तम् (ष्टम) १/८१४ श-जै×	अवैक्लव्ये (प) क्षी। वैक्लव्ये—मै-सा-च-काकृ-कात-शा-हे-वो।	√सम् (षम) १/ अवैक्लव्ये (प)। √स्तम्ब् १/२०६w मर्दने (प) काकृ। √स्तम्भ् (ष्टभि) १/ प्रतिबन्धे (आ)।

√सम्>√स्तम्।

√स्तम्भ् (ष्टभि) १/३८३ श×	प्रतिबन्धे (आ) क्षी-मै-सा-च-काकृ-कात। स्तम्भने—काकृ। स्तम्भे—जै-शा-हे-वो।	√स्तब् १/२०६x मर्दने (प) काकृ। स्तम्ब् १/२०६w मर्दने (प) काकृ। √स्तुम्भ् ५/, ९/ रोधने (प)—सौ. धा.-वो।

प्रतिबन्धः= क्रियानिरोधः—क्षी।

क—उत्तरधातुवत्।

ग—आपस्तस्तम्भिरे यतः-मभार. १२,६८०७। स्तभमानम्-ऐआ. १,४,१। बाहुप्रतिष्टम्भ०-रघु. २,३२—प्रतिष्टम्भेन=प्रतिबन्धेन (संजी.)।

√स्तम्भ् (स्तम्भु) ५/२, ९/ सौ. धा. क्षी-मै-श-च-जै-काकृ-कात-शा-हे×	स्तम्भार्थः (प) सा। रोधने—वो।	पूर्वधातुद्वयवत्।

क—स्तेब्- तथा स्तेब्-: स्तृब्-, नासिक्यम्-स्तेम्ब्-; स्तेभ-तथा स्तेभ्-: स्तृभ्-, नासिक्यम्-स्तेम्भ्:—वा. पॉकर्नीः। लिथु.-स्तेम्ब्ति-जू. पॉकर्नीः।

ख—अवे. स्तृम्बन्=स्थितौ, स्तम्भे। न. पर्सि. सितम्ब् (=स्तम्भः)=क्रूरः (मृ), तीव्रः (मृ)-वा. पॉकर्नीः।

ग—स्तभ्नुवन्ति-शब्रा. ६,५,२,१५। अस्तभ्नुवन्-तांब्रा. ७,४,७। अस्तभ्नात्-ऐब्रा. १,३०; शांब्रा. ९,६।

ङ—√थब्भ (अक)=अहंकारे। थंब्भइ-सूअ. १,१३,१०।

च—√थंभ (अक)=१-रोधे, स्थितौ। २-(सक) क्रियानिरोधे। थंभइ-भवि.।

छ—√थँभना } (<स्तम्भनम्)=स्थितौ, (२), निरोधे, (३) धैर्ये।
छ—√थमना }

√स्तिघ् (ष्टिघ) ५/१९ श (काक्ठ-√सिघ् [षिघ]) लैपिकी स्यात् त्रुटिः	आस्कन्दने (आ) क्षी-मै-सा-जै-कात-शा-हे स्कन्दने—च। आस्कन्दने—काक्ठ। स्कदि—वो।	√तिक् (तिक) ५/ आस्कन्दने (प)। √तिक् (तिक्ठ) १/ गत्यर्थः (आ)। √तिग् (तिग) ५/ आस्कन्दने (प)। √स्तिक् ५/१९० हिंसायाम् (प) च।

क—स्ताइघ्=लङ्घने, रोहणे। अल्बे. स्तेक्, स्तेग्-उ—वा. पॉकर्नीः।
ग—स्तिघ्नोति-हस्तलेखे (द्रष्ट. जी.डी.एम.जी. ३३,१९५ स्तिघ्नोति)-ह्वि.।

+√स्तिप् (ष्टिप) १/३५९ श-च-जै-काक्ठ-कात×	क्षरणार्थः (आ) क्षी-मै-सा। क्षरणे—शा-हे। च्युति—वो।	स्तिपा स्तियापालन उपस्थितान् पालयति इति वा-निरु. ६,१७,८। स्तिया आपो भवन्ति स्त्यायनात्-निरु. ६,१७,७। स्तिपाः=कूप इत्युपपद्यते-दुर्गाचार्यः। स्तिपाः-निघ. ४/३= अग्निरुच्यते-देवराजयज्वा। द्रष्ट. √स्तेप् १/३६०।

√तिप् १/३५७ >√स्तिप्।

√स्तिम् (ष्टिम) ४/१७ श	आर्द्रीभावे (प) क्षी-मै-सा। आर्द्रभावे—च-जै-काक्ठ-कात-शा-हे।	√तिम् (तिम) ४/ आर्द्रीभावे (प)। √तीम् (तीम) ४/ आर्द्रीभावे (प)।

क्लेदे—वो ।
निश्चलीभावे—ह्वि. ।

√स्तीम् (ष्टीम) ४/ आर्द्रीभावे (प) ।
√स्त्यै (ष्ट्यै) १/ शब्दसंघातयोः (प) ।

ग—स्तिमितम्-आर्षेयो. ८ : १३ । स्तिमिता हृष्टरोमाण आसन् सर्वे सभासदः—मभार. ५,३४४८ ।

ङ—√ थिम (सक)=आर्द्रीकरणे । हेकृ-थिमिउँ-राज. ।

√स्तीम् (ष्टीम) ४/१८ श
आर्द्रीभावे (प) क्षी-मै-सा । आर्द्रभावे—च-जै-काकृ-कात-शा-हे । क्लेदे—वो । निश्चलीभावे—ह्वि. ।
पूर्ववत् ।

ग—अप्सु स्तीमासु-अ.वे. ११,८,३४ ।

च—√ तिम्म (अक)=आर्द्रीभावे । वकृ-तिम्ममाण-पउम. ३५,२० ।

√स्तु (ष्टुञ्) २/३२ श (काकृ-√स्तू)
स्तुतौ (उ) क्षी-मै-सा-च जै-काकृ-कात-शा-हे-वो ।
√स्तूण् १/२०७mm शब्दे (प) काकृ । स्तौति-निघ. ३/१४=अर्चतिकर्मा ।

क—स्तॉइ=स्तुतौ ।

ख—अवे. स्तओइति=स्तुतौ-वा. पॉकर्नीः ।

ग—अभिष्टुहि-ऋ. १,५४,२ । स्तौति-तैब्रा. १,३,५,४; तैआ. ५,४,१९ । सौवादिकोप्ययम्—स्तुन्वन्ति-प्रश्नो. २,४ । यं ब्रह्मा......... स्तुन्वन्ति दिव्यैः स्तवैः—भा. पु. १२,१३,१ । स्तुते-शब्रा. ८,४,१,२६ ।

ङ—√ थुव्व (सक)=स्तुतौ । कवकृ-थुव्वंत, थुव्वमाण-सुपा. ८८; सुर. ४,६६; स. ७०१ ।

च—√ थुण (सक)=स्तुतौ । वकृ-थुणंत-भवि. ।

+√स्तुच् (ष्टुच) १/१७२ श×
प्रसादे (आ) क्षी-मै-सा-च-जै-काकृ-
√स्तु (ष्टुञ्) २/३२ स्तुतौ (उ) ।

	कात-शा-हे-वो।	अथाप्याद्यन्तविपर्ययो भवति स्तोका रज्जुः-निरु. २,१,१३। √श्चुत् (श्चुतिर्) १/क्षरणे-दुर्गादासः।

ग—स्तोको मेदसो घृतस्य-ऋ. ३,२१,१। ये पुरस्तादपां स्तोकाः (=बिन्दवः) -मा. पु. ४९,५९। स्तोकं ह्यपि न पश्यामि-मभार. १,१,२१८=अल्पम्। स्तोककः-मनु. १२,६७=चातकः पक्षी।

+√स्तुप् (स्तुप) ४/११९ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	समुच्छ्राये (प) इति दुर्गः-क्षी।	√स्तूप् (स्तूप) समुच्छ्राये (प)। √स्तु (ष्टुञ्) २/ स्तुतौ (उ)।
√स्तुभ् (ष्टुभु) १/३९२ श×	स्तम्भे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। स्तुतौ—ह्वि.।	√स्तम्भ् (ष्टभि) १/ प्रतिबन्धे (आ)। √स्तु (ष्टुञ्) २/ स्तुतौ (उ)। स्तोभति-निघ. ३/१४=अर्चतिकर्मा। व्यत्ययेन परस्मैपदमिति देवराजयज्वा।

क—स्तॉइ=स्तुतौ-वा. पॉकर्नीः।

ग—सुतं परिष्टोभन्ति नो गिरः-ऋ. ८,८१,१९। स्तोभः-छान्दो. १,१३,३=सामावयवविशेषः। स तु गीतालापपूरणाक्षरः। स च त्रयोदशविधः। यथा-"एवं वावलोको हा उकारः" प्रभृति। क्षीरस्वामी तु-स्तोभः="श्रौतोऽनर्थकः श्रुति-पूरणः"-इति।

छ—√तुभना (<√स्तुभ्=स्तम्भे)=स्तम्भे।

√स्तूप् (स्तूप) ४/११९ मै-सा-श-जै-शा×(काकृ-√स्तृप्)	समुच्छ्राये (प) क्षी-च-काकृ-कात-हे। उच्छ्राये—वो।	>√स्तुप् (स्तुप) समुच्छ्राये (प)। स्तूपः स्त्यायतेः; सङ्घातः-निरु. १०,३३,१।

स्तूपः--स्तूयते—"स्तुवो-दीर्घश्च" (उणा. ३/२५)।
√सूप् १०/२८ समुच्छ्राये (प) काकृ।

ग—उप स्पृश दिव्यं सानु स्तूपैः-ऋ. ७,२,१; स्तूपं ददते-१,२४,७। स्तूपः-तैब्रा. ३,३,६,५।

ङ—थूभ (<स्तूपः)=स्मृतिस्तम्भः, मृल्लोष्ठादिचयः-विसे. ६९८; सुपा. २०९।

ङ—थूव
ङ—थूह } (<स्तूपः)=स्मृतिस्तम्भः, मृल्लोष्ठादिचयः-सुर. १,५८।

छ—√थुपरना=स्थूलकंगु-(वटक)-मञ्जरी राशीकृत्य तासां सभार-माच्छादने।

√स्तृ (स्तृञ्) ५/६ श
आच्छादने (उ) क्षी-मै-सा-जै-काकृ-कात-शा-हे। छादने—च। स्तृतौ—वो।
√स्तृ ५/ प्रीतिरक्षापालने (प) वो। स्तृणाति—निघ. २/१९=वधकर्मा।

क—द्रष्ट.√स्तृ ९/२१।

ग—(स्तृणीत बर्हिरासदे-ऋ. ५,२६,८)। प्रत्यगेनमभिचारः स्तृणुते-तैब्रा. १,७,७,५। यत्र वेदीं पुण्डरीकैः स्तृणोति-मभार. १३,४८९६।

+√स्तृंहू (स्तृन्हू) ६/७१
मै-श-च-जै-काकृ-शा-हे× (कात-√स्तृंहू)
√स्तृंहू (ष्टृन्हू)........
हिंसार्थः (प) क्षी-सा-कात। वधे—वो। हिंसायाम् (प) इति दुर्गः—क्षी।
√तृहू (तृह) ६/ हिंसायाम् (प)।
√तृंहू (तृन्हू) ६/ हिंसायाम् (प)।
√स्तृहू (स्तृहू) ६/ हिंसायाम् (प)।

"क्षीरस्वामी तु ष्टृन्हू हिंसार्थः"-पुरुषकारे १२१ पृ.।

+√स्तृक्ष (स्तृक्ष) १/६५२
मै-सा-श×(काकृ (√स्तृक्ष)
गतौ (प) क्षी-च-जै-काकृ-कात-शा-हे। गत्याम्—वो।
√तृक्ष (तृक्ष) १/ गतौ (प)।
√स्तृख् १/४६० b चलने (आ) काकृ।

√स्तृक्ष् (ष्टृक्ष) श-च-जै-काक्र-कात-शा-वो×	'गतौ' न्याय्यः—क्षी। क्षी-मै-सा-हे !	
√स्तृह् (स्तृहू) ६/७० श-च-जै-काक्र-कात-शा×	हिंसायाम् (प) क्षी,-हे। हिंसार्थः— मै-सा-कात। वधे—वो।	
√स्तृह् (ष्टृहू) सा×, श-(कात- √स्तृह्)	हिंसार्थः (प)। क्षी-मै-जै-कात-शा। हिंसायाम्—च-काक्र-हे। वधे—वो।	

ग—स्तृहन्तीं गां नाचक्षीत्—आपस्त. १,३१,९।

√स्तृ (स्तृञ्) ९/१२ श	छादने (उ) क्षी-च-वो। आच्छादने— मै-सा-जै-कात-शा-हे। आप्रवणे—काक्र।	स्तृणाति–निघ. २/१९=वध-कर्मा।

क—स्तॅर्=विस्तारे, विकीर्णौ–वा. पाकर्नीः। लैति. स्तॅर्नो; पु. उ. ज.–स्तिर्न; एँग्लो-सैक्सॉ. स्तॅऑ र्नें दे=क्रूरम्—जू. पाकर्नीः।

ख—अवे. स्तर् (वर्तमा०–स्तरैति, स्तूर्नओइति, स्तूर्नाइति)–वा. पॉकर्नीः।

ग—स्तृणाति–शांब्रा ३,९; शब्रा. १,३,३,८। स्तृणीहि–गोब्रा. २,२,१६।

+√स्तेप् (ष्टेपृ) १/३६० श×	क्षरणार्थः (आ) क्षी-मै-सा-च-कात। क्षरणे—काक्र-शा-हे। जै ? श्च्युति—वो।	√तिप् (तिपृ) १/ क्षरणार्थः (आ)। √तेप् (तेपृ) १/ क्षरणार्थः (आ)। √स्तिप् (ष्टिपृ) १/ क्षरणार्थः (आ)। √शिप् १/४५७८ क्षरणे (आ) काक्र।

√शेफ् १/४५७ a क्षरणे (आ) काक्रु।
√स्तिप् (स्तिप) १०/ क्षेपे (प)।

√स्तै (ष्टै) १/९२६ क्षी-श-शा-हे× | वेष्टने (प) मै मै-सा-च-जै-काक्रु-कात। वेष्टे—वो। | √स्नै (ष्णै) १/ वेष्टने (प)।

नो गणनिर्देशः····गुप्तत्वे, अप्राकाश्ये—ह्वि.।

ग—स्तायन्त्०-अ.वे. ४,१६,१; ७,१०८,१ (=चोरितम्, गुप्तम्, अप्रकाशितम्)।

√स्त्यै १/८९६ श× | शब्दसंघातयोः (प) क्षी-मै-सा-काक्रु-कात। शब्दे संघाते च—च-शा-हे। संघाते—जै। संहतौ ध्वनौ—वो। | √ष्ट्यै १/ शब्दसंघातयोः (प) स्त्रियः स्त्यायतेरपत्रपणकर्मणः-निरु.३,२१,२

क—स्ताइ्-, स्ति-, स्ती-, स्ति्-आ = संघाते, घनीभावे।
ख—अवे. स्ता (य्)=राशिः, संहतिः-वा. पॉकर्नीः।
ग—स्त्यायते ०गन्धः-उत्तरराम. ३४,१ (४५,३)।
ङ—ठीण (<स्त्यान०)=घनीभूतम्, पिण्डीभूतम्—कुमा.।

√स्थग् (ष्ठगे) १/७८३ श-काक्रु-कात-शा× | संवरणे (प) क्षी-मै-सा-च-जै-हे। संवृतौ—वो। | >√सग् (षगे) संवरणे (प) इति दुर्गः-क्षी।
√स्थग् (स्थगे) १/७८४ मै-श-च-जै× | संवरणे—क्षी-सा-काक्रु-कात-शा-हे। संवृतौ—वो।

क—(स्) तेग्=आच्छादने-वा. पॉकर्नीः। लैटि.-तेगो-एरे=आच्छादने। लिथु. स्तिऐगि्ति=छादनेन सहोपस्थितौ-जू. पॉकर्नीः।

ग—स्थगयसि पुनरोष्ठम्-मालतीमा. ७,८;१४९,१५। स्थगयति दिशं तमः-रत्नाव. ६०,६। स्थगयसि-बृहत्सं. ५,६। शुद्धो भ्वादिप्रयोगो नोपलभ्यते।

ङ—√थय (सक)=छादने। थएइ–पि. ३०९; गा. ६०५।
ङ—√ठय (सक)=छादने। ठएंति–स. १५९।
ङ—√ठग (सक)=छादने। ठगेइ, ठएइ–सट्टि. २३ टी.; सुख. २,७।

+√स्थल (स्थल) १/८२० मै-सा-श-च-जै-काकृ-कात×	स्थाने (प) क्षी-शा-हे-वो।	√स्था (ष्ठा) १/ गतिनिवृत्तौ (प)।
√स्थल (ष्ठल) श-शा×	'स्थाने' इति चन्द्रः—क्षी। क्षी-मै-सा-च-जै-काकृ-कात-हे-वो।	

क—स्तेल्=स्थितौ, व्यवस्थितौ। म. नि. ज. स्तले, स्तल्=पदम्। पु. आइस. स्ताल्=तृणबुसादिचयः। पु. सैक्सॉ. स्तॉल्लो=स्तम्भाधारः, मूलम्, तलम्। पु. उ. ज. स्तॉलो; म. उ. ज. स्तॉल्ले; आइस. स्तालिम; नॉर्वे. स्तल्मे–जू. पॉकर्नीः।

ग—स्थलयोदकं परिगृह्णाति–तै. १,६,१०,५। स्थली–मनु. ७,१९२। स्थलम्–रघु. ५,५२। स्थालैः सह–याज्ञवल्क्य. ३,८५=अस्थिविशेषैः। स्थालानि="दन्तमूलप्रदेशस्थान्यस्थीनि" इति तत्र मिताक्षरा।

ङ—थल (<स्थलम्)=भूमिः–कुमा.; उप. ९८६ टी.।

√स्था (ष्ठा) १/९१२ श	गतिनिवृत्तौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। स्थाने—वो।	√स्थल (स्थल) १/ स्थाने (प)।

क—स्ता=स्थितौ (आर्याणाम्–स्था–)–वा. पॉकर्नीः। लैति. स्तॉ (स्तारे, स्तेती); गॉथि. स्तॉप–जू. पॉकर्नीः।

ख—अवे. हिश्तेति=स्थितौ–वा. पॉकर्नीः।

ग—आपो अर्वागतिष्ठन्–ऋ. ५,४५,१०। तिष्ठति–ऐब्रा. १,१४। तिष्ठते–शब्रा. १२,२३,९।

ङ—√ठा (अक)=स्थितौ, उपवेशे। वकृ–ठायमाण–उप. १३० टी; संकृ–ठाइऊण–पि. ३०९।

ङ—√चिट्ठ (अक)=उपवेशे। वकृ–चिट्ठंत, चिट्ठेमाण–कुमा.; भग.।

+√स्थुड् (स्थुड) ६/१०५ सा-श-च×	संवरणे (प) क्षी-मै-जै-काकृ-कात-	√थुड् (थुड) संवरणे (प)।

शा-हे । √तुड् ६/८७ a संवरणे
वृत्याम्—वो । (प) च ।

ग—मुकुलीकृतैः स्थुलैः-शिशु. १२,४=दीर्घैः पटमण्डपैः (सर्वङ्कषा)।

ङ—थुलम्=पटकुटी, वस्त्रगृहम्-दे. ५,२८।

+√स्नस् (ष्णसु) ४/४ निरसने (प)
श-च-जै-काकृ× क्षी-मै-सा-कात-शा-हे।
(मै-√स्नुस् [ष्णुस]) मिदित्येके-क्षी
निरासे—वो।
√स्नस (ष्णसु) १/८०५ c निरसने-मित्-सा

>√स्नुस् (ष्णुस) अदर्शने (प) इति द्रमिडाः-क्षी।
√स्नुस् (ष्णुसु) ४/५ अदने (प)।

छ—√छिनकना (<छिनखना<सिनसना<स्नसनम्)=निरसने, नासामलनिस्सारणे, नासातः कफनिस्सारणे।

√स्ना (ष्णा) २/४१ शौचे (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
शोधने—वो ।
ग्लास्नावनुवमां च १/८०३ w मित्त्वं वा।
श-जै-शा-हे-वो×

√स्नै (ष्णै) १/ वेष्टने (प)।

क—स्ना-, स्नू-(त्), स्नौ-, स्न्ऑइ=प्रवाहे, द्रुतगतौ, द्रवे, आर्द्रता।
ख—अवे. स्नयेइति=प्रक्षालने-जू. पॉकर्नीः।
ग—स्नाति-शब्रा. ३, १, २, १०[२]; तैब्रा. ३, ८; अव्यक्तो. ७।
ङ—√सिणा (अक)=स्नाने। सिणाइ-सूअ. १, ७, २१।
ङ—√ण्हाण (अक)=स्नाने। ण्हाणेइ-पि. ३१३।
छ—√न्हाना†*
छ—√नहाना
छ—(√हनाना-बुं.ख.)
} =स्नाने।

√स्निह् (ष्णिह) ४/८७ प्रीतौ (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे-वो।

√स्निह् १/३१६f हिंसागत्योः (प) काकृ।
√स्निह् (स्निह) १०/ स्नेहने (प)।
√स्निट् (स्निट) १०/ स्नेहने (प)।

√स्मिट् (स्मिट) १०/ स्नेहने (प)।
स्नेहयति–निघ. २/१९= वधकर्मा। तुल. काक्र।

क—स्नाइग् = रिङ्गणे, साष्टाङ्गप्रणामे, चाटुत्वे। स्नाइग् उह्-, स्नॉइग्गुहोस् = प्रालेयम्, हिमम्–वा. पॉकर्नीः।

ग—अपष्णिहाम्–पै. १२,३,९। स्निह्यतेः–दैब्रा. ३,४; नरः स्निह्यति–चरक. १,१३। औरस इव पुत्रे स्निह्यति मे मनः–शाकु. १०२,६। यत् स्निह्यते भवान्–मभार. ७,४४५।

ङ—√सिणिज्झ (अक) = प्रीतौ। कवक्र–सिप्पंत–कुमा. ७,९०।

√स्नु (ष्णु) २/१७ श×(च–मुद्रणदोषः) (जै√स्नु) √स्नु इति भाव्यम्।	प्रस्रवणे (प) क्षी-मै-सा-च-काक्र-कात-शा। क्षरणे—जै। प्रस्नवने—हे। प्रस्नुत्याम्—वो।	√स्ना (ष्णा) २/ शौचे (प)।

क—स्ना–स्नाउ–तथा स्नॉइ–जू. पॉकर्नीः।

ग—तस्याः प्रस्नौति स्म नासिका–कथासरि. १३,१२६। मातरौ स्नुवन्त्यौ–भा. पु. १०,८,२३।

+√स्नुस् (ष्णुस) ४/४ श-च-जै-शा×	अदर्शने(प)इति द्रमिडाः –क्षी क्षी, सा (इत्यपरे)।	√स्नस् (ष्णुसु)निरसने (प)।
√स्नुस् (ष्णुसु) ४/५	अदने–मै-सा-काक्र-कात-हे। आदाने इत्येके–सा। भक्षे–वो।	
√स्नुस् (ष्णुस) ४/६	'निरसने' इत्येके—मै। भिन्न।	
+√स्नुह् (ष्णुह) ४/८६ श	उद्गिरणे (प) क्षी-मै-सा-च-जै-काक्र-	√स्नुह् १/३१६J हिंसागत्योः (प) काक्र।

	कात-शा-हे ।	√स्नु (ष्णु) २/२७ प्रस्रवणे (प)।
	उद्गारे—वो ।	√स्नुस् (ष्णुस) ४/६ निरसने (प)।

ग—स्नुही-सुश्रु. १,३२,१६ ।

√स्नै (ष्णै) १/९०७	वेष्टने (प)	√स्ना (ष्णा) १/ शौचे (प)।
श-च-जै-काकृ-कात-वो ×	क्षी-मै-सा-शा-हे ।	
√स्ना ४/	स्नाने (आ)-ह्वि. ।	

क—(स्)ने-तथा (स्)नाइ । लेट्टिश्-स्नते, स्नने, स्नात्(ऐ)ने-जू. पॉकर्नीः ।

ग—स्नायन्-गोत्रा. १,२,५ [स्नाति-स्नायत्योः सन्देहः]। पाश्चात्याः पद्म-पत्राक्ष्याः स्नायत्या जघनं घनम्-मभार. इति वेस्तरगार्द् ।

√स्पन्द् (स्पदि) १/१४	किञ्चिच्चलने (आ)
श	क्षी-मै-सा-च-जै-काकृ-कात-शा-हे ।
	ईषत्कम्पे—वो ।

क—स्प् (ह्) ऐ (न्) द् = स्पन्द तथा स्पेन्ध् = दीप्तौ । ऍंग्लो-सैक्सॉ. फिन्त, स्पेन् = कर्षणे । लैति. पेन्देओ, स्पेन = कर्षणे-वा. पॉकर्नीः ।

ग—स्पन्दते-पत्रा. ३,७ । स्पन्दते मे दृढं बाहुः-वा. रा. ३,७४,११ ।

ङ—√ फंद (अक) = स्फुरणे । फंदइ, फंदंति-उत्त. १४,४५ ।

छ—√ फांदना (<स्पन्दनम्) = कूर्दने, लङ्घने ।

छ—फरफंद (<प्रस्पन्दः) = चाञ्चल्यम् , छलम्-बुं. ख. ।

√स्पर्ध् (स्पर्ध) १/३	संघर्षे (आ)	स्पूर्धसे-ऋ.४ ,६४,४ ।
श	क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	स्पूर्धन्-ऐत्रा. ५,१६ ।
	संहर्षे—वो (श. क. द्रु.) ।	

संघर्षः = पराभिभवेच्छा-क्षी ।

क—स्प् (ह्) एरेद् (ह्)-नासिक्यम्—स्प्(ह्)रेन्द्(ह्)-द् (ह्)-विस्तारः स्प् (ह) र् इत्यस्य = विस्तारे, उच्छालने, क्षेपणे, कूर्दने, गॉथि.-स्पौर्दस् =

अश्वधावनस्पर्धावर्तुलपथः; पद्या, एकपदी। एँग्लो-सैक्सॉ. स्प्यू र्दु = अश्वधावनवर्तुलपथः, अश्वधावनस्पर्धा। पु. उ. ज.-स्पुर्त् = अश्वधावनवर्तुलपथः; म. उ. ज.- स्पोर्ते-अन्तः, पुच्छभागः-वा. पॉकर्नीः।

ख—अवे. स्पूर्द्-जू. पॉकर्नीः। फ़ा०. स्पूर्द्=लालसा-वा. पॉकर्नीः।

ग—स्पर्धेते-शब्रा. २, २,२,१४; स्पर्धन्ते-ऐब्रा. २, २०। स्पर्धते-बृहदारण्यको. १, ५, २१। स्पर्द्धा-मभार. १, २१, १७=संहर्षः स्पर्धयेष महाक्रतुः-३, १५२९२।

ङ—फद्धा (<स्पर्द्धा)-कुमा. ३, १८।

√स्पशृ (स्पश) १/८७३ श-जै-काकृ-कात-शा×	बाधनस्पाशनयोः (उ) क्षी। बाधनस्पर्शनयोः —मै-सा-हे। बाधने—च। ग्रन्थबाधयोः—वो। दर्शने—ह्वि,।	>√पष् (पष) बाधनस्पाशनयोः (उ) इत्येके —क्षी। √पशृ (पश) १०/ बन्धने (प)। √स्पशृ (स्पश) १०/ ग्रहणसंश्लेषणयोः (आ)।

स्पाशनम्=ग्रथनम्-क्षी।
स्पर्शनम्=ग्रथनम् इति स्वामी-सा ८७२।

क—स्पेश्=परीक्षणे, अन्वेषणे।

ख—अवे. स्पस्त=(लैति. स्पेक्तुस्=) स्पष्टः।

ग—प्रतिस्पशो विसृज-ऋ. ४,४,३। पस्पशे-शब्रा. ३,७,१,१७। स्पशम्=तैब्रा. २,४,६,७। सैषोभयतः स्पाशारज्जुर्भवति-मभाष्य.-६,१,६८=पाशः। स्पशः= चरः-मभार. १,१४७,२५।

छ—√फँसना=बाधने।

छ—√फाँसना=बाधने।

√स्पृ ५/१३ श-काकृ-कात×	प्रीतिबलनयोः (प) इत्येके-क्षी। क्षी। प्रीतिपालनयोः—मै-सा। प्रीतौ—च। प्रीतिचलनयोः—इत्येके —मै-सा।	>√स्मृ प्रीतिबलनयोः (प)। √पृ ३/ पालनपूरणयोः (प)।

प्रीतौ चलने च—जै।
प्रीतौ बलने च—शा।
प्रीतौ पालने च—हे।
प्रीतिरक्षाप्राणने—वो।
जये—ह्वि.।

क—स्पृ = शैथिल्ये। लैति. स्पेर्नो; पु. आइस्. स्पार. पु. उ. ज.–स्पॉरो, स्पॉर्न। लिथु. स्पिर्ति = प्रेरणे–जू. पॉकर्नीः।

ग—स्पृणवाम–ऋ. ५,४४,१०; स्पृणुहि–१०,८७,७। स्पृणोति–तांब्रा. २,१४,२। क्रैयादिकोऽपि–स्पृणाति–जैउ. ४७,१,९। स्पृणुते–शब्रा. १,३,५,१३।

√स्पृश् (स्पृश) ६/१४१ श

संस्पर्शे (प)
क्षी-मै-च-काकृ-कात-हे।
संस्पर्शने—सा।
स्पर्शे—जै।
स्पर्शने—शा।
स्पृशि—वो।

√छुप् (छुप) ६/१३७ संस्पर्शे (प)।

ग—उशतीरुशन्तं स्पृशति–ऋ. १,६२,११। स्पृशते–प्रश्नो. ४,२; वरा. २,५८।

घ—छुपति–विनय.१,१९१।

ङ—√फरिस (सक) = स्पर्शे। कवकृ–फरिसिज्जंत–धर्मवि. १३६।

ङ—√फास (सक) = स्पर्शे, (२) पालने। फासइ–भग.।

ङ—√फंस (सक) = स्पर्शे। कर्म. फंसिज्जइ–कुमा.।

ङ—√फुस (सक) = स्पर्शे। फुसइ–भग.।

ङ—√फोस (सक) = स्पर्शे। फोसंति–जीवस. १९९।

ङ—√छिव (सक) = स्पर्शे। वकृ–छिवंत–गा. २६९। कवकृ–छिप्पंत, छिविज्जमाण–कुमा.; गा. ४४३।

छ—√छूना = स्पर्शे।

छ—√छीना = स्पर्शे–बुं. ख.।

√स्फट् (स्फट) १/३२६ मै-श-जै-काकृ-कात-शा ×

विशरणे (प) इति नन्दिस्वामी—क्षी।
क्षी-सा-च-हे।
शीर्णौ—वो।

<√स्फण्ट् (स्फटि) विशरणे (प)।
√फल (ञिफला) १/ विशरणे (प)।

क—(स्) प् (ह्) ऐल् =दारणे-वा. पॉकर्नीः ।
ग—स्फटिक०–श्वेताश्वतरो. २,११ । स्फाटिकम्–मभार. २,५५,१७ ।
ङ—√फड (सक)=खनने, शोधने–सुपा. ६१३ ।
च—√फट्ट (अक)=स्फटने, विशरणे । फट्टइ–भवि. ।
छ—√फटना=विशरणे, मनाग्दीर्णे ।

+√स्फण्ट् (स्फटिं) १/३२६ मै-सा-श-च-जै-काकृ-कात-शा×	विशरणे (प) क्षी-हे । शीर्णौ—वो ।	>√स्फट् (स्फट) विशरणे (प)।

√स्फर् (स्फर) ६/१११ श-च-काकृ-कात×	चलने (प) क्षी-हे । स्फुरणे—सा-जै-शा-हे । स्फुरणे सञ्चलने दीप्तौ —वो ।	√स्फल् (स्फल) ६/ चलने(प)। √स्फुर् (स्फुर) ६/ चलने (प)। √स्फुल् (स्फुल) ६/ चलने (प)।

ग—अपस्फरीः–ऋ. ६,६१,१४; मै. ४, ११,२; काठ. १७, १८; क. ४६,६ । कार्मुकं स्फारयामास–वा. रा. ५,४४,४ । विस्फारयति–मभार. १,६४४२ ।
छ—√फनना=कार्यारम्भे ।
छ—√फरकना, छ—√फड़कना } (<स्फरणम्)=चलने, स्फुरणे ।

√स्फल् (स्फल) ६/११३ मै-सा-श-च-काकृ-कात×	चलने (प) क्षी-जै-शा-हे । स्फूर्तौ चाले च—वो । ताडने—ह्वि. ।	√स्फर् (स्फर) ६/ स्फुरणे सञ्चलने दीप्तौ च (प) मै ।

ग—गजेन गजमास्फाल्य–हरिवंश. ६२२३ । आस्फालितं यत् प्रमदाकराग्रैः–रघु. १६,१३=ताडितम् (संजी.) ।

छ—√फिसलना (<सिफलना<स्फलनम्)=चलने, स्खलने । प्रसरणादस्य व्युत्पत्तिश्चिन्त्या ।

√स्फाय् (स्फायी) १/४८४ श×	वृद्धौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । संवृद्धौ—वो ।	√प्याय् (ओप्यायी) १/ वृद्धौ(आ) √प्यै (प्यैङ्) १/ वृद्धौ (आ)।

क—स्प् (ह्) ए (इ)-, स्पी-तथा स्फे-ः स्फू=वृद्धौ । पु. उ. ज.-स्पाति, स्पातॉ, स्पःत्; ऍग्लो-सैक्सॉ. स्पॉवन्=वृद्धौ; लिथु. स्पेति=अधिकारे; लेट्टिश्-स्पिते=अवज्ञा, आह्वानम् (युद्धाय), अविनयः; पु. च. स्ला. स्पेति=साफल्ये; स्पर=स्फिरम्—जू. पॉकर्नीः ।

ग—स्फात्यै-तैब्रा. ३,२,४,७ । स्फीयन्ते-साब्रा. ३,३,१ । अपस्फानस्य-पै. १,५८,१ । स्फावयिता-ऐब्रा. १,१३ ।

+√स्फुट् (स्फुट) १/२५७ विकसने (आ)
क्षी×,श
मै-सा-च-जै-काकृ-कात-शा-हे ।
विशरणे—वो ।

उत्तरधातोरेवायं भेदः । आत्मनेपदनिमित्तं पार्थक्यम् ।

√स्फुट् (स्फुटिर्) १/३२७ विशरणे (प)
श×
क्षी-मै-सा-च-जै-कात-शा-हे-वो ।
विशरणे विकासे च—काकृ ।

√स्फट् (स्फट) १/ विशरणे (प) ।

क—द्रष्ट. √स्फट् १/३२६ ।

ग—स्फोटतः-शब्रा. ८,१,४,९ ।

ङ—√फोड (सक)=विदारणे, (२) राजिकादिना शाकादेर्व्याघारणे । फोडेज्ज-कुप्र. ६७ ।

छ—√फोड़ना (<स्फोटनम्) ।

√स्फुट् (स्फुट) ६/९३ विकसने (प) कुटादिः
श
क्षी-मै-सा-जै-काकृ-कात-शा-हे ।
भेदे—च ।
विकाशे—वो ।

√स्फट् (स्फट) १/ विशरणे (प) ।
√स्फुट् (स्फुटिर्) १/ विशरणे (प) ।
√फुल् (फुल) १/२४४ a विकसने (प) काकृ ।
√फुल्ल् (फुल्ल) १/ विकसने (प) ।

क—द्रष्ट. √स्फट् १/३२५ ।

ग—स्फुटति-षत्रा. ५,७। हृदयं प्रस्फुटिष्यति-वा. रा. ६,७२,५५। यदि पुरोडाशः स्फुटेत्-आश्व. श्रौ. ३,१४,१३।

ङ—√फुट,√फुट्ट (अक)=विकसने, (२) प्रकाशने, (३) विशरणे, (४) नाशे। फुटइ, फुट्टइ—संक्षि. ३६।

छ—√फूटना।

+√स्फुड् (स्फुड) ६/११६	संवरणे (प) मै	पूर्ववत्।
क्षी-श-जै-काक्र-कात-शा-हे×	मै-सा-च।	
	वृत्याम्—वो।	

ङ—√फुड=विकसने, संवरणादौ। फुडंति-उप. ७२८ टी; वक्र-फुडमाण-सुर. ३,२४३।

+√स्फुण्ड् (स्फुडि) १/२७५	विकसने (आ)	पूर्वद्वयवत्।
मै-श-जै-काक्र-कात-शा×	क्षी-च-हे।	
	इति केचित् पठन्ति—सा।	
	फुल्ले—वो।	

√स्फुर् (स्फुर) ६/११२	चलने (प)	√स्फुल् (स्फुल) ६/११३
श	क्षी-सा-च-हे।	चलने (प)।
	स्फुरणे संचलने दीप्तौ च—मै।	शेषः√स्फुट् ६/९३ वत्।
	स्फुरणे—जै-काक्र-कात-शा-हे।	स्फुरति-निघ. २/१९=वधकर्मा।
	स्फूर्तौ चले—वो।	

क—स्प् (ह्) एर्-, स्प् (ह्) एर्=कर्षणे, उद्योगे, कूर्दने, उड्डयने—जू. पॉकर्नीः।

ग—क्षम्पमिव स्फुरत्-ऋ. १,८४,८; उपरि स्फुरन्ति-१०,३४,९। स्फुरति-योशि. ४,१७। स्फुरते नयनं सव्यम्-हरिवंश. ९२९८; कस्य स्फुरते जिह्वा स्तुतौ-१४९०२।

ङ—√फुर=चलने, (२) विकसने, (३) प्रकाशने। फुरइ-से. १५,७६; पिंग.।

ङ—√हुर=(१) चलने, स्फुरणे, (२) विकसने, (३) प्रकाशने-कुप्र. ४२०।

च—√फुल। फुला-पिंग.।

छ—√फुरना *=विकसने, निर्गमे।

+√स्फुर्च्छ् (स्फुर्छा) १/२१० शX	विस्मृतौ (प) इति दुर्गः—क्षी क्षी-च-कांक्र-कात-शा-हे-वो। विस्तृतौ—मै-सा-जै।	<√स्मुर्च्छ् (स्मुर्छा) विस्मृतौ (प)।
√स्फुल (स्फुल) ६/११४ शX	चलने (प) क्षी-सा। सञ्चये च=चलने—(क्षी.यु.मी.सं.) च-जै-शा-हे। सञ्चलने—मै-सा। स्फुरणे सञ्चये च—काक्र-कात-हे। स्फूर्तौ चले—वो। चये चले—वो।	√स्फुर् (स्फुर) ६/११२। शेषः√ स्फुट् ६/९२ वत्।

ग—स्फुलिङ्गिनी–मुण्डको. १,२,४=अग्निसप्तजिह्वान्तर्गतजिह्वाविशेषः। स्फुलिङ्ग०–वा. रा. ३,३४,६। कर्णाभ्यर्णस्फुलित०–वालरा. ८७,१५।

√स्फूर्ज् (टुओस्फूर्जा) १/२३१ श	वज्रनिष्पेषे (प) क्षी-च। वज्रनिर्घोषे—मै-सा-जै-काक्र-कात-शा-हे-वो।	पूर्ववत्।

क—* (स्) प् (ह्) ऐरेज्–, (स्) प् (ह्) ऐरूज्–, (स्) प् (ह्) रेज्–(नासिक्यम्–स्प्रेंज) स्प् (ह्) ऐर् इत्यत्र–ज् इत्यस्य विस्तारः=कर्षणे, वज्रवन्निर्घोषे; उच्छलने। लिथु. (स्प्रञ्ज,–एति=(वज्रनिर्घोषे) विस्फोटे; स्वरपरिवर्तनेन स्प्रॉग्ति=विशीर्योड्डयने; सशब्दं विशरणे। लैति. स्पर्गो=सशब्दं विशरणे– जू. पॉकर्नीः।

ग—वाश्यमानाभिस्फूर्जति–अ.वे. १२, ५, २०। अर्चिषा स्फूर्जयन्–ऋ. १०,८७,११। अवास्फूर्जत्–पै. २,७०,४। अवस्फूर्जते–मा. २२, २६; का. २४, १२, १।

√स्मि (ष्मिङ्) १/९३३ (यु. मी. सं.—स्मिङ्) च-जै-काक्र-कात X,श	ईषद्धसने (आ) क्षी-मै-सा-शा-हे। स्मितौ—वो।	√स्मिट् (स्मिट) १०/अनादरे (प)।
√स्मि (स्मिङ्)........ १/२६८	ईषद्धसने—जै-काक्र-कात। विहसने—च।	

क—(स्) माइ-, स्मॉइ=ईषद्धसने, आश्चर्ये। लेट्टि. मेंर्जु, स्मिएत्=हासे अलेम. रिमए=आश्चर्ये; mengl. स्मीलिन्; इँग्लि. स्माइल; पु. च. स्ला. स्मिज-ति से=हासे-जू. पॉकर्नीः।

ग—श्रिये स्मयते विभाती (उषाः)-ऋ. १, ९२, ६। स्मयसे, सिष्मिये-जैब्रा. १५१।

+√स्मील (स्मील) १/५२० निमेषणे (प) क्षी-मै-सा-च-जै-शा-हे-वो। श-काकृ-कातX (क्षी. यु. मी. सं.X)

√श्मील (श्मील) १/निमेषणे (प) मै।
√क्ष्मील (क्ष्मील) १/ निमेषणे (प)।
√मील (मील) १/ निमेषणे (प)।

निमेषणम् =संकोचः—क्षी।

√मील्>√स्मील् इति।

+√स्मुर्च्छ् (स्मुर्छा) १/२१० विस्मृतौ (प) क्षी-हे-वो। मै-सा-श-च-जै-काकृ-कात-शाX

>√स्फुर्च्छ् (स्फुर्छा) विस्मृतौ (प) इति दुर्गः-क्षी।
√मुर्च्छ् (मुर्छा) १/ मोहसमुच्छ्राययोः (प)।

√स्मृ १/८०० आध्याने (प) ज्वलादिः क्षी-मै-सा-जै-काकृ-कात-शा-हे।
शX अध्ययने—च।
औत्क्ये—वो।

ग—नान्यद् दृष्टं स्मरयत्यन्यः-सर्वदर्शनस. ८४,१५।

√स्मृ १/९१७ चिन्तायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
श स्मृतौ—वो।

क—(स्) मेर्=स्मरणे, ध्यानाकर्षणे। पु. लिथु. मेरेति=चिन्तायाम्; सेर्बि. मरिति=चिन्तायाम्।

ख—अवे. मरैति,हिस्मरैति=स्मरति, ध्याने, विचारणे-जू. पॉकर्नीः।

ग—स्मरति-गर्भो. ३; सुबा. ११; गी. ८,१४। स्मरन्ते-शांआ. ४,४।

ङ—√समर (सक)=स्मरणे–चउ. १७; नाट–शाकु. ६।

ङ—√सर (सक)=स्मरणे। सरइ–गुरु. १२।

छ—√सौंरना*, √सुमरना*†, √स्मरना (<स्मरणम्)=स्मरणे, चिन्तने, ध्याने।

छ—√सिमरना†, √सुमिरना* (<स्मरणम्)=स्मरणे, चिन्तने, ध्याने।

+√स्मृ ५/१३ च-जै-शा×,श — प्रीतिबलनयोः (प) क्षी। प्रीतिचलनयोः—मै-सा। प्रीतौ पालने च—काकृ-(उ),-कात-हे। जीवने—हे। प्रीतिरक्षाप्राणने—वो। — >√स्पृ प्रीतिबलनयोः (प) इत्येके–क्षी।

√स्यन्द् (स्यन्दू) १/७५३ श× — स्रवणे (प) क्षी-मै-च-काकृ-कात-शा-हे। प्रस्रवणे—सा। स्रवे—जै। स्रुतौ—वो। — स्यन्दते–निघ. २/१४=गतिकर्मा।

ग—स्यन्दते-ऋ. ९,८०,३; स्यन्दन्तां कुल्याः–५,८३,८। स्यन्दन्ति–गोब्रा. १,२,१४।

घ—सन्दति-दीघ. २,१२८; जातक १,१८।

ङ—√संद (अक)=क्षरणे, श्च्योतने। संदंति–सूअ. १,१२,७।

+√स्यम् (स्यमु) १/८०९ श-वो× — शब्दे (प) मित् क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। — √स्यम् ६/ ध्वनने (प) वो। स्यमति–निघ. २/१४=गतिकर्मा। सीमिका स्यमनात्–निरु. ३,२०,७ सीमिका=पिपीलिका–दुर्गाचार्यः।

+√स्रंस् (स्रन्सु) १/३९१ श-च× (जै-काकृ- √श्रंस्)	प्रमादे (आ) इत्येके-क्षी क्षी-मै-सा-जै-काकृ- कात-शा-हे-वो।	<√स्रम्भ् (स्रन्भु) प्रमादे (आ)।

अवस्रंसनार्थकस्य √स्रंस् १/७४५ इत्यस्य धातोः स्यादर्थभेदः।

√स्रंस् (स्रन्सु) १/७४५ श (काकृ—√श्रंस्)	अवस्रंसने (आ) क्षी-मै-सा-च-काकृ- कात-शा-हे। अवस्रंसे—जै। भ्रंशे—वो।	स्रंसति—निघ. २/१४=गतिकर्मा।

क—स्रेन्स्—अथवा स्रेम्स्=स्रंसने—जू. पॉकर्नीः।

ग—(अतिस्रसेम वृजिनम्—ऋ.६,११,६।) स्रंसते—शब्रा.४,५,७,६; गी. १,३०। स्रंस्यमाने वसने—वा. रा. ५,३६,३७ इत्यत्र स्रसिधातुः।

ङ—√ल्हस (अक)=स्रंसने, स्खलने। वक्क—ल्हसंत—वज्जा. ९०।

+√स्रंहू (स्रन्हु) १/७४९ मै-सा-श-च-जै-काकृ- कात-शा×	विश्वासे (आ) इति कौशिकः—क्षी। क्षी-हे-वो। स्पष्टो विकासः।	<√स्रम्भ् (स्रन्भु) विश्वासे (आ)।

+√स्रङ्क् (स्रकि) १/८२ क्षी-श-च-जै- कात-हे×	गत्यर्थः (आ) मै। मै-सा। गतौ—काकृ-शा। गत्याम्—वो।	√श्रङ्क् (श्रकि) १/ गत्यर्थः (प)। √श्लङ्क् (श्लकि) १/ गत्यर्थः (प)। √स्रेक् (सेकृ) १/ गत्यर्थः (प)।

क—स्लेङ्क्-,स्लेङ्ग्=वेष्टने—वा. पॉकर्नीः।

ग—सृङ्कां चेमामनेकरूपां गृहाण—कठोप. १,१,१६। सृङ्काम्=मालाम्।

+√स्रंभ् (स्रन्भु) १/३९० मै-श-च-जै-काकृ-कात- शा×	प्रमादे (आ) क्षी-सा-हे-वो।	>√स्रंस् (स्रन्सु) प्रमादे (आ) इत्येके—क्षी। √श्रम्भ् (श्रम्भु) १/ प्रमादे (आ) क्षी (यु. मी. सं.)।

प्रमादः=अवलेपः—क्षी।

+√स्रंभ् (स्रन्भु) १/७४९ (श-काकृ-√श्रम्भ्)	विश्वासे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	>√स्रंह् (स्रन्हु) विश्वासे (आ) इति कौशिकः-क्षी।

√स्रिव् (स्रिवु) ४/३ श-च-जै-कात-शा-हे×	गतिशोषणयोः (प) क्षी-मै-सा-काकृ। शोषे गतौ—वो।	√श्रिव् (श्रिवु)४/३a गतौ (प) च।
√स्रीव्	स्रंसने—ह्वि.।	√श्रिव् ४/३ गतिशोषणयोः (प) कात-शा। √श्रिव् ४/२२ गतिशोषणयोः (प) हे।

क—लैट्‌आॅ=? पु. उ. ज.-स्लेआॅ; एँग्लो-सैक्साॅ. स्लाव्; पु. आइस्. स्ल्जाॅर्, स्लार्; पु. सैक्साॅ. स्लेउ=निर्बलः, मन्दः, मूर्खः-वा. पॉकर्नीः।

ग—स्रीव्यन्ति वै तानि-ऐब्रा. ४,२२।

√स्रु १/९२७ श-जै× (काकृ-√स्रू)	गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे द्रुवत् (=स्रुतौ गतौ) —वो	√सु (षु) गतौ (प) मै। √सृ १/ गतौ (प)। स्रवति-निघ. २/१४=गतिकर्मा। √श्रु १/ गतौ (प)।

क—स्राॅइ=प्रवहणे, द्रवे, द्रुतगतौ-जू. पॉकर्नीः। पु. च. स्ला. स्रोवो=स्रवः। लिथु. स्रुत=स्रुतम् (:); लेट्टिश-स्रौत्स्=स्रुतम् (:)-वा. पॉकर्नीः।

ग—सम्यक् स्रवन्ति सरितो न धेनाः-ऋ. ४,५८,६। स्रवति-शब्रा. ९,५,१,५७। स्रवते-हंसो. १९।

ङ—√सव (अक)=स्रवणे। सवइ-विसे. १३६८।

ङ—√सय (अक)=स्रवणे। सयइ-सूअ. २,२,५६।

छ—√स्रवना*=प्रवहणे, स्रवणे, निश्च्योतने (स्रंसने)।

छ—√सूवना*†=प्रवहणे।

+√स्रेक् (स्रेकृ) १/८० श-कात×	गत्यर्थः (आ) क्षी-मै-सा-च। गतौ—जै-काकृ-शा-हे। गत्याम्—वो।	√सेक् (सेकृ) १/ गत्यर्थः (आ)। √शीक् (शीकृ) १/ गत्यर्थः (आ)।

ग—स्रेकपर्णाष्ठीवन्ता कृणुतात्–तैत्रा. ३,६,६,३।

छ—सरगना=विकत्थने, मिथ्याप्रशंसने (देश. ?)।

+√स्नै १/९०३ सा-श×	पाके (प) क्षी-मै-च-जै-काकृ-कात-शा-हे। पचि—वो।	√श्रा २/४२ पाके (प)। √श्रै १/९०४ पाके (प)।

ग—अभ्यवस्नातेन–पै. ९,२२,१८।

+√स्वङ्क् (स्वकि) १/९६ क्षी-मै-श-च-जै-शा-हे-वो×	गत्यर्थः (आ) सम्मतायाम्–सा। सा-कात।	<√श्वङ्क् (श्वकि) गत्यर्थः (आ)। सु+√अङ्क्=√स्वङ्क् इति वागीशः। √श्वङ्ग् (श्वगि) १/ गत्यर्थः (आ) मै।
√स्वञ्ज् (ष्वन्ज) १/९६१ जै-शा-हे×,श	परिष्वङ्गे (आ) क्षी-मै-सा-च-काकृ-कात। आलिङ्गे—वो।	√स्वञ्ज् ६/१४४ सङ्गे (आ) जै। √स्वञ्ज् ६/१२३सङ्गे(आ)शा। √स्वञ्ज् ६/१५७सङ्गे(आ) हे।

क—सुएेङ्ग्–, सुएेङ्क्–, सुएेग्–, सुएेक्–ः सॉङ्क् =नमने, इतस्ततो दोलने–वा. पॉकर्नीः। नार्वे. स्वेक=स्वक्तम्; म. उ. ज.–स्वेङ्केन् =स्वक्तम् –जू. पॉकर्नीः।

ख—पइरिस्क्स्वक्स्त=परिष्वक्तम्—वा. पॉकर्नीः।

ग—परिष्वजे–ऋ. १०,४०,१०। पितेव पुत्रानभि सं स्वजस्व–अ.वे. १२,३,१२। स्त्री पुमान् संपरिष्वक्तौ–शत्रा. १४,४,२,४।

√स्वद् (ष्वद) १/१८ श×	आस्वादने (आ) क्षी-मै-सा-च-काकृ-कात-शा-हे। 'संवरणे' इति क्षीरस्वामी–सा। आस्वादे—जै। प्रीतिलिहोः—वो।	सु+√अद् २/१ भक्षणे (प)=√स्वद्–इति वागीशः।

क—सुआद्=मधुरम्, प्रियम्, रमणीयम्-वा. पॉकर्नीः ।

ख—अवे. क्स्वास्तो-जू. पॉकर्नीः । अफगा. क्स्वन्द्-वा. पॉकर्नीः ।

ग—सस्वदे घर्मम्-ऋ. १,११९,२; ३,१४,७; सोमं स्वदन्ति गावः-९,९२,५ । स्वदते-शब्रा. २,४,४,१६; काब्रा. १,३,४,९ ।

√स्वन् (स्वन) १/८१० श×	शब्दे (प) क्षी-मै-सा-च-जै-काक्‍-कात-शा-हे-वो ।	सु+√अन् प्राणने= √स्वन्-इति वागीशः । सु+√अण् शब्दार्थः= √स्वन्-इति वागीशः ।
+√स्वन् (स्वनः) १/८०३ श-च-काक्‍-कात×	अवतंसने-मित्-दुर्गः-क्षी । क्षी-मै-सा-जै-शा-हे । तंसने—वो ।	.√शंण् १/२०७ q शब्दे (प) काक्‍ । √श्वन् १/२०७ rr शब्दे (प) काक्‍ । √स्त्वन् १/२०७ oo शब्दे (प) काक्‍ । √हण् १/२०७ t शब्दे (प) काक्‍ ।

ग—अव''अस्वनीत्-ऋ. ४,२७,३ । स्वनन्तम्-पारमात्मिको. ६,१० । मही स्वनति गम्भीरम्-वा. रा. २,१०६,७ । अस्य शुष्मासः स्वनयन्-ऋ. १०,३,६-मित् ।

√स्वप् (ञिष्वप्) २/५७ श	शये (प) क्षी-मै-सा-च-जै-काक्‍-कात-शा-हे-वो ।	सु+√आप् (आप्लृ) व्याप्तौ (प)=√स्वप् इति वागीशः ।

क—सुऐप्-, सुप् =शयने । लैटि. सॉपिओ,-ईरे=शयने; ऍंग्लो-सैक्सॉ. स्वफन् =स्वप्ने ।

ख—क्स्वप्=निद्रायाम्, शयने-वा. पॉकर्नीः ।

ग—स्वपिति-ऐआ. ३,१,६; शब्रा. १,६,३,४१ । यदा स्वपिति शान्तात्मा-मनु. १,५२=निवृत्तेच्छो भवति (मन्वर्थ.)

ङ—√सुव (अक)=शयने । सुवई, सुवंति-महा.; रंभा. ।

ङ—√सुअ (अक)=शयने । सुअइ-पि. ४९७; उत्र. सुयामि-निसा. १ ।

ङ—√सोव (अक)=शयने । सोवइ, सोवंति-उव.; भवि. ।

छ—√सोवना *†
छ—√सोअना*
छ—√सोना } =शये ।

'सोना' इत्यस्य 'शयनम्' इत्यतो व्युत्पत्तिरसमञ्जसा ।

+√स्वर्द् (स्वर्द) १/१९ श×	आस्वादने (आ) क्षी-मै-सा-च-काकृ- कात-शा-हे । आस्वादे—जै । प्रीतिलिहोः—वो ।	√स्वद् (ष्वद) १/१८ आस्वादने (आ) रकारोपजनेन √स्वर्द्— इति वागीशः; सु+ √अर्द् गतौ याचने च (प)=√स्वर्द् इति वा ।
√स्वाद् (स्वाद) १/२७ श×	आस्वादने (आ) क्षी-मै-सा-च-काकृ- कात-शा-हे आस्वादे—जै । प्रीतिलिहोः—वो ।	√स्वद् (ष्वद) १/१८ आस्वादने (आ) । √स्वर्द् (स्वर्द) १/१९ आस्वादने (आ) । √स्वद् (स्वद) १०/२६५ आस्वादने (प) सा । √स्वाद् (स्वाद) १०/२६५ आस्वादने (प) इत्येके- सा ।

ग—स्वादः-ऋ. १,१८७,२ । अन्त्राणि च यथा स्वादेयम्-वा. रा. २,२५,४६ । स्वादेतां तौ च ते फले-हरिवंश. ११३५ ।

√ष्विद् (ञिष्विदा) २/७३५ श×	स्नेहमोहनयोः (आ) इति नन्दी—क्षी । क्षी । स्नेहमोचनयोः—मै । गात्रप्रस्रवणे—सा । पाके—च । स्नेहे मोक्षे च—जै । स्नेहने;मोचने च— काकृ-कात-शा-हे । मोहस्नेहमोक्षे—वो ।	<√क्ष्विद् (ञिक्ष्विदा) स्नेह- मोहनयोः (आ) । √क्ष्विड् (ञिक्ष्विडा) स्नेह- मोहनयोः (आ) इत्या- र्हतः-क्षी । सु+√इन्द् बन्धने= √स्विद् इति वागीशः ।

क—सुआइद्=स्वेदे (स्नेहे), गात्रप्रस्रवणे-वा. पॉकर्नीः। लैति. सूदॉर; एँग्लो-सैक्सॉ. स्वात्; पु. सैक्सॉ. स्वत्; पु. उ. ज. स्वाइज; पु. आइस. स्वाइति; पु.उ.ज. स्विज्जेन=स्विद्यति। लेट्टिशु-स्विएद्रि-जू. पॉकर्नीः।

ख—क्स्वएद=स्वेदः (शार्मण्यभा.-* स्वैत)-ग्रा. पॉकर्नीः।
ग—स्वेदते-ऐआ. १,३,५; छान्दोग्यो. ६,२,३।
छ—सेद (<स्वेदः)

√स्विद् (ष्विदा) ४/७५ मै-श-काकृ-कात-वो×	गात्रप्रक्षरणे (प) क्षी-सा-जै-शा-हे। पाके—च।	पूर्ववत्।
√स्विद् (ञिष्विदा) ४/८२	गात्रप्रक्षरणे—मै। मै-सा-काकृ-कात। स्विदि—वो।	

क—,ख—पूर्ववत्।
ग—स्विद्यति-ह्वि.। मया नोपलब्धम्। स्विद्यते-याज्ञ. २,१३। स्विद्यमान० सुश्रु. २,१८४,५।

√स्वृ १/९१६ श×	शब्दोपतापयोः (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो। शब्दे—च।	सु+√ऋ गतिप्रापणयोः,=√स्वृ इति वागीशः। स्वरति-निघ. २/१४=गतिकर्मा।

क—सुएल्=दीप्तौ। शनैर्ज्वलने-वा. पॉकर्नीः। एंग्लो-सैक्सॉ. स्वेलन्=दीप्तौ; लिथु. स्विल्ति=मनाग्दाहे (उपतापे); प्रयोजके तु स्विलिन्ति-जू. पॉकर्नीः।
ख—अवे. क्स्वरनः-वा. पॉकर्नीः।
क—सुएर्=भङ्कृतौ, भणभणशब्दे, सीत्कृतौ, अव्यक्तशब्दे। लैति. सुसुर्रस्=शनैः संभाषणे-वा. पॉकर्नीः।
ग—स्वरन्ति घोषं विततम्-ऋ. ५,५४,१२। स्वरति-तांब्रा. १३,१२,१३।
ङ—√सर (सक)=शब्दे-सरइ, सरंति-विसे. ४६२।

+√स्वृ ९/१८ क्षी-सा-श-च-जै-काकृ-कात-शा-हे-वो×	हिंसायाम् (प) मै।	√स्वृ १/९१६ शब्दोपतापयोः (प)।

+√हट् (हट) १/३०८ दीप्तौ (प)
श
क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
त्विषि—वो।
√हट्ट् १/१२१ निवासे (प)
काकृ।
√खट् (खट) १. काङ्क्षायाम् (प)।

ग—महाहाटकतोरणम्–वा. रा. ५,४,२४ (गी. प्रे. सं.)-अयं दीप्त्यर्थकः। तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्–मभार. २,२८,३।

ङ—हट्ट=क्रयविक्रयस्थानम्–गा. ७९४; भवि.; (२) विपणिः, निषद्या–सुपा. ११; १८६।

ङ— हट्टिगा / हट्टी } =लघुपण्यशाला–मोह. ९२; सुपा. १८६।

+√हठ् (हठ) १/३३४ प्लुतिशङ्कुबन्धनयोः (प)
श×
क्षी-मै।
प्लुतिशठत्वयोः—सा।
स्तुतिशठत्वयोः—जै।
'स्तुति-' स्यान्मुद्रणदोषः;
'प्लुति-' इत्युचितम्।
प्लुतिशङ्कुत्वयोः—शा।
'बलात्कारे' इति तु चान्द्राः—क्षी।
क्षी-सा-च-काकृ-कात-हे।
बलात्कृतौ—वो।

ग—हठेन मधुरेण च–वा. रा. ५,६१,१७। हठे नैवास्ति पौरुषम्–मभार. ३, ६५९७।

ङ—हड (<हठः)=बलात्कारः–पण्ह. १,३-पत्र. ४४।

छ—√हठना=दुराग्रहे (शाठ्ये)।

√हद् (हद) १/९६२ पुरीषोत्सर्गे (प)
श
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
ग्वर्थे (=विष्ठोत्सर्गे)—वो।

क—घेद्=हदने, विष्ठात्यागे।

ख—अवे. जदह् (<हदः)=नितम्बः–वा. पॉकर्नीः।

ग—हदति–भा. पु. ५,५,३२। हदते–यशस्तिलकच., ३ आश्वा., ३३८ श्लो.=पुरीषोत्सर्गं करोति।

घ—हनति (सम्भवतो निष्ठाप्रत्ययान्तहन्नशब्दसम्बद्धः)-पेतवत्थु ८९।

छ—√हगना=मलोत्सर्गे।

√हन् (हन) २/२ श — हिंसागत्योः (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। हिंसायाम्—चं। गतौ वधे—वो

√हण्ड् १/१८३ a हिंसागत्योः (प) काकृ। √हण् १/२०७ t शब्दे (प) काकृ। वधिः प्रकृत्यन्तरम्-द्र. काशिका ७/३/३५। √घन् इत्यपीति वागीशः, घ्नन्ति, जघानेति दर्शनात्। हनति-निघ. २/१४=गतिकर्मा।

क—गुहन् =ताडने-वा. पॉकर्नीः।

ख—अवे. जैन्ति = हन्ति-पी.टी. ऐस. पालि-इँग्लिश्कोशात्। (जुत=हत (म्)-वा. पॉकर्नीः।

ग—सानौ जघान-ऋ. १,३२,७। हन्ति-ऐब्रा. १,४। हनामि-तैब्रा. ३,१४,४। आसीनं चाहनञ्छूलैः-भा. पु. ७,६, ४०। हतस्य-वा. रा. २,७३,२=प्रापितस्य (तिल.)। ब्राह्मणो हन्तुमर्हति-मभार. ५,४२,३५=गन्तुम् (नील.)। हतः-मभार. ८,१,५६=गतः (नील.)। हन्यमानस्य-मभार. ५,१३३,४०=अनुद्रुतस्य। अत्र हन्तिर्गत्यर्थः (नील.)।

घ—हन्ति-सुत्तनिपात १२५। हनति-जातक ४,१०२।

ङ—√हण (सक)=वधे, (२) गतौ। हणइ; हणिया-कुमा.; आचा.।

ङ—√हम्म (सक)=वधे। कुमा.; संक्षि. ३४।

छ—√हनना†*(<हननम्)=वधे, (२) आघाते।

+√हम्म् (हम्म) १/४६१ शा-जै×, (च-√हम्य्) (शा-√हर्म्) — गतौ (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-चो।

√हम् १/२२५ e गतौ (प) काकृ। √हय् १/५१३ गतिकान्त्योः (प)। √हम्ब् १/२०६ ff मर्दने (प) काकृ।

ग—हम्मतिः सुराष्ट्रेषु, गमिमेव त्वार्याः प्रयुञ्जते-महाभाष्ये पस्पशाह्निकम्-५२ पृ.। हम्मीर०-(शाकम्भरीसम्बद्ध०)-राजतर. ७,५३।

+√हय् (हय) १/५१३ श×	गतिकान्त्योः (प) क्षी-शा। गतौ—मै-सा-च-काकृ-कात। भक्तिशब्दयोरपीति केचित्—सा। गतिक्लान्त्योः—जै। गतौ क्लान्तौ च—हे। क्लमे गतौ—वो।	√हि ५/११ गतौ वृद्धौ च (प)। √हर्य् (हर्य) १/ गतिकान्त्योः (प)।

ग—हय०-ऋ. ५,४६,१; ऐब्रा. ८,२२; शब्रा. १०,६,४,१। √हि गतौ (प) इत्यतोऽपि व्युत्पत्तिः।

√हर्य् (हर्य) १/५१५ श×	गतिकान्त्योः (प) क्षी-मै-सा-शा। गतौ—च। गतौ क्लान्तौ च—काकृ-कात-हे। गतिक्लान्त्योः—जै। क्लमे गतौ—वो।	हर्यति-निघ. २/१४= गतिकर्मा। हर्यति-निघ. २/६= कान्तिकर्मा। √हय् (हय) १/५१३ गतिकान्त्योः (प)।
√हर् ४/	ह्वि.।	

क—घेर्=इच्छायाम्-वा. पॉकर्नीः।

ग—अभिहर्यन्ति देवाः-ऋ. १०,११२,६। हर्यतम्-शांब्रा. २५,७; तांब्रा. १५,५,४।

+√हल (हल) १/८२१ श×	विलेखने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। विलेखे—वो।

क—घेल=छेदने, (विलेखने) ?। अर्मे. ज्लेम्=सीता (लाङ्गलपद्धतिः); जलोद्गमस्थलम्; चर्मरेखा, वलीरेखा; प्रणाली (कुल्या)-वा. पॉकर्नीः।

ग—हल-हल-वनदुर्गो. ४३:११। हलम्-मभार. ३,८०९।

ङ—हल=लाङ्गलम्-उवा.; औप.'।

√हस् (हसे) १/७१३ हसने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। हासे—वो।
श
√घस् (घस्लृ) अदने (प)। √जक्ष् (जक्ष) २/ भक्षहसनयोः (प)। √हस्त् १०/४७ आदाने (प) काकृ। हासमाने हासति स्पर्द्धायां हर्षमाणे वा-निरु. ९,३९,१।

ग—हसति-छान्दोग्यो. ३,१७,३; योशि. ६,६७। हसन्ति-पत्रा. ५,१०।

घ—हसति-बुद्धवंस १, २८; महावंस ३५,५९।

ङ—√हस=(१) हासे, (२) सक-उपहासे। हसमाण-औप.; दस. ७,५४।

छ—√हँसना / √हाँसना†* } =हसने।

√हा (ओहाङ्) ३/७ गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
श
√हा (ओहाक्) ३/८ त्यागे (प)। √जह् १/३१६m हिंसागत्योः (प) काकृ।

क—उत्तरधातुवज्ज्ञेयम्।

ग—द्यौर्जिहीत-ऋ. ८,२०,६; अनु···जिहते-६,१८,१५। अतीव जिहीते-पञ्च. ब्रा. १७,४,३।

ङ—द्रष्ट.-उत्तरधातोः प्रथमो ङः।

√हा (ओहाक्) ३/८ त्यागे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
श
√हा (ओहाङ्) ३/७ गतौ (आ)।

क—घा (इ)=स्खलतौ, (२) पार्थक्ये, दूरगमने।

ग—यथा न पूर्वमपरो जहाति-ऋ. १०,१८,५। जहाति-ऐब्रा. ८,२५; छान्दोग्यो. ६,११,२।

घ—जहाति-सुत्तनिपात १,५०६।

ङ—√हा (सक)=त्यागे, (२) गतौ, नैयून्ये । कर्म. हायइ, हायंति–भग.; उव. ।

ङ—√जह (सक)=त्यागे । जहइ–पि. ६७ ।

√हि ५/११ गतौ वृद्धौ च (प)
श क्षी-मै-सा,-काकृ (उ),-कात ।
गतौ—च ।
गतिवृद्ध्योः—जै-शा-हे ।
वर्धने गतौ—वो ।

क—घ्राइ=प्रेरणे, उत्तेजने, कम्पने ।

ख—अवे. जएनि=शीघ्रगामी, इच्छुकः–वा. पॉकर्नीः ।

ग—वृजिनं हिनोति–ऋ. ७,१०४,१३; हिनुहि–१,१४३,४ । हिनोति–ऐआ. ५,२,२ ।

घ—पहिणति–विनय. ३,१४० ।

√हिंस् (हिसि) ७/१९ हिंसायाम् (प)
श क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे ।
हिंसने—जै ।
हिंसे—वो ।

√हन् (हन) २/ हिंसागत्योः (प) ।
√सिंह् १/३१६ h हिंसायाम् ; गतौ (प) काकृ ।

क—घ्राइस्=(हिंसायाम्) पीडायाम् , आघाते–वा. पॉकर्नीः ।

ग—हिंसन्ति धीतयः–ऋ. ६,३४,३ । हिनस्ति–ऐब्रा. १,१३; ऐआ. २,५,१ ।

घ—हिंसति–दीघ. २,२४३; सुत्तनिपात ५१५ ।

ङ—√हिंस (सक)=(१) वधे, (२) पीडायाम् । हिंसइ–आचा.; पव. १२१ ।

(छ—√हूंसना=शपने ।)

√हिक्क् (हिक्क) १/८४६ अव्यक्ते शब्दे (उ)
श-जै × (काकृ-√हिष्क्) क्षी-मै-सा-कात-शा-हे ।
स्याल्लैपिकी त्रुटिः । शब्दे—च ।
गतौ—काकृ ।
कूजे—वो ।

ग—हिक्कते-चरक. ८,१५। हिक्कन्त्०-सुश्रु. २,४९५,११। हिक्केत्—बृहत्सं.-५१,३२। हिक्किका प्रोच्यते ज्वरः-मभार. १२,१२०६३।

ङ—हिक्का=रोगविशेषः-सुपा. ४८६।

छ—√हीचना*† =हिक्कने, अनिच्छया सङ्कोचेन वा क्वापि कार्यप्रवृत्तौ।

छ—√हिचकना
छ—√हिलकना† } =हिक्कने, अनिच्छया सङ्कोचेन वा क्वापि कार्यप्रवृत्तौ।

+√हिठ् (हिठ) १।३१४ आक्रोशे (प) केचित् पठन्ति—सा।

<√विट् (विट) आक्रोशे (प)।

√हिण्ट् १/१०१ शोषणे (प) काकृ।

√हिट्ट् १/१२३ बन्धने (प) काकृ।

√हिण्ड् (हिडि) १/२६५ श

गत्यनादरयोः (आ) क्षी-मै-सा-जै-शा।

अनादरे गतौ च—काकृ-कात।

गतौ—च।

गतौ अनादरे च—हे-चो।

रिक्तीभावे—ह्वि.।

√हण्ड् (१/१८३ a हिंसागत्योः (प) काकृ।

√हेड् (हेडृ) १/ अनादरे (आ)।

ग—पर्यहिण्डन्त शुष्काः काकमण्डल्यः-दशकु. १५१,६। हिण्डसे-यशस्ति. च., २ आ., ३५० पृ. =पर्यटसि।

घ—आहिण्डते-दिव्यावदान १६५। आहिण्डति-विनय. १,२०३।

ङ—√हिंड (सक)=(१) भ्रमणे, (२) गतौ, चलने। हिंडइ-सुपा. २८४; महा.।

छ—[√हँडना (<अभ्यटनम् ?)=भ्रमणे, (२) वृथा भ्रमणे, (३) अन्वेषणे।

√हिन्व् (हिवि) १/५८९ श× | प्रीणनार्थः (प) इति च चान्द्राः-क्षी। क्षी-मै-सा-च-कात। प्रीणने—जै-काक्ट-शा-हे। प्रीतौ—वो। हि १/ प्रवृत्तौ, प्रोत्साहने—ह्वि.। | √धिन्व् (धिवि) प्रीणनार्थः (प)।

ग—हिन्वति-शब्रा. ३,५,१,३५, हिन्वन्ति-१२,८,१,१।

+√हिल् (हिल) ६/८२ श× | हावकरणे (प) क्षी-मै-काक्ट-कात-शा-हे। भावकरणे—सा-जै। हावे—च। हावकृतौ—वो। | >√मिल् (मिल) श्लेषणे (प)इति दुर्गः—क्षी। √हिल्लोल १०/ दोलने (प) वो।

ग—कथं हिलसि भोः! छात्र!

छ—√हिलना }
छ—√हीलना } =दोलने, हावे।

छ—√हेलना *=(१) क्रीडायाम्, केलौ, (२) विनोदे।

(छ—√हीला (आरण्य.-हीलः)=व्याजः, मिषः।)

√हु ३/१ श (काक्ट-√हू) | दानादनयोः (प) क्षी-सा-जै-शा-हे। दाने। आदानेऽप्येके—मै। 'दानादानयोः' इत्यन्ये—सा-काक्ट। होमेऽदने—वो। हवने—च। दाने—कात। | √हुन्—हुनेत्-बृजा.३,१६; रार. २,३४; वपू. २५। सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत्-दे. भा. ११,१७,३४। ङ-√हुण (सक)=होमे। हुणइ-भग. ११,९-पत्र. ५१६; कुमा.। छ-√हुनना=हवने।

दानम्=हविःप्रयोगः। अदनम्=भक्षणम्।

ग—अव पथिषु जुह्वति-ऋ. ५,७,५। जुहोति—ऐब्रा. १,२; तैब्रा. १,१,६,९।

ङ—√जुहु (सक) = (१) दाने, (२) हवने। जुहुणामि–ठा. ७–पत्र. ३८१; पि. ५०१।

+√हुड् (हुड़्) १/३४९ मै-श-च-काकृ× — गतौ (प) क्षी-सा-जै-कात-शा-हे-वो। — √हुल् (हुल) १/ गतौ (प) √हुण् १/२१० a गतौ (प) काकृ। √हुण्ड् १/१८३ b हिंसा-गत्योः (प) काकृ। √हूड् (हूड़्) १/ गतौ (प)।

ग—जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना–पञ्चत. मित्र., १७३ श्लो. [खेमराजश्रीकृष्ण. १९२३ खीस्ताब्दे]।

ङ—हुड = मेषः–दे. ८,७०; कुक्कुरः–मृच्छ. २५३।

ङ—हुडुअ = प्रवाहः–दे. ८,७०।

ङ—हुडुम = पताका–दे. ८,७०।

+√हुड् (हुड) ६/१०२ क्षी-सा-श-च-जै-काकृ-कात-शा-हे-वो× — सहने (प) मै। — पूर्ववत्।

ग—पूर्ववत्।

ङ—हुडुक्क = वाद्यविशेषः–औप.; कप्पू.; सण.; विक्र. ८७।

छ—√हुड़कना = येनातिसक्तो बालकस्तदर्थं रोदित्वा व्याकुलताप्रकाशने।

+√हुड् (हुड) ६/१०८ श ? सा× (जै√हुड्) — निमज्जने (प)। क्षी-शा-हे। संघाते–मै-च-जै-काकृ-कात-हे। मग्ने संघे च—वो। — √दुड् (दुड) ६/ निमज्जने (प)।

क—इँग्लि. हुड = रथच्छदिः; शिरश्छादनम्

ग—सहुडोपला योधाः–मभार. ३,१६३२६।

पुरी समन्ताद् विहिता सपताका सतोरणा।
सचक्रा सहुडा चैव सयन्त्रखनका तथा॥

मभार. वनपर्वणि सौभवधे १५ अध्यायः–हुडः=सैन्याश्रयस्थानम्। अन्ये तु विण्मूत्रोत्सर्जनशृङ्गाणि हुडा इत्याहुः, उदाहरन्ति च—

कल्पान्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः।
विण्मूत्रस्पर्शशुद्ध्यर्थं करादिस्पर्श उच्यते ॥ श. क. द्रु.।

+√हुण्ड् (हुडि) १/२६६ सङ्घाते (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। मग्ने संघे च—वो। श

√हुञ् १/३१३ h हिंसा-गत्योः (प) काकृ।

ग—हुण्ड० (=राक्षस०)–मभार. ६,२०८१। हुण्डन०–चरक. ८,२६।

ङ—हुंड=शरीरस्य विलक्षणः (विस्थितिकः) अवयवः–ठा. ६–पत्र. ३५७; सम. ४४,१४९; विलक्षणावयवको मनुष्यः—विपा. १,१–पत्र. ५।

छ—हुंडार=वृकः।

छ—√हुदना †* (<हुण्डनम्)=स्तब्धीभावे, रोधने।

+√हुण्ड् (हुडि) १/२७४ वरणे (आ) क्षी-सा। हरणे—मै-सा। श-च-जै-काकृ-कात-शा-हे-वो×

><√भुण्ड् (भुडि) १/३८३a भरणे (आ) च।
√भुण्ड् (भुडि) १/११८ भृतौ (आ) जै।
√भुण्ड् (भुडि) १/४४६ भरणे (आ) काकृ।
√भुण्ड् (भुडि) १/३६८ भरणे (आ) कात।

वरणम्=स्वीकारः-क्षी।

ग—हुण्डिका=मुद्रा—क्षीरस्वामी।

छ—हुंडी=धनार्पणादेशपत्रम्।

√हुर्च्छ् (हुर्छा) १/२०८ कौटिल्ये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। श×(काकृ-√हूर्छ्)

√ह्वृ १/९१५ कौटिल्ये (प)।

क—घुएल्=नमने, कौटिल्ये-वा. पॉकर्नीः।

ग—यज्ञो हूर्च्छति–काठ. ३२,६; विहूर्च्छति य एवं वेद–२७,१। अनुहूर्च्छन्ति–मै. १,१०,७; काठ. ३६,१।

√हुल् (हुल) १/८२८ गतौ (प) √हुड् (हुड़्) १/ गतौ (प)।
श
क्षी-मै-सा-च-काकृ-कात-शा-हे.
हिंसावरणयोः, च= गतौ—क्षी,-मै-सा-काकृ-कात-शा-हे।
गमने हिंसावरणयोश्च—जै।
हतौ छदि—वो।
√हूड् (हूड़्) १/ गतौ(प)।

ग—चक्रयुक्ता हुला गुडाः–मभार. ३,१७१८।
ङ—√हुल (सक)=प्रक्षेपणे। हुलण–कुमा.=क्षेपणम्।
छ—√हुलना=प्रेरणे।

+√हूड् (हूड़्) १/३४८ गतौ (प) द्रष्ट. √हुड् १/३४९।
श-जै कात×
क्षी-मै-सा-च-काकृ-कात-शा-हे,-वो (आ)।

छ—√हूलना=प्रेरणे।
छ—√हूटना *† (<हूडनम्)=अपसृतौ, स्थगने, (२) परिवृत्य गतौ।

√हृ (हृञ्) १/८८३ हरणे (उ). √भृ (भृञ्)१/ भरणे (उ)।
श
क्षी-मै-सा-च,-जै (प),-काकृ-कात-शा-हे।
हृत्याम्—वो।

क—घेर्=ग्रहणे, हरणे।
ख—अवे. जर् =हरः; आजर्=आहरः, निर्दयता, उत्पीडनम्–वा. पॉकर्नीः।
ग—तमाहरामि–ऋ. १०,१६१,२। हरति–ऐब्रा. ५,३४; शांब्रा. १७,१।
घ—हरति–जातक २,१७६।
ङ—√हर (सक)=हरणे, (२) प्रसारे। हरइ–उव.; महा.।
छ—√हरना (<हरणम्)।

√हृ ३/१५ प्रसह्यकरणे (प) √हृ (हृञ्) १/ हरणे (उ)।
श-च-जै-शा×
क्षी-मै-सा-काकृ-कात-हे।
प्रसह्यहृत्याम्—वो

ग—जिहर्ति–ह्वि.। मया नावाप्तम्।

√हृषु (हृषु) १/७०२ शX	अलीके (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	

क—घेर्स्=निर्निमेषं दर्शने।

ख—अवे. जर्सयम्न-वा. पॉकर्नीः।

ग—सोमपीथाय हृर्षते-ऋ. १,५१,७। हृर्षते अस्य सेना-ऋ. ९,६१,१।

घ—घंसति-जातक ४,५६। हंसति-विनय ३,८; मज्झिम. १,७९।

ङ—√हरसना, √हरसाना, √हरखना, √हरखाना, √हरषना, √हरषाना, √हर्षना, √हर्षाना (<हर्षणम्)=मोदे।

√हृष् (हृष) ४/११६ श	तुष्टौ (प) क्षी-मै-सा-च-जै-कात-शा-हे-वो। पुष्टौ—काकृ।	

क—पूर्ववत्।

ग—हृष्यति-नारदपरिव्राजको. ३,३८; महो. २,४,३; गी. १२,१७। हृष्यसे-मार्क. पु. ११०,११। जहृषिरे मुदा-वा. रा. ५,१,८।

घ—हस्सति-सुत्तनिपात ८२३; ८२९।

+√हेठ् (हेठ) १/२६३ शX	विबाधायाम् (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। बाधे—वो।	√एठ् (एठ) १/ विबाधायाम् (आ)।
		√हेट् १/५८६ विश्वधायाम् (प) जै।
हेठ् (हेठ) १/३१४ मै-सा-श-जै-काकृ-कात-हेX (क्षी. यु. मी. सं √हेड्)	विबाधायाम्—क्षी-च। बाधे—वो।	√हेट् १/३९१ विबाधायाम् (प) शा।
		√हेट् १/३९२ विबाधायाम् (प) हे; बाधे—वो
		√हेड् १/१९२ विबाधायाम् (प) हे।

ग—हेठस्य-यशस्ति. च., ३ आश्वा., ५५६ पृ.।

घ—हेठक-जातक ४,४४६; पेतवत्थु ३,५।

छ—हेठी=मानहानिः, अपमानः।

+√हेठ् (हेठ) ९/६० च=भूतप्रादुर्भावे (प)
मै-श-च-जै-काकृ-कात- क्षी-सा-हे ·
शा× खचे (=भूतिपूत्यो-
रुत्पत्तौ)—वो।

√हेड् (हेडृ) १/२८३ अनादरे (आ)
श-च× क्षी-मै-सा-जै-काकृ-
कात-शा-हे-वो।

हेळते—निघ. २/१२=
क्रुध्यतिकर्मा।
√हिण्ड् (हिडि) १/ गत्य-
नादरयोः (आ)।
√हेड् १/२१५ d गतौ (प)
काकृ।
जिहीडिरे-शब्रा. १,२,५,
५; काब्रा. २,२,३,५।

क—घाइ-: घी=जृम्भायां गात्रविनामे वा। गाइल्—,घाइस्-तथा-घाइज्-
द्=क्रोधे, उद्वेगे-वा. पॉकर्नीः।

ग—मा हेळे भूम वरुणाय-ऋ. ७,६२,४। अहेडमानाः-वा. रा. २,६८,२२=
उपेक्षारहिताः (तिल.)। हेलनम्—भा. पु. ६,२,१४। (लडयोरेकत्वस्मरणात्)

घ—(हीळेति-संयुत्त. १,३०८)।

ङ—√हील (सक)=न्यक्कृतौ, (२) निन्दायाम्, (३) पीडने। हीलइ-
उव.; सुख. २,१९।

छ—√हेलना*=तिरस्कारे, (२) अनवधाने।

+√हेड् (हेड) १/७७१ वेष्टने (प)
श× क्षी-मै-सा-च-जै-काकृ-
कात-शा-हे।
वेष्टे—वो।

ग—(अहेडत् -गोब्रा. १,२,२१;) कुनद्यामिव हेलमानाः-मभार. १०,५६५।
ङ—हेडा=घटा, समूहः-सुपा. ३८६; ५३०; अक्षवाटः-धम्म. १२ टी.।
छ—√हेलना†=(१) प्रवेशे (विशेषतो जले), (२) जलसंतरणे।
छ—√हेलान=क्षेपण्या नौस्थापने (वेष्टने)-लश्क.।

+√हेप् (हेपृ) १/३७०	गतौ (आ) क्वचित् पठ्यते—सा।	<√रेप् (रेपृ) गतौ (आ)। √धेप् (धेपृ) १/गतौ(आ) क्वचित् पठ्यते—सा।
√हेष् (हेषृ) १/६१५ श-जै×	अव्यक्ते शब्दे (आ) क्षी-मै-सा-काकृ-कात-शा-हे। शब्दे—च। स्वनेऽश्वानाम्—वो।	√हेष् (हेषृ) १/ अव्यक्ते शब्दे (आ) सा। √रेष् (रेषृ) १/ अव्यक्ते शब्दे (आ) इत्यपि चन्द्रः-क्षी।

ग—न हेषन्तं पेरुमस्यसि–ऋ. ५,८४,२। तद्यथाभिहेषते पिपासते–ऐब्रा. ६,८। हयानां हेषताम्–मभार. १५,१००९। जिहेषिरे–शिशु. १७,३१।

घ—हेसति–जातक १,५१,६२।

ङ—हिंसा (<हेषा)=अश्वशब्दः। हयहिंसं च–सुपा. १९४।

ङ—हेसा (<हेषा)=अश्वशब्दः—सुपा. २८८; श्रा. २७।

छ—√हींसना (<हेषणम्)=अश्वशब्दे।

+√होड् (होडृ) १/२८२ क्षी-श-जै×	अनादरे (आ) मै-सा-च-काकृ-कात-शा-हे-वो। गतौ अनादरे च—वो।	द्रष्ट. √हुड् १/३४९।

छ—होड़=प्रतिस्पर्द्धा।

+√होड् (होडृ) १/३५५ क्षी-श-च-जै-शा-हे×	गतौ (प)। मै-सा-काकृ-कात। गतौ अनादरे च —वो (आ)।	द्रष्ट.√हुड् १/३४९।
+√हौड् (हौडृ) १/३५० मै-सा-श-जै-कात-शा×	गतौ (प) क्षी-च-काकृ-हे,-वो (आ)।	हौड् (हौडृ) गतौ (आ) वो।

ग— न होढेन विना चौरं घातयेद् धार्मिको नृपः।
सहोढं सोपकरणं घातयेदविचारयन्॥ मनु. ९,२७०।

इह प्राकृतप्रभावो लक्ष्यते ।
[ङ—होढ=मोषवस्तु-(पा. स. म.)]
छ—पूर्वधातुवत् ।
छ—होढ=मोषितम् ।

√हु (हुङ्) २/७१ अपनयने (आ)
श (काकृ-√हू) क्षी-मै-सा-च-जै-काकृ-
स्याल्लैपिकी त्रुटिः कात-शा-हे ।
चौर्ये—वो ।

ग—न ते सख्यमप ह्नुवे-ऋ. १,१३८,४; देवानामपि ह्नुतः-८,३१,७। ह्नुवते-तैब्रा. ३,९,६,१। निर्दिश्यापह्नुते च यः-मनु. ८,५३=अपनयति (मन्वर्थ.)।

+√ह्मल् (ह्मल) १/७९९ चलने (प) √ह्मल् (ह्मल) १/७९८
श× क्षी-मै-सा-च-जै-काकृ- चलने (प)।
कात-शा-हे ।
चाले—वो ।
√ह्मल् (ह्मल) १/८०३s अनुपसर्गाद्वा मित् ।
श-जै-शा-हे-वो×
√ह्मल् (ह्मल) १/८२९ गतौ (प) सा । <√हुल् (हुल) गतौ (प)।

ग—अप ह्मलयति-अ.वे. प्राति. १,५८ टीकायाम् ।

+√ह्मग् (ह्मगे) १/७८१ संवरणे (प) √ह्मग् (ह्मगे) १/ संवरणे
श× क्षी-मै-सा-च-जै-काकृ- (प)।
कात-शा-हे-वो ।

√ह्रस् (ह्रस) १/७०४ शब्दार्थः (प) क्षी । √ह्रस् (ह्रस) १/ शब्दे
श×(च-√ह्रष्) शब्दे—मै-सा-च-जै- (प)।
काकृ-कात-शा-हे । √रस् (रस) १/ शब्दे (प)।
रवे—वो ।
संक्षेपे—ह्वि. ।

क—घे़र्-(घे़रे-?)= संक्षिप्तम् । धातुविस्तारः-घे़रेस्-, ग्रेस्-, घेर्स्—:
ख—अवे. जरहेहिस्=शैथिल्ये,नैर्बल्ये-वा. पॉकर्नीः ।

ग—आयुर्ह्रसति पादशः-मनु. १,८३ । दैर्घ्य एव ह्रसन्तीमे-दे. भा. ८,५,१२ । धर्मो न ह्रसते-मभार. १,२४७८ ।

यथालभ्यं लक्ष्येष्वयं शब्दार्थको न प्राप्यते। स्याद्√रस् धातोर्विकासो हकारप्रसारेण।

ङ—√हस (अक)= (१) न्यूनतायाम्, क्षीणतायाम्। हसइ–पंच. ५,५३।

ङ—√हस्स (अक)=(१) न्यूनतायाम्, क्षीणतायाम्। वक्क–हस्समाण–णंदि. ८२ टी.।

√ह्राद् (ह्राद) १/२५ श×	अव्यक्ते शब्दे (आ) क्षी-मै-सा-काक्ट-कात। शब्दे—च-जै-शा-हे। स्वने—वो।	ह्रदो ह्रादतेः शब्दकर्मणः– निरु. १,९,१

क—ह्लाद्=शब्दे।

ख—अवे. ज्राद=रक्षाकुक्कुरः। न. पर्सि. जिरिह्=तनुत्राणम्, कवचः—वा. पॉकर्नीः।

ग—यदि ग्रावाणः संह्रादेरन्–आश्व. श्रौ. ५,१२,२१। संह्रादमानाभरण०–हरिवंश. २६७८।

ङ—√हर (सक)=शब्दे। ०हरइ–से. ५,१७।

√ह्री ३/३ श	लज्जायाम् (प) क्षी-मै-सा-च-जै-काक्ट- कात-शा-हे। लज्जे—वो।	√ह्रीच्छ् (ह्रीछ) १/ लज्जा- याम् (प)।

ग—जिह्रेति–कथासरि. ४५,२६५। जिह्रीयात्—वाग्भ. १,१२,७४।

घ—हिरियति–पुग्गलपञ्ञत्ति–२०,२४।

ङ—√हिरि (अक)=लज्जायाम्। हिरिआमि–अभि. २५५।

+√ह्रीच्छ् (ह्रीछ) १/२०७ श×	लज्जायाम् (प) क्षी-मै-सा-च-जै- काक्ट-कात-शा-हे। लज्जे—वो।	√ह्री ३/ लज्जायाम् (प)। गच्छ-यच्छवदत्रापि ह्री- धातुतश्छकारो बोधनीयः।

√गम्धातोरिव 'छ' इति जातमत्र ज्ञेयम्।

√ह्रेप् (ह्रेपृ) १/३६९ मै-सा-श-च-जै-काकृ-कात-शा-हे×	गतौ (आ) इति च कौशिकः—क्षी । क्षी । गत्याम्—वो ।	<√रेप् (रेपृ) गतौ (आ) । √लेप् (लेपृ) १/ गतौ (आ) । √हेप् (हेपृ) १/गतौ (प) क्वचित् पठ्यते—सा ।
√ह्रेष् (ह्रेषृ) १/६१३ क्षी-मै-श-च-जै-काकृ-कात-शा-हे×	अव्यक्ते शब्दे (आ) सा । स्वनेऽश्वानाम्—वो ।	√रेष् (रेषृ) १/ अव्यक्ते शब्दे (आ) । √हेष् (हेषृ) १/ अव्यक्ते शब्दे (आ) ।

ग—ह्रेषमाण०—मभार. ४,२०००; ह्रेषन्ति-मभार. ४,१४९७ ।

+√ह्रेष् (हेषृ) १/६१४ सा-श×	गतौ (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । सर्पणे—वो ।	पूर्ववत् ।

ङ—हरेस (अक)=गतौ—नाट—वेणी. ६७ ।

+√ह्लग् (ह्लगे) १/७८२ श×	संवरणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो ।	√ह्लग् (ह्लगे) १/ संवरणे (प) । √लग् (लगे) १/ सङ्गे (प) ।
+√ह्लस् (ह्लस) १/७०५ श×(च-√ह्लष्)	शब्दार्थः (प) क्षी । शब्दे—मै-सा-च-जै-काकृ-कात-शा-हे । रवे—वो ।	√ह्लस् (ह्लसे) १/ शब्दे (प) । √रस् (रस) १/ शब्दे (प) ।
√ह्लाद् (ह्लादी) १/२६	सुखे, च=अव्यक्ते शब्दे (आ) क्षी-मै-सा शब्दे सुखे च—च-जै-शा-हे ।	ह्लादतेर्वा स्याच्छीतीभावकर्मणः–निरु. १,९,१ । √ह्लाद् (ह्लाद) १/२५ अव्यक्ते शब्दे (आ) ।

सौख्ये, च=अव्यक्ते
शब्दे—काकृ-कात।
स्वने मोदने च—वो।

क—घेल्ट्=प्रालेयम्—वा. पॉकर्नी। तुल. निरु. १,९,१।
ग—प्रह्लादते मनः–किराता. ११,८। ह्लादयते–तैआ. १,३,४।

√ह्वल (ह्वल) १/७९८ शX
चलने (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
चाले—वो।
गतौ—सा-शा।
√ह्याल (ह्याल) १/ चलने (प)।
√ह्वेल १/२४७ m गतौ (प) काकृ।
<√हुल (हुल) १/ गतौ (प)।

ज्वलह्वलह्मल··· १/८०३ मित्।
श-जै-शा-हे-वोX

क—घु्उ्एल्=नमने, कौटिल्ये–वा. पॉकर्नी।
ग—ह्वलति–शब्रा. ५,१,३,६; ११,५,३,६। विह्वलतीव मे मनः–मभार. १,२१६
ङ—√हल्ल (अक)=चलने, दोलने। हल्लंति–सप्ति. ६८।

√ह्वृ १/९१५ शX
कौटिल्ये (प)
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
ह्वरति–निघ. २/८=अत्तिकर्मा।
ह्वृणाति तत्–ऋ. १,१६६,१२।
√ह्वॄ १/३४८ वरणे (प) काकृ,-कात।

क—घु्उ्एल्=नमने, कौटिल्ये–वा. पॉकर्नी।
ग—उप ह्वरते–ऋ. १,१४१,१। ह्वार्षीत्–शब्रा. १,१,२,१२; तैब्रा. ३,२,३,२।

√ह्वे (ह्वेञ्) १/९९२ जैX,श
स्पर्द्धायां शब्दे च (उ)
क्षी-मै-सा।
स्पर्धायाम्—च।
स्पर्धायां वाचि—काकृ-कात।
स्पर्धाशब्दयोः—शा-हे।
स्पर्धे शब्दे—वो।
ह्वयते–निघ. ३/१४=अर्चतिकर्मा।

क—घुङआ-, घुङ = शब्दे ।
ख—अवे. जवैति = ह्वयति, शब्दे, विलापे, शोके-वा. पॉकर्नीः ।

ग—अव ह्वये-ऋ. ५,५६,१ ; ह्वयते-शब्रा. ३,२,१,२१ । ह्वयति-तैब्रा. ३,२,५,८। हवामहे-बृहदारण्यको. ६,४,२२ [ऋ. १०,१८४,३] । हूमहे-वनदुर्गो. ४४२:८ [ऋ. १,८९,५]

धातुपाठसमीक्षेयं भ्वादेः क्र्यादिगणान्तगा ।
भागीरथप्रसादेन श्रीक्षेत्रेशप्रसादतः ॥
विहिता मानसी पूर्वं वृन्दारण्यनिवासिना ।
विद्यामभ्यस्यता सीतारामशर्मसकाशतः ॥
काश्यां पुष्टिमिता सा श्रीरघुनाथस्य शर्म्मणः ।
शब्दशास्त्रप्रकाण्डस्य कृपालोरनुकम्पया ॥

अथ चुरादिगणधातवः

चुरादिगणपठिता धातवो नवगणपठितधातुभ्यः पृथक्कृत्योपन्यस्यन्ते। अमी प्रायशो नामधातव इति। तद्यथा क्षीरस्वामी—"अन्ये तु प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च" (१०/२९६ यु. मी. सं.) इत्येव सिद्धे सूत्र-छिद्रान्ध-दण्डादय उदाहरणार्थं निदर्शिता इति व्याख्यन्—१०/३२५ (यु. मी. सं.)।

तत्रैव पृष्ठे स्वामी "भूवादिनवगणोक्ताः स्वार्थे णिजन्ता अपि भवन्ति, चुरादिगणस्तु निदर्शनार्थं इत्येके। (तेनापठितेभ्योऽपि क्वचित् स्वार्थे णिच्-सि. कौ. धा. सं. १९४४)-रामो राज्यमकारयत्-वा. रा. ६,१२८,१०५"। "चुरादिणिचौ बहुलं निदर्शनं वेत्यपरे। तेन पक्षे 'चोरति' 'चिन्तति' इत्यादि सिद्धम्।"

विलियम्-ड्वाइट्-हिट्नीमहाशयश्चुरादिगणं नाङ्गीकरोति। स इह नामधातूनां प्रयोजकधातूनां च संक्रान्तिमभिव्यनक्ति "संस्कृत ग्रामर" इत्याख्यस्य स्वपुस्तकस्य ६०७ तमेऽध्याये। तद्यथा—

"हिन्दुवैयाकरणा दशमगणम् उत वा चुरगणम् 'अय'-विकरणान्वितं संख्यान्ति। अन्यादृशधातुभ्य इव तिबादयोऽपि ततः सञ्जायन्ते। इह यौगिकक्रियापदता प्रयोजकता च। सुतमाम् एष पूर्णतो यौगिकक्रियापदत्वेन व्यवहरिष्यते।"

"पूर्वं (६०७ तमेऽध्याये) सूचितमासीद् यद् हिन्दुवैयाकरणा अनुतदुदाहरणं च भूयिष्ठाः पाश्चात्या अपि (नवगणतः) अन्यं यौगिकधातुगणं प्रमाणयन्ति वर्णितपूर्व-(भ्वाद्यादिक्र्याद्यन्त)-तुल्यक्रमम्। यद्यप्येतद्गणधातुरूपाणि सामान्यतो मूलधातुसम्पृक्तम् 'अय'-विकरणं दर्शयन्ति तथाप्ययं शुद्धो गणो नास्ति प्रत्युत सहकारी यौगिकक्रियापदात्मको वा। (अस्य क्रियापदानि सन्त्यंशतः प्रयोजकरूपाणि, परिवर्तितयतिना सहांशतो नामधातुरूपाणि च)।

—"संस्कृत ग्रामर" इत्यस्य ७७५ तमेऽध्याये।

वयं तु ब्रूमः—सर्वे धातवः पूर्वं नामान्येवासन्, व्यापाराणां नामस्वेव सत्त्वेन तेषां स्वातन्त्र्येणोपस्थानासम्भवात्। कस्यापि नाम्नो बहवो व्यापारा भवन्ति। अत एव कारणाद् धातूनां बहवोऽर्था लभ्यन्ते, क्वचन मिथो विरुद्धा अपि। तद्यथा—√चक् (चक) तृप्तौ प्रतिघाते च; √पुस्त् √बुस्त् आदरानादरयोः। भूशब्दः पृथिवीवाचको नाम। तस्मिन् स्थिति-वृद्धि-संक्रान्ति-द्रव-जय-पूज्यता-पालन-शोधन-जीवनावर्तन-क्षरणोत्पत्तिप्रभृतयो व्यापारा विद्यन्ते, इति हेतोः क्रियारूपतां गतेऽपि तस्मिंस्तथात्वं साम्प्रतम्। स्थितिद्रवादिविरुद्धार्थोदाहरणानि—भूत्यै–मनु.

५,३९=विवृद्ध्यर्थः (मन्वर्थ.); भूत्यर्थम्-रघु. १,१८=वृद्ध्यर्थम् (संजी.); अभवत्-रघु. ४,१०=संक्रान्तः (संजी.); देवान् भावयतानेन-गी. ३,११=तर्पयत(नी. व्या.); भावेषु-रघु. ३,४१=वस्तुषु (संजी.); भवन्-नैष. २,३२=प्रपद्यमानः (प्रकाश.); भवन्ति-नैष. २,३२ (प्रकाशटीकायामेव)=भ्रमन्ति; भाविता=तर्किता, द्राविता (प्रकाश.); भविष्यन्ति-मभार. ५,१२८,४३=जेष्यन्ति (नील.); (प्रणयं) भावयन्ती-मभार. ४,३७,७=दर्शयन्ती (नील.); भावितस्य-मभार. ५,२६,१४=पूजितस्य (नील.); भावितः-मभार. ५,८७,१=हृष्टः (नील.); बुभूषति-मभार. १२,१३९,९७=पालयितुमिच्छति (नील.); भवन्ति-मभार. १२,२९५,३४=उत्पद्यन्ते (नील.); भावितैः-मभार. १२,३२६,२६=शोधितैः; भविष्यामि-मभार. २,११३,२४=जीविष्यामि (नील.); भवन्ति-हरिवंशे १,८,४०=आवर्तन्ते (नील.); भावयेत्-हरिवंशे १,६,१०=क्षरेत् (नील.)।

भूवादयो धातवः १/३/१ इति सूत्रं नाम्नामेव क्रियावाचकानां धातुसंज्ञां विदधाति न तु धातूनाम् इति ह्विट्नीमहाशयेन चुरादिमेव नामधातुं वदता नाचिन्ति। अपरम्, चौरादिकानां धातूनां प्रयोजकता नास्ति, स्वार्थे णिच्त्वात्। यथा-चोरयति,-चिन्तयति,-कथयति,-गणयति-प्रभृतीनि शुद्धधातुरूपवदेव प्रयुज्यन्ते। गणयति=गणनां करोति, न तु कारयति—"गणयति न दुःखं न च सुखम्"। आम्, केचन धातवः सन्ति ये प्रयोजकसारतामप्यादधते।

यदीयः प्रथमः क्रमः क्वापि नास्ति तादृशाः केचन धातवः—√अंश १०/३६२; √कथ (कथ) १०/२९७; √क्षम्प् (क्षपि) १०/८३; √गण १०/२९९; √चम्प् (चपि) १०/८२; √चिक्क् (चिक्क) १०/६०; चिन्त् (चिति) १०/२; √चुण्ट् (चुटि) १०/१९९; √चुम्भ् (चुभि) १०/९४; √चुर् (चुर) १०/१; √पल्यूल १०/३२८; √बुल् (बुल) १०/६६ प्रभृतयः सन्ति। मन्ये नवगणप्रयुक्ता बहवोऽत्र धातवः संक्रान्ताः। अत एव हेतोर्न ते प्रयोजकत्वेन निर्धारणीयाः, स्वार्थणिजन्तत्वेन भ्वाद्यादिवत् तदर्थकत्वात्।

+√अंश (अंश) १०/३६२ मै-सा-श-च-जै-शा×	समाघाते (प) क्षी-क्रात-हे संघाते—काक्ष। विभाजने—वो।	<√अंस (अंस) समाघाते (प) इति चन्द्रः-क्षी। √अक्ष् (अक्षू) १/ व्याप्तौ संघाते च (प)। अंशुः शमष्टमात्रो भवति। अननाय शम्भवतीति वा —निरु. २,५,५। √अश् (अशू) ५/ व्याप्तौ (आ)

समाघातः=विभाजनम्—क्षी।

क—ऐनेक्-, नेक्-, एँक्-, अंक्=प्रापणे, दाने, उपस्थितौ (उपहारे), कर्षणे।

ख—अवे. अस=अंशः-वा. पॉकर्नीः।

क—लैति. उमेरुस्; गॉथि. अम्स; अर्मे. उस्-पी. टी. ऐस. पालि-इँग्लिश्-कोशात्।

ग—अंशु०-ऋ. १,४६,१०; अंशुक० (ऋषि०)-ऋ.८,५,२६; त्वमंशो विदथे देव भाजयुः (अग्नि०)-ऋ. २,१,४; वा. सं. १०, ५; अ. वे. ६,२,५।

+√अंस (अंस) १०/३६२ श-च-काकृ-कात×	समाघाते (प) इति चन्द्रः-क्षी। क्षी-मै-सा-जै-शा-हे। विभाजने—वो।	<√अंश (अंश) समाघाते (प)। √अंहृ (अहि) १०/भासार्थः (प)।

क—ऑम् (ए) सॉ-स्=स्कन्धः-वा. पॉकर्नीः।

ग—व्यंसयामास तस्य प्रहारम्-मभार. ३,११७२८; शक्तिं व्यंसितां माधवेन-मभार. १,१९७।

घ—अंस=स्कन्धः-जातक १,९।

+√अंहृ (अहि) १०/२३७ मै-श-च-जै-काकृ-कात-शा×	भासार्थः (प) क्षी-हे। भाषार्थः—सा भासे—वो।	√अंहृ (अहि) १/ गतौ (आ)। √अंहृ १/३१९ कलुषे (प) काकृ। √अम् (अम) १/ गत्यादिषु (प)। अघायति-ऋ. १,१३१;७। अभ्यघायति-शौ.७,७३,३। √अङ्घ् (अघि) १/ गत्याक्षेपे (आ)
+√अघ (अघ) १०/३८५ मै-सा-श-च-जै-शा×	पापे (प) क्षी। पापकरणे— काकृ-कात-हे।	√अघ् १/४१३b गत्याक्षेपे (आ) काकृ। √अंहृ १/३१९ कलुषे (प) काकृ।

	पापकृतौ—वो।	√अंह् (अहि) १०/ भासार्थः (प)।
		√अंह् (अहि) १/ गतौ (आ)

क—अघ् (लॉ)=अननुकूलम्, घृणापूर्णम् (:)।

ख—अवे. अग्र=अघम्-वा. पॉकर्नीः।

ग—अघो वृकः-ऋ. १,४२,२। अघम्-खि. २,११,१,४; मा. ३५,६; शौ. १,२८,३।

अर्वाञ्च एतच्छब्दनिष्पत्त्यर्थं कल्पितम् √अघ् इति धातुं √अंह् इत्यस्यैव रूपान्तरमाहुः। √अङ्घ् इत्यस्य तु भौवादिकस्य गत्याक्षेपे पठितत्वादपार्थ एवायमायासः संभाव्येत। आक्षेपस्य निन्दायां वैयाकरणैर्व्याख्यातचरत्वान्निन्दितकर्मात्मकशब्दार्थसांगत्यस्य √अङ्घ् इत्यनेन सहजप्राप्तत्वादिति भाव इति शास्त्री विश्वबन्धुः (वैदि. प. को. संहि. भा.)

वयं तु ब्रूमः √अघ् १,४१३७bगत्याक्षेपे (आ) काकृ, √अंह् १/३१९ कलुषे (प) काकृ, √अङ्घ् १/१०५ गत्याक्षेपे (आ) इत्येतेष्वस्ति कश्चन विकाससंबन्धः। √अघ्>√अङ्घ्>√अंह् इति। अतः काशकृत्स्नीयस्य √अघ् धातोः सत्त्वादपार्थ एवायमायास इति।

+√अङ्क (अकि) १०/३७२ मै-सा-च-काकृ-कात×, श	लक्षणे (प) क्षी-जै-शा-हे। गतौ—हे। लक्ष्मणि—वो।	√अङ्क् (अकि) १/ लक्षणे (आ)। √अङ्क (अङ्क) १०/ पदे लक्षणे च (प) सा। √अङ्ग (अङ्ग) १०/ च=पदे लक्षणे (प) मै। √अङ्घ (अङ्घ) १०/ पदलक्षणयोः (प) इत्येके—क्षी।

ग—अङ्कयेन्-सुदर्शनो. २९४ : १०।

घ—अंकेति-जातक १, ४५१।

छ—√अँकाना=मूल्यनिर्धारणे, परीक्षणे।

+√अङ्क (अङ्क) १०/३७३ श-च-जै-शा×	पदलक्षणयोः (प) इत्यन्ये-क्षी। पदे लक्षणे च—सा। लक्षणे—मै-काकृ-कात-हे। पदे लक्ष्मणि—वो।	<√अङ्ग पदलक्षणयोः (प)। शेषः पूर्ववत्। पर्यङ्ख्याते—ऋ. १०,१६,७। 'अञ्चतेरङ्कः' इति भाष्याद् √अङ्क पदे लक्षणे चेति धातुरनार्ष इत्यन्ये [नागेशः]—

महाभाष्ये ८,२,४८; गु. प्र. सं. १२३पृ.।

पदम् = संख्यास्थानम्—दुर्गादासः।

ग—विराधाङ्कगतां शुभाम्–वा. रा. ३,२,१६(गी. प्रे. सं.) –अङ्कः = उत्सङ्गः।

+√अङ्ग (अङ्ग) १०/३७३ शा-च-काक्र-कात× (जै-शा—√अङ्ग)	पदलक्षणयोः (प) क्षी। पदे लक्षणे च—मै-सा-जै-शा-हे। पदे लक्ष्मणि—वो।	>√अङ्क (अङ्क)पदलक्षणयोः (प)। पूर्ववत्।

ग—अङ्गं गलितं पलितं मुण्डम्–च. प. स्तो. (शङ्करा०)। अङ्ग! कच्चित् कुशली तातः—कादम्ब. (मुम्बा. संस्क.) २२१।

+√अङ्घ (अङ्घ) १०/३७३ मै-सा-श-च-जै-काक्र-कात-शा-हे-वो×	पदलक्षणयोः (प) इत्येके —क्षी।	<√अङ्ग (अङ्ग)पदलक्षणयोः (प)। पूर्ववच्छेषो ज्ञेयः।

√अङ्क<√अङ्ग>√अङ्घ इति विकासो मननीयः।

+√अञ्च् (अन्चु) १०/२११ श-च×	विशेषणे (प) क्षी-मै-सा-जै-काक्र-कात-शा-हे। व्यक्तौ—वो।	√अञ्च् (अन्चु) १/गतौ याचने च (उ) मै।

विशेषणम् = अतिशयः—क्षी।

ग—मुदमञ्चय–गीतगो. १०,११ = जनय।

+√अञ्ज् (अजि)१०/२२८ मै-श-च-जै-काक्र-कात-शा×	भासार्थः (प) क्षी-हे। भासि—वो। भाषार्थः—स्वामिकाश्य-पानुसारेण लिख्यते—सा।	√अञ्ज् (अन्जू) ७/ व्यक्तिम्रक्षणकान्ति''' (प) मै। √अज् (अज) १/ गतिक्षेपणयोः (प)।

+√अट्ट् (अट्ट) १०/२५ श×	अनादरे (प) इति च दुर्गः—क्षी	√अट्ट् (अट्ट) १/ अतिक्रमण-हिंसनयोः (आ)।

क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो । तौच्छये—वो । √अड्ड् (अद्ड) १/ अभियोगे (प)।

ग—कालाट्टहसित०—राजतर. २,४७।

घ—अट्टियति=व्याकुलतायाम्, चिन्तायाम्-दीघ. १, २१३।

छ—अठाना*†(<अटनम् =अनादरे)=पीडने, क्लेशने।

छ—आटना=दमने, भारेणानमने।

ज—आटा·आटि=कलहे, तर्कणे (तु. सन्थाल-आड्रा, आड्रि इति)।

+√अन्ध (अन्ध) १०/३७० च×,श(जै-शा-√अन्ध्) दृष्ट्युपसंहारे (प) क्षी-सा-जै-काकृ-कात-शा-हे। दृष्ट्युपघाते—मै-सा। दृक्क्षये—वो। √अन्त् (अति) १/ बन्धने (प)। √अन्द् (अदि) १/ बन्धने (प)।

क—अन्धॉ=अन्धः; अन्धकारः। लैति. उम्ब्र=छाया। म. नीदेर्लै. अन्दॉरेन्; पु. उ. ज. अन्दार्न्; म.उ.ज. अन्तार्न्, अन्दार्न्; आंग्लभा. ब्लआइन्द्।

ख—अवे. अन्द=अन्धः (म्), अन्धकारः—वा. पॉकर्नीः।

ग—प्रेमान्धः ख्यन्निःश्रोणो भूत्—ऋ. १,११२,८; ४,४,१३।

ङ—√अंधाव (सक)=अन्धत्वे। अंधावेइ-विक्रान्तकौर. ८४।

+√अम् (अम) १०/१८८ च×, श रोगे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो। √अम् (अम) १/ गत्यादिषु (प)।

प्रयोजकः —ह्वि.।

क—ऑमॉ-ः औमॉ=अपरिपक्वम्, असिद्धम्। लैति. अमारुस् =तीक्ष्णम्। अर्मे. हुम्=अपरिपक्वम्, असिद्धम्। पु. इरि. ऑम्=अपरिपक्वम्, असिद्धम्—वा. पॉकर्नीः।

ग—यस्या उदरमामयत्-ऋ. १०,८६,२३। मूत्रं भवत्वामयत्-अ.वे. ९,८,१०।

+√अर्क् (अर्क) १०/१०३ च×, श स्तवने (प) क्षी-मै-सा-कात-हे। स्तुतौ—जै-काकृ-शा। 'तपने' इत्येके—क्षी-सा। स्तवनपाठो युक्तः—सा। अर्चन्त्यर्कमर्किणः—निरु. ५,४,६ √अर्च् (अर्च) १/ पूजायाम् (प)। √ऋच् (ऋच) ६/

	तापस्तुत्योः—वो ।	स्तुतौ (प) । √अर्क् १/४१० f आदाने (आ) काकृ । √अर्च् (अर्च) १०/ पूजायाम् (प) । अर्कः—निघ. २/७= अन्ननाम ; २/२०= वज्रनाम । अर्को देवो भवति यदेनमर्चति—निरु. ५,४,६ ।

क—ऐर्क्=मयूखः, गभस्तिः; द्युतौ । अर्मे. ऐर्ग्=किरणः; ऐर्किन्=स्वर्गः, आकाशः-वा. पॉकर्नीः ।

+√अर्च् (अर्च) १०/२५९ श	पूजायाम् (प) आधृषाद् वा क्षी,-मै-सा (उ), काकृ,-जै-कात-शा-हे (आ) । पूजे—वो ।	√अर्क् (अर्क) १०/ स्तवने (प) । शेषः पूर्ववत् ।
प्रयोज.	ह्वि. ।	

ग—अर्चयन्ति-अथर्वशिखो. ६,१६; रुद्र. ६; वउ. ६,४५; अर्चय-बि. १७। अर्चयेत्-मुण्डको. ३,१,१०; मैत्र्यु. ४,६; व्रबि. ५५; अर्चयिष्यन्ति-भव. १,५६ ।

+√अर्ज् (अर्ज) १०/१९३ च×,श	प्रतियत्ने (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे । संस्कारे—वो ।	√अर्ज् (अर्ज) १/ अर्जने (प) ।
प्रयो.	ह्वि. ।	
प्रतियत्नः =	संस्कारः—क्षी ।	

ग—यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्-मनु. ११,१९३। धनमर्जयेत्-कथासरि. ६,३६ । इह नास्ति प्रयोजकता, स्वार्थे णिच्त्वात् ।

+√अर्थ (अर्थ) १०/३४९ श (जै-शा—√अर्थ्)	उपयाच्ञायाम् (आ) क्षी-मै-सा-जै-काकृ-कात-शा । याच्ञायाम्—च ।	√ऋ १/ गतिप्रापणयोः (प)-उणा. २/४ स्थन् । √अर्द् (अर्द) १/ गतौ याचने च (प) ।

क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। √अड्ड् (अड्ड) १/ अभियोगे (प)।
तौच्छये—वो।

ग—कालाट्टहसित०—राजतर. २,४७।
घ—अट्टियति=व्याकुलतायाम्, चिन्तायाम्—दीघ. १, २१३।
छ—अठाना*†(<अटनम् =अनादरे)=पीडने, क्लेशने।
छ—आटना=दमने, भारेणानमने।
ज—आटा·आटि=कलहे, तर्कणे (तु. सन्थाल–आड्डा, आड्डि इति)।

+√अन्ध (अन्ध) १०/३७० दृष्ट्युपसंहारे (प)
चX, श(जै-शा-√अन्ध्)
क्षी-सा-जै-काकृ-कात-शा-हे।
दृष्ट्युपघाते—मै-सा।
दृक्क्षये—वो।
√अन्त् (अति) १/ बन्धने (प)।
√अन्द् (अदि) १/ बन्धने (प)।

क—अन्धाँ=अन्धः; अन्धकारः। लैति. उम्ब्र=छाया। म. नीदेर्लें. अन्दॉरेन्; पु. उ. ज. अन्दान्; म.उ.ज. अन्तार्न्, अन्दार्न्; आंग्लभा. ब्ल्आइन्द्।
ख—अवे. अन्द=अन्धः (म्), अन्धकारः—वा. पॉकर्नीः।
ग—प्रेमान्धः ख्यन्निःश्रोणो भूत्—ऋ. १,११२,८; ४,४,१३।
ङ—√अंधाव (सक)=अन्धत्वे। अंधावेइ–विक्रान्तकौर. ८४।

+√अम् (अम) १०/१८८ रोगे (प)
चX, श
क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो।
प्रयोजकः —ह्वि.।
√अम् (अम) १/ गत्यादिषु (प)।

क—ऑमॉ-ः औमॉ=अपरिपक्वम्, असिद्धम्। लैति. अमारुस्=तीक्ष्णम्। अर्मे. हुम्=अपरिपक्वम्, असिद्धम्। पु. इरि. ऑम्=अपरिपक्वम्, असिद्धम्—वा. पॉकर्नीः।
ग—यस्या उदरमामयत्—ऋ. १०,८६,२३। मूत्रं भवत्वामयत्—अ.वे. ९,८,१०।

+√अर्क् (अर्क) १०/१०२ स्तवने (प)
चX, श
क्षी-मै-सा-कात-हे।
स्तुतौ—जै-काकृ-शा।
'तपने' इत्येके—क्षी-सा।
स्तवनपाठो युक्तः—सा।
अर्चन्त्यर्कमर्किणः—निरु. ५,४,६
√अर्च् (अर्च) १/ पूजायाम् (प)।
√ऋच् (ऋच) ६/

	तापस्तुत्योः—वो।	स्तुतौ (प)।
		√अर्क् १/४१० f आदाने (आ) काक्र।
		√अर्च् (अर्च) १०/ पूजायाम् (प)। अर्कः—निघ. २/७= अन्ननाम ; २/२०= वज्रनाम। अर्को देवो भवति यदेन-मर्चति—निरु. ५,४,६।

क—ऐर्क् = मयूखः, गभस्तिः; द्युतौ। अर्मे. ऐर्ग् = किरणः; ऐर्किन् = स्वर्गः, आकाशः-वा. पॉकर्नीः।

+√अर्च् (अर्च) १०/२५९ श	पूजायाम् (प) आधृषाद् वा क्षी,-मै-सा (उ), काक्र,- जै-कात-शा-हे (आ)। पूजे—वो।	√अर्क् (अर्क) १०/ स्तवने (प)। शेषः पूर्ववत्।
प्रयोज.	ह्वि.।	

ग—अर्चयन्ति-अथर्वशिखो. ६,१६; रुद्र. ६; वउ. ६,४५; अर्चय-वि. १७। अर्चयेत्-मुण्डको. ३,१,१०; मैत्र्यु. ४,६; व्रबि. ५५; अर्चयिष्यन्ति-भव. १,५६।

+√अर्ज् (अर्ज) १०/१९३ च×,श	प्रतियत्ने (प) क्षी-मै-सा-जै-काक्र-कात-शा-हे। संस्कारे—वो।	√अर्ज् (अर्ज) १/ अर्जने (प)।
प्रयो.	ह्वि.।	
प्रतियत्नः =	संस्कारः—क्षी।	

ग—यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्-मनु. ११,१९३। धनमर्जयेत्-कथासरि. ६,३६। इह नास्ति प्रयोजकता, स्वार्थे णिच्त्वात्।

+√अर्थ (अर्थ) १०/३४९ श (जै·शा—√अर्थ्)	उपयाच्ञायाम् (आ) क्षी-मै-सा-जै-काक्र-कात-शा। याच्ञायाम्—च।	√ऋ १/ गतिप्रापणयोः (प)-उणा. २/४ स्थन्। √अर्द् (अर्द) १/ गतौ याचने च (प)।

	उपयाचने—हे ।	अर्थोऽर्तेररणस्थो वा—
	याचने—वो ।	निरु. १,१८,१ ।

क—ऐर्र्—:

ख—अर्त=कर्तव्यम्, अनुग्रह उपकारो वा-वा. पॉर्क्नी: ।

ग—अर्थयेथे-ऋ. १०,१०६,७; अर्थयाथे-१,८२,१; कौ. १,४१६; जै. १,४० । अर्थयस्व धनं बहु-मभार. ३,१२६८१ । स्वर्गतिं प्रार्थयन्ते-गी. ९,२० । समर्थये-रघु. ११,७२=मन्ये (संजी.)

ङ—√अत्थ (सक)=याचने, प्रार्थने, विज्ञप्तौ । अत्थए-निशीथचूर्णि ४ ।

छ—√अत्थाना=बोधने, विवरणे, (२) व्याख्यायाम् ।

+√अर्द् (अर्द) १०/२७७	हिंसायाम् (प)	√अर्द् (अर्द) १/ गतौ
श-च×	आधृषाद् वा	याचने च (प); यातने
	क्षी-,मै-सा-(उ)-,काक्ट-,	च इत्येके—क्षी ।
	जै-कात-शा-हे (आ) ।	अर्दयति—निघ.२/१९=
	वधे—वो ।	वधकर्मा ।
		√ऋ १/ गतिप्रापणयोः (प) ।

ग— अर्दयोदधिम्-अ.वे. ४,१५,६; अर्दयन्-६,४९,२ । अर्दयति-मै. ४,५,६ । अर्दयामास तौमरै:-मभार. ३,१६४५० ।

ङ— √अद्द (सक)=वधे, ताडने-व्यवहारसूत्रभा. १० ।

छ—√अर्दना*=पीडने ।

छ—√अरदना*†=मर्दने, पेषणे, (२) वधे ।

+√अर्ह् (अर्ह) १०/१९९	पूजायाम् (प)	√अर्ह् (अर्ह) १/ पूजायाम्
च×,श	क्षी-मै-सा-जै-काक्ट-	(प) ।
	कात-शा-हे	√अर्घ् (अर्घ) १/ मूल्ये
	पूजने—वो ।	(प) वो ।
प्रयो.	ह्वि. ।	

ग—स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा-मनु. ३,३; अर्हयेन्मधुपर्केण-३,११९ ।

+√अवधीर (अवधीर) १०/३८६	·····मै
क्षी-श-च-जै-काक्ट-कात-	मै-सा×
शा-हे×	अवज्ञायाम्—वो ।

अवधीरितसुहृद्वचनस्य-हितो. १। अवधीर्य-शिशु. ९,५९=तिरस्कृत्य सर्वङ्कषां अवधीरणाम्-रघु. ८,४८; शाकु. ३,१४। अवधीरिता प्रिया-शाकु. ६,१२।

+√अश्व (अश्वतर) १०/३८८ ......(आ)
श-जै-शा-हे-वो×

तेनातिक्रामति।

यः कश्चाध्वानमश्नुवीता-श्वः स वचनीयः—निरु. १,१२,५।
आचक्षीरन्नष्टेत्यश्वम्—निरु. १,१३,१।
अश्वः कस्मादश्नुतेऽध्वानम्। महाशनो भवतीति वा—निरु. २,२७,४।

अश्वतरः (=तनुरश्वः)--वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे-पा. अ. ५/३/९१। अश्वतरी- पञ्चत. २३२।

+√आन्दोल(आन्दोल) १०/६४; ३८४ ....(प)
श-च-जै-काक्र-कात-शा×
(हे-√अन्दोल)।

क्षी-मै-सा×(हे)।
दोलने—वो।

√दुल (दुल) १०/ उत्क्षेपे (प)।

ग—आन्दोलयति-महो. ४,११३।
ङ—√अंदोल (अक)=दोलने, (२) कम्पने, (३) संदेहे-स. ५२१।
ङ—√अंदोल (सक)=कम्पने-सुरसुन्दरीचरि. ३,६७।

+√आप (आप्ल) १०/२८६ लम्भने (प)
श-च×

क्षी-मै-सा-, (उ),-जै-काक्र-कात-शा-हे।
व्यापने—वो।

√आप (आप्ल) ५/ व्याप्तौ (प)।

प्रयो. ह्वि.।
लम्भनम्=प्राप्तिः—क्षी।

ग—आपयतो वै तावन्योन्यस्य कामम्-छान्दोग्यो. १,१,६। आपयितुं भूपमाह यौगन्धरायणः—कथास. १७,३२।

+√आह्वर (आह्वरक) १०/३९० ....(प)
श-जै-शा-हे-वो×

आचष्टे;
तेनातिक्रामति वा।

√ह्वृ १/कौटिल्ये (प)।

+√इल् (इल) १०/१२० श-च×	प्रेरणे (प) क्षी-मै-सा-जै-काक्ट-कात-शा-हे। क्षेपे—वो।	√इल् (इल) ६/ स्वप्नक्षेपणयोः (प)। √ईर् (ईर) २/ गतौ कम्पने च (आ)। √एला (कण्ड्वा.) विलासे (प)।

क—ऐल्=विश्रान्तौ, शयने ?—वा. पॉकर्नीः।

ग—(कथं वातो नेलयति कथं न रमते मनः-अ.वे. १०,७,३७। यां यां कामयते सा भूत्वेलयति—शत्रा. १०,३,३,८।)

+√ईड् (ईड) १०/१३० च×, श	स्तुतौ (प) क्षी-मै-सा-जै-काक्ट-कात-शा-हे-वो। स्तवने—कात।	√ईड् (ईड) २/ स्तुतौ (आ)।
प्रयो.	ह्वि.।	

ग—ईलयति-शत्रा. १०,३,३,८। गीर्भिरुग्राभिरैडयन्-वा. रा. ३,५,११ (गी. प्रे. सं.)। नास्त्यत्र प्रयोजकता।

+√ईर् (ईर) १०/२६१ च×, श	क्षेपे (प) क्षी-मै-सा-काक्ट-हे। क्षेपणे—जै-कात। प्रेरणे—शा। गतौ नुदि—वो।	√ईर् (ईर) २/ गतौ कम्पने च (आ)। √ईड् (ईड) २/ स्तुतौ (आ)।
प्रयो.	ह्वि.।	

ग—अपः समुद्रमैरयत्-ऋ. ८,६,१३। पन्थानो येभिर्विश्वमैरयः-अ.वे. ७,३३, १। रथन्तरं साम ईरयति-मभार. १३,९८६; अथ वाचमीरयति तासु नाम्नीरयति—१३,९८६।

+√उध्रस् (उध्रस) १०/२१४ मै-श-च-जै-काक्ट-कात-शा× (सा-हे-वो-√उध्रस्)	उञ्छे (प) उः प्रयोगसमवायीत्येके—क्षी। क्षी-सा-हे। उञ्छे उत्क्षिपि च—वो।	√उत्+√ह्रस (ह्रस) १/ शब्दार्थः (प) √ध्रस् (उध्रस) ९/ उञ्छे (प)।

+√ उलण्ड् (उलडि) १०/९ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×

उत्क्षेपणे (प) अपरे तु—सा।

√ ओलण्ड् (ओलडि) १०/ उत्क्षेपे (प)।
√ लण्ड् (लडि) १०/ उत्क्षेपे (प) अन्ये—क्षी।
√ लन्द् (लदि) १०/उत्क्षेपे (प) चान्द्राः—क्षी।

छ—√ उलटना; √ (उ) लादना; √ उल्दना–बुं. ख. = अन्नादिपूर्णशकट्या अग्रत उपरि क्षेपणे, पृष्ठभागतश्चाधोनयने, (२) अधःक्षेपे।

छ—उलदना*; √ उलेड़ना*; √ उँड़ेलना; √ उलैंडना (<उलण्डनम्) = पातने, क्षेपणे—"उलदत मद अनुमद ज्यौं जलधि जल"—कविभूषणः।

+√ ऊन (ऊन) १०/३३५ श×

परिहाणे (प) क्षी-मै-सा-जै-कात-शा-हे-वो।
परिहाणौ—च।
परिहरणे—काकृ।

√ ओण् (ओण) १/ अपनयने (प)।
√ ऊ १/५५१ f शब्दे (आ) काकृ।

क—ऑइ–, ऐउआ = अपूर्णम्, न्यूनम् हीनम्। निष्ठान्तत्वेन–नॉ—ः

ख—अवे. ऊन = ऊनम्, न्यूनम्, अपर्याप्तम्–वा. पॉकर्नीः।

ग—मा त्वायतो जरितुः काममूनयीः–ऋ. १,५३,३। (अनित्यण्यन्तत्वं तु यथालक्ष्यम्–क्षी. १०/२०१ यु. मी. सं.) आङ्योगेऽभाव इति वागीशः। यत्त ऊनं तत्त आपूरयति–अ.वे. १२,१,६१।

√ ऊर्ज् (ऊर्ज) १०/१६ श

बलप्राणनयोः (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे।
जीवने बले—वो

√ ओज १०/ बलतेजनयोः (प) वो।
√ ऊर्ज् १/४२५ g गतौ (आ) काकृ।

ऊर्क्–निघ.२/७=अन्ननाम। ऊर्जयमाने–निरु.९,४३,१ = बलवती, ऊर्जतां च कुर्वाणे–दुर्गाचार्यः।

प्राणनम् = जीवनम्—क्षी।

क—ऊएर् (ऐ) गु् = वाग्बाघाते, उच्छूनतायाम्, विस्तारे–वा, पॉकर्नीः।

७३

ग—सनाभयो वाजिनमूर्जयन्ति-ऋ. ९,८७,४। स प्राणिति तमूर्जयति-शत्रा. ७,५,१,१८। ऊर्जयति-काठ. २०,७।

+√ऊष (ऊष) १०/३८५ मै-सा-श-च-जै-काकृ-कात-शा-वो×	छुरणे (प) क्षी-हे।	√ऊष् (ऊष) १/२९० a रुजायाम् (प) काकृ; कात २२३। √ऊष् (ऊष) १/ रुजायाम् (प)। √रूष् (रूष) १/ भूषायाम् (प) इति सुधाकरः-सा।
+√ओलण्ड् (ओलडि) १०/९ श	उत्क्षेपे (प) क्षी-च-जै-काकृ-कात-शा-हे-वो। उत्क्षेपणे—मै-सा।	√लण्ड् (लडि) १०/ उत्क्षेपे (प) अन्ये-क्षी। √लन्द् (लदि) १०/ उत्क्षेपे इति चान्द्राः—क्षी √ओलञ्ज् १/ उत्क्षेपणे (प) —वो।

[छ—√ओंझना, √उड़ेलना, √उलझना-बुं. ख. (<ओलण्डनम्, आ+उज्झनम् ?)=उदेलने, पातने, क्षेपे।]

+√कण् (कण) १०/१८३ च×, झ	निमीलने (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो।	√क्ष्मील् (क्ष्मील) १/ निमेषणे (प)। √कण् (कण) १/ शब्दार्थः (प)। √कण् (कण) १/ गतौ (प) मित्त्वम्। काणो विक्रान्तदर्शन इत्यौपमन्यवः। कणतेर्वा स्यादणूभावकर्मणः। ....दर्शनाणूभावात् काणः-निरु. ६,३०,१।

क—स्कैर्-, कैर्=छेदने।

ग—काणः-ऋ. १०,१५५,१; अ. वे. १२,४,३; तै. २,५,१,७। (सरांसि सोमस्य काणुका-ऋ. ८,६६,४)।

+√कण्ठ् (कठि) १०/२९४ शX	शोके (प) आधृषाद्वा क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । आध्याने—वो ।	√कण्ठ् (कठि) १/ शोके (आ) ।

ग—कण्ठः स्तम्भितवाष्पवृत्तिकलुषः-शाकु. ४,५ ।

+√कण्ड् (कडि) १०/४५ शX	भेदे (प) इत्येके-क्षी क्षी-जै-काकृ-कात-शा । भेदने—मै-सा । खण्डने—च । भेदे खण्डने च—हे । भेदे रक्षणे—वो ।	<√खण्ड् (खडि) भेदे (प) । √खड् (खड) १०/ भेदे (प) । √खण्ड् (खडि) १/ मन्थे (आ) ।

क—केल्-, केला = ताडने, तोडने-वा. पॉकर्नीः ।

ग—त्रिभिः काण्डैः-अ. वे. १२,३,४२ । काण्डचित्राणि-वा. रा. २,८९,१८ काण्डे = जले, चित्राणि (तिल.) । कण्डनी चोदकुम्भश्च-मनु. ३,६८ । काण्डात् काण्डात् प्ररोहन्ती—वा. सं. १२,३,४२ ।

ङ—√कंड (सक) = (१) अवहनने, (२) कर्षणे, (३) खर्जने (प्रयोज.) । कंडिंत-णाया. १,७ । वक्कु-कंडंत-ओघ. ४६८; गा. ६६३ ।

छ—√काँड़ना † * = (१) मर्दने, (२) अवहनने, (३) अतिताडने ।

+√कत्र (कत्र) १०/३५७ क्षी-श-च-जै-काकृ-शाX	शैथिल्ये (प) मै मै-सा-कात-हे-वो ।	√कन्त्र् १०/६ उपाये (प) काकृ । √कर्त् (कर्त्) १०/ शैथिल्ये (प) इति चन्द्रः-क्षी । √कर्त्र् (कर्त्र) १०/ शैथिल्ये (प) इति दुर्गः-क्षी । √कत्थ (कत्थ) १०/३३५ शैथिल्ये (प) हे । √कध्र (कध्र) १०/२४० शैथिल्ये (प) काकृ । √गात्र (गात्र) १०/ शैथिल्ये (आ) वो ।

इह स्पष्टो विकासः । सर्वेषामन्ते √गात्रधातुः सुपरिचितः प्रतीयते ।

+√कथ (कथ) १०/२९७ श — वाक्यप्रतिबन्धे (प) क्षी-हे। वाक्यप्रबन्धे—मै-सा-च-काकृ-कात-शा-हे-वो। वदने—जै-हे। — √कत्थ् (कत्थ) १/ श्लाघायाम् (आ)।

क—केत्-(?), कोत्, कुत्=विकत्थने, कथने। लिथु. कतिलिन्ति=संभाषणे, कथने-वा. पॉकर्नीः।

ग—कथयति-त्रिपाद्विभूतिमहानारायणो. ५,६। कथयन्ति-भव. २,५०। कथयस्व-त्रिता. ५,१। कथयिष्यामि-मै. २,३; मैत्र्यु. २, ३।

घ—कथेति-जातक ५,४६०=सूचनायाम्। कथेति-जातक १,२=कथने।

ङ—√कह (सक)=कथने। वक्त-कत्थंत, कहिज्जंत-राज.; सुर. १,४४; गा. १९८।

ङ—√कहाव (सक)=कथने। कहावेइ-महा.।
ङ—√काह (सक)=कथने। काहयंते-महा.।
छ—√कथना*=(१) कथने, (२) निन्दने।
छ—√कहना (<कथनम्)=कथने, वर्णने।

+√कर्ण (कर्ण) १०/३६९ श-च-जै-काकृ× (शा√कर्ण्) — भेदे (प) क्षी-कात-शा-हे। भेदने—मै-सा। भिदि—वो। — √कड् १०/३८० भेदे (प) काकृ। √कण्ड् (कडि) १०/ भेदे (प) इत्येके-क्षी। कर्णः कृन्ततेर्निकृत्तद्वारो भवति-निरु. १,९,१। कीर्यते क्षिप्यते शब्दो वायुना यत्र-√कॄ+उणा. ३/१० इति नन्।

क—केर्—, कर्=ताडने, बलाद् ग्रहणे। किम्रि. कर्न्=ग्रहणे-वा. पॉकर्नीः।

ग—निचेतारा च कर्णैः-ऋ. १,१८४,२। इत्याकर्ण्य क्षितीश-नैष. ५,१३७।
ङ—कण्ण (<कर्णः)-पि. ३५८; प्रासु. २।

+√कर्त् (कर्त) १०/३५८ मै-सा-श-च-जै-काकृ-कात-शा-वो× — शैथिल्ये (प) इति चन्द्रः-क्षी। क्षी-हे। — <√कर्तृ (कर्तृ) शैथिल्ये (प)। द्रष्ट. √कत्र १०/३५७। √कृत् (कृती) ६/ छेदने (प)।

+√कर्त (कर्त) १०/३६८ क्षी-मै-श-च-जै-काकृ-कात-शा×	शैथिल्ये(प) अत्र दुर्ग इत्यपि—सा। सा-हे-वो।	<√कत्र (कत्र) शैथिल्ये (प)। पूर्ववत्।
+√कर्तृ (कर्तृ) १०/३५८ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	शैथिल्ये (प) क्षी।	पूर्ववत्।
+√कर्त्र (कर्त्र) १०/३५८ मै-सा-श-च-जै-काकृ-कात-शा×	शैथिल्ये (प) इति दुर्गः—क्षी। क्षी-हे-वो।	<√कर्तृ (कर्तृ) शैथिल्ये (प)। पूर्ववत्।
+√कल् (कल) १०/६८ च×,श	क्षेपे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। नुदि—वो। प्रयो. ह्वि.।	√कल् (कल) १/ शब्दसंख्यानयोः (आ)। √कल (कल) १०/ गतौ संख्याने च (प)। √किल् (किल) १०/ क्षेपे (प)। कालयति—निघ.२/१४=गतिकर्मा।

क—केल्=प्रेरणे—जू. पॉकर्नीः।

ग—संकालयन्—मभार. २,१०५,२२=क्षपयन् (नील.); कालयिता—२,२१,२=संहर्ता (नील.)। संकालनम्—वा. रा. २,६६,१५=प्रेतनिर्हारम् (तिल.)

+√कल (कल) १०/३१२ श	गतौ संख्याने च (प) क्षी-मै-सा-काकृ-कात। संख्याने—च। गतौ—जै। आगतौ—शा। संख्यानगत्योः—हे। गतिसंख्ययोः—वो। प्रयो. ह्वि.।	√गण (गण) १०/ संख्याने (प.)। √कलञ् १/३१३j गतौ (प) काकृ। शेषः पूर्ववत्।

ग—कालः कलयतामहम्—गी. १०,३०। कालः कलयतां प्रभुः—भा. पु. ३,२९,३८। कलये—तैब्रा. ३,४,१६,१। [समकालयन्—मभार. १,२१,७=वनमनयन्

(नील.)] (प्राकालयत्–काठ. १०,६–धा. गतौ वृत्तिः) । कलयेदमानमनसम्–शिशु. ९,५८=मन्येत ।

ङ—√कल (सक)=(१) संख्याने, (२) शब्दे, (३) ज्ञाने, (४) प्रत्यभिज्ञाने, (५) संकोचे । कलयंति–विसे. २०२९ । वक्र—कलयंत–सुपा. ४ ।

+√काल (काल) १०/३२५ क्षी-श-च-जै-काक्र-कात-शा×	उपदेशे (प) मै-सा-हे । उपयोगे—सा । (चौ. सं.) कालोपदेशे—वो ।	पूर्ववत् ।

ग—कालयन्तः–मभार. २,१७,३४=नियमयन्तः (नील.) ।

+√कालोड (कालोडित) १०/३८९ मै-सा-श-च-जै-काक्र-कात-शा-हे-वो×	..........(प) इति गुप्तः—क्षी । तदाचष्टे; तेनातिक्रामति वा ।	<√गालोड (गालोडित) (प) √लुड् (लुड) १/३१० (प) । क्+आ+√लुड्
√किल् (किल) १०/६९ मै-श-च-जै-काक्र-शा×	क्षेपे (प) क्षी-सा-कात-हे । नुदि—वो ।	√कल् (कल) १०/६८ क्षेपे (प) । √किल् (किल) ६/ श्वैत्यक्रीडनयोः(प) । √केल् (केल) १/५३७ चलने (प) ।
√किष्क् (किष्क) १०/१५४ मै-सा-श-च-काक्र-कात×	हिंसायाम् (आ) क्षी-जै-शा-हे । वधे—वो ।	>√हिष्क् (हिष्क) हिंसायाम् (आ) इति दुर्गः—क्षी । √हिक्क् (हिक्क) १/ अव्यक्ते शब्दे (उ) । √कष् (कष) १/ हिंसार्थः (प) । √खष् (खष) १/ हिंसार्थः (प) ।

क—क्र् (ऑ) स्कॉ–,—उ=दोर्दण्डः, हस्तः । शल्वे. क्रके=दोर्दण्डः, स्कन्धः–वा. पॉकर्नीः ।

ग--किष्किन्धा-वा. रा. १,१;६५। किष्किन्ध्या-वा. रा. ४,१०,३४; मभार. ३,१६१०७ (किं किं दधातीति किष्किन्धा। √धा+कः। पारस्करादित्वात् पूर्वस्य किमो मलोपः सुट् षत्वं च निपातनात्-इति वैयाकरणाः)। चतुःकिष्कुः-वा. रा. ५,३२,११।

ङ--किकिंडि=सर्पः (हिंसायाम्)-दे. २,३२।

ङ--किकिंधा=नगरीविशेषः-से. १४,१५।

च--किकिंधि=पर्वतविशेषः- पउम. ६,४५; नृपविशेषः-पउम. ६,१५४; १०,२०।

छ—खीस (<किष्कः)=विनष्टम्।

छ—खीस जाना=नाशे-'खीस खलाई'-तुलसीदासः।

+√कीट् (कीट) १०/१०० च-वो×,श (काक्र·√टीक्) (वर्णविपर्ययः)	वरणे (प) क्षी। बन्धने—मै-काक्र-कात। वर्णे—सा-शा। वर्णने—जै-हे।	√कील् (कील) १/ बन्धे (प)। √कीट् (कीट) १/ बन्धवर्णयोः (प) वो। √कट् (कटे) १/ वर्षा-वरणयोः (प)। √टङ्क् (टकि) १०/ बन्धने (प)। √टीक् १०/८० बन्धने (प) काक्र।

क--कुऋमि=कृमिः, कीटो जन्तुविशेषः-वा. पॉकर्नीः।

ग—कीट०-अ. वे. ९,४,१६; शब्रा. १४,९,१,१९; छान्दोग्यो. ६,९,३; वा. रा. २,२५,१६।

+√कुंश् (कुशि) १०/२३० च-जै-शा×,श	भासार्थः (प) क्षी—हे। भाषार्थः—मै-सा-काक्र-कात। द्युतौ—वो	√कुश् (कुश) ४/१०५ संश्लेषणे (प)। √कुंस् (कुसि) १०/२२९ भासार्थः (प)।

+√कुंस् (कुसि) १०/२२९ श-च-कात×	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काक्र। भासने—वो।	√कुश् (कुश) ४/१०५ संश्लेषणे (पं)। √कुंश् (कुशि) १०/२३० भासार्थः (प)।

+√कुट् (कुट) १०/१६४ क्षी-मै-श-च-जै-शा-हे-वो×	छेदने (आ) 'इत्येके' स्वामी-सा। सा,-काक्ऌ-कात (प)।	<√त्रुट् (त्रुट) छेदने (आ)। √कुट्ट् (कुट्ट) १०/२३ छेदन-कुत्सनयोः (प)। √कुठ् छिदि-सौ. धा.—वो। √कृत् (कृती)६/छेदने (प)।

ग—कोटि०-मभार. १,४०,२२=धनुरग्रम्। कोटि०-रघु. ७, ४६ = कोणः (कोट्यते=छिद्यतेऽनया। उणा. ४,११७ इतीन्। बाहुलकाद् गुणः)। कोटि०-कुमारसं. २, २६=रेखा।

+√कुट् (कुट) १०/१७० च-काक्ऌ-कात×,श	प्रतापने (आ) क्षी-मै-सा-जै-शा-हे-वो।	>√कूट् (कूट) आप्रदाने (आ) इति दुर्गः-क्षी। √कुट् (कुट) ६/कौटिल्ये(प)। पिता कुटस्य चर्षणिः (ऋ. १,४६,४)। पिता कृतस्य निरु. ५,२४,१। शेषः पूर्ववत्।

ग—प्रकुट्य विधिवत् तदा-मभार. १,२८४२। अवकुंट्य-सुश्रु. २,१७५,२०। कोटः (कुट्यते=प्रताप्यते शत्रुरत्र, अनेन वा। दुर्गमाश्रित्य प्रबलविपक्षमपि प्रतापयितुं शक्यत इत्यर्थः)=दुर्गम्। प्रयोगो नोपलब्धः।

छ—कोट=परिधिः (दुर्गम्)।

+√कुटुम्ब् (कुटुम्ब)१०/१४७ मै-जै-काक्ऌ-कात-शा×	धारणे (आ) क्षी-सा-,च-? हे। धृत्याम्—वो।	पूर्ववत्।

क—कुऍल=(कीटानां पशूनां मधुमक्षिकाणां वा) संघः, समूहः। ट्(ओ)-विस्तारः—वा. पॉकर्नीः।

ग—तयोरपि कुटुम्बाभ्यामाहरेत्-मनु. ११,१४। स्वकुटुम्बान् महीपतिः-मनु. ११,२२।

ङ—कुडुंब=परिजनः, परिवारः-उवा.; महा.; प्रासू. १६७।

+√कुट्ट् (कुट्ट) १०/२३ काक्ऌ-कात×,श	छेदनकुत्सनयोः (प) क्षी। छेदने—च।	√कुद् १/११७ वैकल्ये(प)। √कुठ् १०/२४ छेदने (प) काक्ऌ।

	छेदने कुत्सने च—जै-हे। छेदनभर्त्सनयोः—मै-सा। कुत्सने—शा। कुत्साछिदोः—वो। 'छेदनपूरणयोः' इति स्वामी—सा।	शेषः पूर्ववत्। √कृत् ६/ छेदने इत्यस्य प्राकृतरूपमिति ह्विट्न्यादयः।
प्रयोज.	ह्वि.।	

क—(स्) कॉड्=आच्छादने-वा. पॉकर्नीः।

ग—वाश्मकुट्टकः-याज्ञवल्क्य. ३,४९। अश्मकुट्ट०-मभार. ३,१२३६०; मनु. ६,१७। कुट्टनी (कुट्ट्यते=छिद्यते स्त्रीणां कुलमनया)-कथासरि. १२,७९। कुट्टापरान्त०-मभार. ६,३५६। ससुधाकुट्टिमतलः-वा. रा. २,८०,३। मणिप्रवरकुट्टिम०-मभार. १४,२५२२।

घ—कोट्टेति-जातक १,४७८।

ङ—√कुट्ट (सक)=कुट्टने, ताडने, (२) कर्तने, (३) औष्ण्ये, (४) उपालम्भे। भवि—कुट्टइस्सं-पि. ५२८।

ङ—√कोट्ट (सक)=कुट्टने, ताडने, (२) कर्तने। कवकृ-कोटिज्जमाण-आवम.। संकृ—कोट्टिय-जीव. ३।

छ—√कूटना (<कुट्टनम्)।

ज—√कोटे=मुद्गरेण ताडने।

+√कुट्ट् (कुट्ट) १०/१६८ क्षी-मै-श-च-जै-काकृ-कात-शा-हे×	प्रतापने (आ) इति क्षीरस्वामी—सा-,वो।	√कुट् (कुट) १०/१७० प्रतापने (आ)। शेषः पूर्ववत्।

सर्वाण्युदाहरणानि पूर्ववज्ज्ञेयानि। विशेषतः प्राकृतधातोरुदाहरणं सुस्पष्टमौष्ण्ये दृश्यते।

+√कुण (कुण) १०/३३९ श-च×	आमन्त्रणे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। आभाषमन्त्रयोः—वो।	√कुण् (कुण) ६/ शब्दोपकरणयोः (प)। √गुण (गुण) १०/ आमन्त्रणे (प)। √कूट् (कूट) १०/ आमन्त्रणे (प) सा।

	आमन्त्रणम्=गूढोक्तिः—क्षी।	कुणारुम् इति—निरु. २,२,५; ६,१,४ = क्वणः शब्दार्थः—दुर्गाचार्यः।
+√कुण्ठ् (कुठि) १०/५० क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	वेष्टने (प) एके-सा। 'रक्षणे' इत्येके—सा।	>√गुण्ड् (गुडि) वेष्टने (प)। √गुण्ठ् (गुठि) १०/ वेष्टने (प)। √कुठ् १/ छेदने (प) सौ. धा.—वो।
+√कुण्ड् (कुडि) १०/४६ च×,श	रक्षणे (प) इत्येके-क्षी क्षी-मै-सा-जै-काकृ-कात-शा-हे। रक्षे—वो।	>√गुण्ड् (गुडि) रक्षणे (प)। √गुड् ६/ रक्षायाम् (प)।

ग—कुण्डिनः=मुनिविशेषः। यथाश्वलायने-"०कुण्डिनानां वाशिष्ठमैत्रावरुणकौण्डिन्येति" (श. क. द्रु.); कुरुवंशीयनृपभेदः। स च धृतराष्ट्रस्य पुत्रः। यथा महाभारते १, ९४, ५८।

ङ—कुंड=आज्ञा, आदेशः—कप्प.।

√कुत्स् (कुत्स) १०/१६६ च×,श	अवक्षेपणे (आ) क्षी-मै-सा-कात-शा। अवक्षेपे—जै-काकृ-हे,-वो (उ)।	√कुत् १/ आस्तृतौ (प) सौ. धा.—वो। अवकुत्सिते—निरु. १,४,१४। कुत्सितम्—निरु. १,२०,५।

क—केउएद्-, कुद्-, कूद=आक्रोशे, तर्जने-जू. पॉकर्नीः।
ख—न. पर्सि. निकूहीदन्=आक्रोशे, कुत्सने,अपमाने-वा. पॉकर्नीः।

ग—वहत्कुत्समार्जुनेयं शतक्रतुः-ऋ. ८,१,११; कुत्स्येन-४,१६,१२। कुत्सनम्-१ संन्या. २८६। कुत्सन्तो धृतराष्ट्रजम्-मभार. २,२२९८। अभ्यकुत्सयत्-वा. रा. २,७५,२। न कुत्सयाम्यहं किञ्चित्-मभार. ३, १३७२३।

ङ—√कुच्छ (सक)=निन्दायाम्, धिक्कारे। कृ-कुच्छ, कुच्छणिज्ज-श्रा. २७; पण्ह. १, ३।

√कुद्द् (कुद्द)१०/६ मै-श-च-जै-काक्र-शा-हे-वो×
अनृतभाषणे(प) इत्येके-क्षी। क्षी-सा-कात।
<√कुन्द्र् (कुद्रि) अनृतभाषणे (प)।
√कुण्ड् १०/१३ अनृतभाषणे (प) काक्र।
√गुन्द्र् (गुद्रि) १०/ अनृतभाषणे—पारायणे—क्षी।

द्रष्ट.—√कुन्द्र् १०/६

ङ—कुद्दण=रासकः (रासा ?)–दे. २,३८।

+√कुन्द्र् (कुद्रि) १०/६ काक्र-कात×,श
अनृतभाषणे (प) क्षी-मै-सा-च-जै-शा-हे। मिथ्योक्तौ—वो।
>√कुद्द् (कुद्द) अनृतभाषणे (प)।
>√गुन्द्र् (गुद्रि) अनृतभाषणे (प)।
√कुण्ड् १०/१३ अनृतभाषणे (प) काक्र।

पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः–मनु. ३,१७४। अज्ञाते सति कुण्डमपि सुतं जनाः पत्युरेवाख्यापयन्ति। इदमनृतभाषणम्। काशकृत्स्नपठितः √कुण्ड् १०/१३ अनृतभाषणे (प) इति धातुर्भृशं संवदति। √कुण्ड् >√कुन्द्र् >√गुन्द्र् >√कुद्द् इत्येवं स्यात् प्रततिः (विकासः)।

+√कुप् (कुप) १०/२५० च×,श (शा–√कूप्) जै–√त्रुप् [त्रुप] मुद्रणदोषो भाति।
भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काक्र-कात। द्युतौ—वो।
√कुप् (कुप) ४/ क्रोधे (प)।
√गुप् (गुपू) १०/ भासार्थः (प)।

ग—[कोपयथ पृथिवीम्–ऋ. ५,५७,३=क्रोधे। सपित्तं कोपयेद् वायुम्–सुश्रु. १,३७,८ (क्रोधे ?)]।

+√कुमार (कुमार) १०/३२४ शा-च×
क्रीडायाम् (प) क्षी-मै-सा-काक्र-कात-शा-हे। क्रीडने—जै। केलौ—वो।
कु=कुत्सितः, मारः=कन्दर्पो यस्मात् कुमारः।
कु+√मृ (मृङ्) ६/ प्राणत्यागे (आ)।

√कुमाल १०/३४३ क्रीडायाम् (प) हे।

कुमारः क्रीडयामास उत्सङ्गे शङ्करस्य च।
कण्ठे स्थितं वासुकिं च पाणिभ्यां समपीडयत्॥ स्क. पु. १,२७,१०७।

ग—कुमारं माता बिभर्ति–ऋ. ५,२,१। कुमाराणां च रक्षणम्–मनु. ७,१५२।

ङ—कुमार=प्रथमे वयसि स्थितो बालकः–ठा. १०; णाया. १,२।

√कुम्प् (कुपि) १०/११५ मै-सा-श-च-जै-काक्र-कात-शा-हे×
छादने (प) क्षी।
स्तृतौ—वो।
>√कुम्ब् (कुबि) छादने (प) इति कौशिकः–क्षी।
>√कुम्भ् (कुभि) १०/१२० छादने (प) अपरे–सा।

क—कॉइ=न्युब्जत्वे, प्रह्वत्वे। कॉइ-प्-ः लिथु. कुम्प्ति=कुब्जीभावे; कुम्पस्=अरालता। लेट्टिश्-कुम्प्त्=कौटिल्यम्। गॉथि. हम्फ्स्=संक्षेपे। रसन्-कुपिन=कुब्जः, कुब्जवनिका। पु. प्रशि. ऐत्कूम्प्स्=पुनः, प्रत्यग्रतः–वा. पॉकर्नीः।

ङ—खुंपा=वर्षावरोधार्थं निर्मीयमाणं तृणमयमुपकरणम्–दे. २,७५।

ङ—गुम्मइ=मूर्खः–ओघ. १३६; पूरितम्–दे. २,१०३; स्खलितम्–२,१०३।

छ—गुम्मा=मूकः, छादितवाक्कः–बुं. ख.।

+√कुम्ब् (कुबि) १०/११५ च×,श
छादने (प) इति कौशिकः—क्षी।
क्षी-सा-जै-काक्र-शा।
आच्छादने—मै-कात-हे।
स्तृत्याम्—वो।
<√कुम्प् (कुपि) छादने (प)। शेषः पूर्ववत्।

क—कॉइ-ओष्ठ्यनासिक्ययोर्विस्तारे सति—कुम्-भ्-, कुम्ब्—ः नॉर्वेजियन् (प्रादे.) हुप्प् तथा हुम्प्=आधीन्ये, मार्दवे। इँग्लि. हम्प=कूकुदः। न. ज. हम्पे=घनत्वम्, स्थौल्यम्, शकलम्।

ख—अवे. क्सुम्ब=कुसुम्भम् (=कमण्डलुः), कुम्भः। न. पर्सि. क्सुम्ब्, क्सुम्=कुसुम्भम्, कुम्भः–वा. पॉकर्नीः।

ग—उदीचीनकुम्बां शम्यां निदधाति–तै. प्रा. १२२। [गाथां वा कुम्ब्यां वा–शब्रा. ११,५,७,१०]। कुम्बिक०—बृहत्सं. १४,३०।

ङ—खुम्मिय=नामितम्–णाया. १,१–पत्र. ४७।

छ—गुम्मा=इष्टका–बुं. ख.।

+√कुम्भ् (कुभि) १०/१२० छादने (प) अपरे—सा। <√कुम्ब् (कुबि) छादने (प)।
क्षी-मै-श-च-जै-काकृ-
कात-शा-हे-वो×

शेषः पूर्ववत्।
कुम् = भूमिम्, उम्भति = जलेन पूरयति + अच्—कुम्भः = घटः।

क—, ख—पूर्ववत्।

ग—शतं कुम्भाँ असिञ्चतं सुरायाः—ऋ. १, ११६, ६। इभकुम्भ०—मालती-मा. ५,३२।

+√कुशूल (कुशूल) १०/३२२ क्रीडायाम् (प) इत्येके—मै। कु+√शूल् (शूल) १/रुजायाम् (प)।
क्षी-सा-श-च-जै-काकृ-
कात-शा-हे-वो×
कु+√श्वि (टुओश्वि) १/गतिवृद्ध्योः (प)।

ग—कुशूलधान्यको वा स्यात्—मनु. ४,७। आधिक्येन 'कुसूल' इति लभ्यते पाठः।

ङ—कुसूल = धान्यागारम् (पाअ.)

+√कुस्म् (कुस्म) १०/१७९ नाम्नो वा (आ) कु+√स्मि (ष्मिङ्) १/ईषद्धसने (आ)।
च×, श
कुस्मयने—दुर्गस्तु—क्षी।
क्षी-मै-सा-काकृ-कात-शा-हे।
कुस्मितौ—जै।
कुस्मृताविति मुद्रणदोषः।
मतीक्षिते कुस्मितौ—वो।

मतीक्षितम् = बुद्धिपूर्वकदर्शनम्—दुर्गादासः।
कुस्मेति धातुर्मतिदृष्टं बुद्ध्योत्पादितमर्थमाहेति च—क्षी।

ग—आकुस्मयते—सम्भाष्ये १,३,६२, २८९ [११/१५] विकुस्मयते—१,३,६२, २८९ [११/१५]।

+√कुह् (कुह) १०/३४५ विस्मापने (आ) √कुह् १/३१६ a हिंसागत्योः (प) काकृ।
श×
क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
कुहूः—निरु. ११,३१।

क—(सू) कॉइ = छादने। स्कॉइध्—ः—वा. पॉकर्नीः।

ग—कुहः यत् त्वा पृच्छादीजानः कुहया कुहयाकृते–ऋ. ८,२४,३० । कुहूः–ऐत्रा. ३,४७ । कुह०–वा. रा. २,१०९,२७=माया० । जनः कुहुकुहायते–मभार. ३,१४१२९ । कुहकम्–भा. पु. १,१,१ । कोहलो वदनप्रियः–सुश्रु. सूत्रस्थाने ४५ अध्याये=मद्यभेदः (कोहयति=विस्मापयतीति) ।

ङ—कुह=अनोकहः–दस. ७ ।

+√कूट् (कूट) १०/१७०
च-जै-शा×,श

आप्रदाने (आ) इति दुर्गः–क्षी ।
क्षी-सा ।
अप्रमादे—मै-हे
'अवसादने' इत्येके—सा ।
प्रमादे—काकृ-कात ।
अप्रदाप्रमदोः—वो ।
अप्रसादे—ब्योथ.-रॉथ. ।
अप्रदा=दानाभावः–दुर्गादासः ।

<√कुट् (कुट) प्रतापने (आ)
√कूट् १/११३hगतौ (प)
काकृ ।
कूटः (कूट्यते=दातुं न शक्यते स्थावरत्वात् । कर्मणि घञ्) =गृहम् इति शब्दरत्नावली ।

कं—केरल्-,केल् =कौटिल्ये–वा. पॉकर्नीः ।

ग—अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः–अ.वे. ८,८,१६ । कूटयुद्धाः–वा. रा. १,२०,८—कूटम् =कपटम् (तिल.) ।

ङ—√कूड (सक)=१–असत्यापने, २–अन्यथात्वे । कूडे–अणु. ५० टी. ।

ङ—√कूड (<कूटम्)=पाशः–राय.; उत्त. ५; सूअ. १,५,२ ।

ङ—√कूड (<कूटम्)=असत्यम् , छलयुतम्–पडि.; प्रतारणम्–सुपा.६२७; नरकः–उत. ५ ।

+√कूट (कूट) १०/३३७
श×

दाहे (प)
क्षी-च-जै-काकृ-शा ।
परिदाहे, आमन्त्रणे—मै ।
परीतापे—सा
आमन्त्रणे—सा ।
दाहे आमन्त्रणे च—काकृ ।

√कुण्ड् (कुडि) १/ दाहे (आ) ।
शेषः पूर्ववत् ।

'परिदाहे' इत्यन्ये—
सा।
दाहे मन्त्रे—वो।

क—पूर्ववत्।

ऋग्वेदे √कूळ् धातुर्दाहार्थकः ?। तद्यथा-नेदीयसः कूळयातः पणींरुत-८,२६,१०। सुश्रुते-√कूल् दाहे। तद्यथा-(अग्निः) तासां प्राजमानो योनिमकूलयत्; अङ्गारैः खादिरैरवकूलयेत्-सुश्रु. २,३५०,१८।

√कुण्ड्>√कूड् (>√कूल्) >√कूट् इति स्यात् क्रमः।
ग—कूटं स्म तृंहत्-ऋ. १०,१०२,४।
ङ—पूर्ववत्।

+√कूण् (कूण) १०/१५७ च-काक्ृ×,श	सङ्कोचने (आ) क्षी-मै-सा-जै-कात-शा-हे। सङ्कुचि—वो।	√कुण् (कुण) ६/ शब्दोपकरणयोः (प)। √कुण् (कुण) १०/ आमन्त्रणे (प)।
√कुण् (कुण) १०/१५४	संकोचने(आ)अन्ये—सा। सा-काक्ृ।	आमन्त्रणम् = गूढोक्तिः-क्षी। √कूप (कूप) १०/ दौर्बल्ये
√कूण् (कूण) १०/३५१	संकोचने (प) सा। सङ्कोचे—वो।	(प) इति। त्रिलोचन इति कविकल्पद्रुमटीकायां
√कूण् (यौ. प्र.)	ह्वि।	दुर्गादासः।

क—पूर्ववत्।

ग—विकूणयन्तीव मुखम्-कामसूत्रे २,५,४२=सङ्कोचयन्तीव। कूणित०-सुश्रु. १,३६२,१।

ङ—√कूण (सक)=सङ्कोचने-गउड.।

+√कृप् (कृपेः) १०/२०८ श-च×(मै-काक्ृ- √क्लृप् [क्लृप])	तादर्थ्ये (प। क्षी। अवकल्कने—मै-सा-कात-हे। अवकल्पने—काक्ृ-श। युतौ चिन्ते कल्पने च—वो। जै ?।
प्रयो.····	विलापे, शोके—ह्वि.।

तादर्थ्यम् = उद्देश्यविषयम्-क्षी। अवकल्कनम् = पीडनम्-मै।

ग—उपकल्पितम्-वा. रा. २,१३,४ = सिद्धं कृतम् (तिल.)। अकल्पयन्-मभारं. १२,३२८,८ = प्रवर्तितवन्तः (नील.)।

घ—कप्पेति-जातक १,६२।

+√कृप (कृप) १०/३१६ श-च×	दौर्बल्ये (प) क्षी-मै-सा-काकृ-कात-शा-हे-वो। शैथिल्ये—जै।	√कृप् (कृपेः) १०/ तादर्थ्ये (प)। √कृप् (कृपू) १/ सामर्थ्ये (आ)।
प्रयो.	विलापे, शोके—ह्वि.।	

ग—होत्राय वृतः कृपयन्नदीधेत्-ऋ. १०,९८,७; बृहस्पतिनाकृपयद्वलो गाः-१०, ६८,१०। (कृपयसे-जैब्रा. १००)। कृपणम्-वा. रा. २,१२,७२ = कष्टम् (तिल.); कृपणेभ्यः-२,३२,२८ = दीनेभ्यः (तिल.)। कृपणः-बृहदारण्यको. ३,८,१० [दौर्बल्ये धा. वृत्तिः]। पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः—भा. पु. ८,७,४०।

ङ—√खिप्प (अक) = दौर्बल्ये। खिप्पइ-संक्षि. ३५।

छ—√कपटना (<कपलना<कल्पनम्) = संक्षेपणे, नैयून्ये। अंश-निष्कासनेनाल्पत्वे।

+√कॄ १०/१७५ मै-सा-च-जै-काकृ-कात× (शा√कॄ [कॄञ्]) मुद्रण-दोषः। कॄङ् इत्युचितम्।	विज्ञाने (आ) इति चन्द्रः-क्षी। क्षी-हे-वो।	<√गॄ विज्ञाने (आ)।

+√कॄत् (कॄत) १०/११३ श×	संशब्दने (प) क्षी-मै-सा-च-कात-शा-हे। आख्याने—जै। संशब्दे—काकृ-वो।	√कृत् (कृती) ७/ वेष्टने (प)। √कृ (डुकृञ्) ८/ करणे (उ)।

ग—नान्यासां कीर्तयाश्चन-ऋ. ७,३७,१। यद्रुद्रस्य कीर्तयति-तै. ६,१,७,८।

घ—√कित्त संसद्दे-धापा. ५७९ कित्तेति, कित्तयति-पेतवत्थु १२४।

ङ—√किट्ट (सक) = १-श्लाघायाम्, स्तुतौ, २-वर्णने, ३-कथने। किट्टइ, किट्टेइ-आचा.; भग.।

+√क्लृप् (क्लृप) १०/२०० च=अवकल्कने (प) मै।
क्षी-सा-श-च-जै-कात-शा- अवकल्पने—काकृ।
हे-वो ×

प्रयो. विलापे—ह्वि.।

ग—द्रष्ट. √कृप् (कृपेः) १०/२०८ तादर्थ्ये (प) इति।

+√केत (केत) १०/३३८ निश्रावणे (प) क्षी।
श-च ×
'निमन्त्रणे' इत्येके—क्षी,-सा।
आमन्त्रणे—मै-सा-जै-काकृ-कात-शा-हे।
निश्रावणनिमन्त्रणयोः—हे।
मन्त्रणे निश्रावणे—वो।

√कित् (कित) १/ निवासे. रोगापनयने च (प)।
√कित् (कित) ३/ ज्ञाने (प)।

निश्रावणम् = समयोद्भावनम्—दुर्गादासः।

क—कुऑइ-, कुई=इच्छा। पु. प्रशि. कुआइत्स्=वाञ्छा, निर्णयः, प्रवृत्तिः। गॉथि. हैदुस्=केतुः-वा. पॉकर्नीः।

ग—केतवेदस्-ऋ. १,१०४,३। क्षात्रधर्माणमप्याजौ केतयेत् कुलजं द्विजम्-मभार. १३,१५९६। एकोद्दिष्टस्य केतनम्-मनु. ४,११०=निमन्त्रणम् (मन्वर्थ.)। केतितः-मभार. १२,३,२७८=निमन्त्रितः (नील.)।

ज—केड़ा=आमन्त्रणे, निमन्त्रणे।

+√क्रथ् (क्रथ) १०/१३ प्रतिहर्षे (प) इति नन्दी—क्षी।
मै-श-च-जै-काकृ-कात-शा-हे ×
क्षी-वो।
'अतिहर्षे' इति बहवः—सा।
'प्रस्थाने' इति मैत्रेयः—सा।
प्रसादे, आनन्दे—ह्वि.।

< √श्रथ् (श्रथ) प्रतिहर्षे (प)।

क्रथिमपि केचिदत्र (१०/१३) पठन्ति स मैत्रेयादौ न दृश्यते-सा १३। इति नैनं सायणोऽनुमोदते। ह्विट्नीः संदिग्धार्थानि संज्ञारूपाण्युपस्थापितवान्। तान्येतदर्थकानि मया नाधिगतानि।

+√क्रथ् (क्रथ) १०/२७५ हिंसायाम् (प) √क्रंश्-निरु. २/२५।
शच× आधृषाद्वा। √क्रथ् (क्रथ) १/ हिंसार्थः
क्षी-मै-सा-जै-काकृ- (प) मित्-द्र.।
कात-शा-हे। √क्लथ् (क्लथ) १/
वधे—वो। हिंसार्थः (प) मित्-द्रष्ट.।
प्रसादे, आनन्दे—
प्रयो. ह्वि.।

ग—जासिनिप्रहणनाटक्राथपिषां हिंसायाम्-पा. अ. २/३/५६। द्रष्ट. √क्रथ् (क्रथ) १/७९३।

+√क्रन्द् (आङः क्रन्द) १०/१९५ सातत्ये (प)।
श ? च-जै-शा× क्षी-मै-सा-काकृ-कात-हे।
शब्दसातत्ये—वो।

√घुष् (घुषिर्) १०/१९४ विशब्दने (प) इत्यस्माद् 'विशब्दने' इत्यस्यानुवृत्तौ "विशब्दन-सातत्ये" इति योजनीयमिति वागीशः।

ग—आ क्रन्दय बलमोजो न आ धाः-ऋ. ६,४७,३०। आ क्रन्दय धनपते-अ.वे. २,३६,६। पुरुषानाक्रन्दयतः-शब्रा. ११,६,१,६; वा. सं. १६,१९। मुहुराक्रन्दयिष्यतः-भा. पु. ३,१४,३८।

+√क्लप् (क्लप) १०/१२३ व्यक्तायां वाचि (प) √लप् (लप) १/ व्यक्तायां
क्षी-मै,-श ?-च-जै-काकृ- इत्येके—सा। वाचि (प)।
कात-शा-हे-वो×

छ—कलपना (<क्लपनम्) = विलापे, दुःखोदन्तमनुचिन्तमनुचिन्त्य मुक्त्वोक्त्वा वा रोदने। * कल्पने।

+√क्लव् (क्लव) १०/३८५ ·········(आ) √क्लु (क्लुङ्) १/
मै-श-च-जै-काकृ-कात-शा× क्षी-सा-हे× गतौ (आ) इत्येके-मै।
भये—त्रो। √क्रु (क्रुङ्) १/ गतौ
(आ) इति क्वचित्
पठ्यते-सा।

ग—विक्लवं दूतमासाद्य-वा. रा. ५,२,३९; वैक्लव्यम्-५,२,४१।

+√क्षञ्ज् (क्षजि) १०/८४ कृच्छ्रजीवने (प) √खञ्ज् (खजि) १/
श क्षी-मै-सा-च-जै-काकृ- गतिवैकल्ये (प)।

	कात-शा-हे ।	√खज् (खज) १/ मन्थे (प)
	तङ्के—वो ।	
		ङ—√खंज (अक)=गति-वैकल्ये—कप्पू. ।

क—स्कॆंज्=गतिवैकल्ये, तङ्के । स्वीडिश् -स्किक्=तङ्के; पु. आइस. हिंक=तङ्के—वा. पॉकर्नीः ।

+√क्षप (क्षप) १०/३८५ शा-च-जै-काकृ-कात-शा×	प्रेरणे (प) क्षी-मै-सा-हे ।	क्षपा (निघ. १/७) √छम्प् (छपि) १०/
√क्षप् (क्षप) १/८०३ k; भोजः १,१,१९२— । मै-श-च-जै-काकृ-कात-शा-वो×(हे)	क्षेपे—वो । मित्त्वम् ।	गत्याम् (प)। √क्षम्प् (क्षपि) १०/ क्षान्त्याम् (प)। √क्षिप् (क्षिप) ४/,६
	संयमित्वे (उ)—ह्वि. । उपवासे (उ)—ह्वि. ।	प्रेरणे (प)।

क—कृउ सेप्-(?)=क्षपा, अन्धकारः ।

ख—अवे. क्षप्=अन्धकारः—वा. पॉकर्नीः ।

ग—क्षपयित्वा—ब्रसू. ४,१,१९ । क्षपय—वनदुर्गो. ४५९:१८ । संक्षपितोदकः—वा.रा. २,४८,३७=क्षीणोदकः (तिल.)। कालं क्षपयित्वा—मभार. १२,२७९,१८=नीत्वा (वाहयित्वा) । क्षपेयुस्त्र्यहमेव च—मनु. ५,६९=त्र्यहाशौचं कुर्यात् (मन्वर्थ.); कामं तु क्षपयेद् देहम्—मनु. ५,१५७=क्षीणं कुर्यात् (मन्वर्थ.)। क्षपणः—शांआ. १२,७; मभार. १,३,१२=संन्यासी । क्षपणं त्र्यहम्—मनु. ४,२२२=उपवासः (मन्वर्थ.)। क्षपिता—रघु. ८,४७=नाशिता (संजी.)।

ङ—√खव (सक)=नाशे, (२) प्रेरणे, क्षेपे, (३) उल्लङ्घने । खवेइ—उव. ।

छ—√खपना,√खपाना (<क्षपणम्)=केनापि प्रकारेण व्यये, (२) निर्वाहे, (३) नाशे

+√क्षम्प् (क्षपि) १०/८३ शा-कात×	क्षान्त्याम् (प) क्षी-मै-सा-जै-शा ।	√क्षम् (क्षमूष्) १/ सहने (आ)।
	क्षान्तौ—च-काकृ । हे ?	√छम्प् (छपि) १०/ गत्याम् (प)।
	शक्तौ—वो।	√कम्प् १०/३५ c क्षान्तौ (प) काकृ।

√चम्प् १०/३५ d क्षान्तौ (प) काकृ।
√सम्प् १०/३५ e क्षान्तौ (प) काकृ।
√क्षज् १०/२८ क्षान्तौ (प) कात।

शक्तिः=इह क्षमा-दुर्गादासः।

छ—√झाँपना=आवृतौ, व्यवधाने; (२) क्षान्तौ, लज्जायाम् ('झेंपना' इति हिन्दी)।

√क्षल् (क्षल) १०/६१ श — शौचकर्मणि (प) क्षी-मै-सा-जै-शा। शौचे—च-काकृ-कात-हे-वो। प्रक्षालने—ह्वि.। — √क्षल् (क्षल) १/ संचये, च=संचलने (प)। √क्षर् (क्षर) १/ संचलने (प)।

क—गुह्एर् (अथवा-गुअर् ??)=प्रवाहे, धावने।

ख—अवे.-य्ज़ुरैति=क्षलति। य्ज़ारयेइति=क्षालयति-वा. पॉकर्नीः।

ग—प्रक्षाल्य पाणी-शब्रा. १४,९,३,१३। क्षालयन्ति-रुद्रो. २७। क्षालयेत्-जाबालदर्शनो. ५,१४।

ङ—√खाल (सक)=प्रक्षालने। कृ-खालणिज्ज-उप. ३२६।

छ—√पखारना (<प्रक्षालनम्)=शौचकर्मणि।

छ—√खंगारना † } =(<स्वयम्भूरनुस्वारः <खगालना <खकालना
छ—√खंघारना † } <षकालनम् <क्षालनम्)=मनाक् प्रक्षालने, (२)
छ—√खंगालना } सर्वस्वापहरणे।

+√क्षोट (क्षोट) १०/३१९ क्षेपे (प) क्षी-श-च-जै-काकृ-मै-सा। कात-शा-हे-वो× — √खोट (खोट) १०/ भक्षणे (प) मै। √खोट्ट १०/२०८ क्षेपे (प) काकृ। √खोड (खोड) १०/ क्षेपे (प)

ङ—, च— { √छोड (<क्षोटनम्)=क्षेपणे, उन्मोचने। छोडइ, छोडेइ-भवि.; महा.। संकृ-छोडिवि-सुपा. २४९।

छ—√छोड़ना=प्रेरणे, क्षेपे, उन्मोचने ।

+√खट्ट् (खट्ट) १०/९२ श×	संवरणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । वृतौ—वो ।	√कट् (कटे) १/ वर्षावरणयोः (प)। √कष् १/६७६ a संवरणे (उ) काकृ; ५८५ a कात । √खुड् (खुड) ६/ संवरणे (प) इत्येके-मै । √छुड् (छुड) ६/ संवरणे (प) इत्येके-मै । √छद् (छद) १०/ संवरणे (प)।

छ—खटिया (<खट्टिका-शब्दमाला)=शवयानम् ।

छ—खटीक (<खट्टिकः-शब्दमाला । खट्टनम् =आवरणम्-खट्टः, स शिल्पत्वेनास्यास्तीति [ठन्])=शाकुनिकः ।

+√खड् (खड) १०/४४ श	भेदे (प) क्षी-च-जै-काकृ-कात-शा-हे-वो । भेदने—मै-सा ।	√खण्ड् (खडि) १०/ भेदे (प)। √कण्ड् (कडि) १०/ भेदे (प) इत्येके-क्षी । √कड् १०/३८ c भेदे (प) काकृ ।

क—केल्-, केला=ताडने, नाशे । ड्-विस्तारः-वा. पॉकर्नीः ।

ग—खड्गरेऽधिचक्रमां खर्विकां खर्ववासिनीम्-अ. वे. ११,९१६ । खड्गः=अस्त्रविशेषः-मभार. ४,४१,२५ (खडति=भिनत्तीति (उणा. १/१२३) इति गन्)। खड्गः=गण्डकः । यथाह मनुः-३,२७२ ।

+√खण्ड् (खडि) १०/४५ वो×, श	भेदे (प) क्षी-च-जै-काकृ-कात-शा-हे-वो । भेदने—मै-सा ।	>√कण्ड् (कडि) भेदे (प) इत्येके-क्षी । √खड् (खड) १०/ भेदे (प)। √खण्ड् (खडि) १/ मन्थे (आ)।

ग—आखण्डल०-ऋ. ८,१७,१२। अवखण्डयति-बृहदारण्यकोप. ५,७। खण्डयेत्-पै. ४,२२।

घ—वेतनं खण्डेत्वा-जातक ३,१८८।

ङ—√खंड (सक)=खण्डने, भेदने,। कवक्र-खंडिज्जंत-से.१३,३२; सुपा. १३४। हेक्र-खंडित्तए-उवा.; क्र-खंडियव्व-उप. ७२८ टी.।

ज—√खांडा=खण्डने। खड्गः।

+√खुण्ड् (खुडि) १०/४८	खण्डने (प)	पूर्वधातुवत्।
मै-श-च-जै-काक्र-	क्षी-सा-हे।	√खुर् (खुर) ६/ खण्डने (प) मै।
कात-शा×	भेदे—वो	

ङ—√खुड (सक)=खण्डने। खुडेंति-से. ८४८; वक्र-खुडंत-स. ११३।

ङ—√खुट्ट (सक)=खण्डने। खुट्टइ-नाट-साहित्य. २२९; खुट्टंति-उत्त.।

छ—√खूँदना (<खुण्डनम्)=पादैर्मर्दने, मर्दयित्वा विकृतौ, (२) कुट्टने।

छ—√खोंटना (<खुण्डनम्)=खण्डने-बुं. ख.।

छ—√खूँटना (<खुण्डनम्)=खण्डने।

+√खेट (खेट) १०/३२१	भक्षणे (प)	>√खेड (खेड) भक्षणे (प) इति दौर्गाः-क्षी।
श-च-शा×	क्षी-मै-सा-जै-काक्र-कात-हे-वो।	√खिट् (खिट) १/ उत्त्रासे (प)।
		√खोट् (खोट) १०/ भक्षणे (प) इत्येके-सा।

क:—स्केर्-, केर्=छेदने। अल्बे. केत् =कर्तरिका-वा. पॉकर्नीः।

छ—खेट=(<खेटम्=तृणम्-शब्दरत्नावली)=तृणकः।

छ—खेटकी='भड्डरी' इति हिन्दी। "कोई पूछै चेटकीन, कोई पूछै खेटकीन" -रघुराजः।

+√खेड (खेड) १०/३२१	भक्षणे (प) इति दौर्गाः-क्षी।	<√खेट (खेट) १०/ भक्षणे (प)।
मै-श-च-जै-काक्र-कात×	क्षी-सा-शा-हे-वो।	√खेण् १/२१३ g गतौ (प) काक्र।
		शेषः पूर्ववत्।

+√खोट (खोट) १०/३१८ क्षी-श-च-जै-काकृ-कात-शा-हे-वो×	भक्षणें (प) इति च —मै। मै-सा।	<√खेट (खेट) १०/ भक्षणे (प)। √खोट् १/ गत्याघाते (प) वो। √खोट्ट १०/२०८ क्षेपे (प) काकृ।
+√खोट (खोट) १०/३२२ मै-सा-श-च-काकृ-शा×	क्षेपे (प) इति पाठभेदः—क्षी। क्षी-जै-कात-हे-वो।	√क्षोट (क्षोट) १०/ क्षेपे (प) मै। √खोद (खोद) १०/ क्षेपे (प)। √खोड (खोड) १०/ क्षेपे (प)। √खोट्ट १०/२०८ क्षेपे (प) काकृ।

छ—खोट (<खोटः)=दोषः। "सूरदास पारस के परसे मिटत लोह की खोट"—सूरदासः।

छ—खोड़ा (<खोटः)=भूतप्रेतादिकोपः।

+√खोड (खोड) १०/३२२ मै-सा-श-च-जै-काकृ-कात×	क्षेपे (प) क्षी-शा-हे-वो।	>√खोट (खोट) क्षेपे (प)। √खोड् १/ खोटने (प) वो। √खोल् १/ खोटने (प) वो।

छ—खोड़ा (<खोडः)=भूतप्रेतादिकोपः।

छ—खोंड़ा (<खोडः)=दूषितम्।

+√खोद (खोद) १०/३२२ मै-सा-श-च-जै-काकृ-कात-शा-वो×	क्षेपे (प) इति पाठभेदः—क्षी। क्षी-हे।	<√खोड (खोड) क्षेपे (प)।

सुस्पष्टो विकासः—√खोट>√खोड>√खोद इति।

छ—√खोदना (<खोदनम्)=प्रेरणे, क्षेपे। खननादस्य व्युत्पत्तिः क्लिष्टकल्पनात्मिका।

+√गज् (गज) १०/१०७ मै-श-च-जै-काकृ- कात×	शब्दार्थः (प) क्षी-सा। शब्दे—शा-हे। स्वने—वो।	द्रष्ट.√गज् (गज) १/ शब्दार्थः (प)।

छ—गच=कस्मिंश्चिन्मृदुवस्तुनि कस्यचन निशितवस्तुनः प्रवेशशब्दः।

+√गण (गण) १०/२९९ श	संख्याने (प) क्षी-मै-सा-च-जै- काकृ-कात-शा- हे-वो।	√कल् (कल) १/ शब्दसंख्या- नयोः (आ)। √कल (कल) १०/ गतौ संख्याने च (प)।

क—गेर्=ग्रहणे-वा. पॉकर्नीः।

ग—मारुतं गणम्-ऋ. १,१४,३; ओगणासः-१०,८९,१५। गणयाञ्चकार-जैब्रा. १८१। सोऽहं न गणयाम्येनान्-मभार. २,१५५२।

घ—गणेति-धम्मपद १९; जातक ६,३३४।

ङ—गण (सक)=गणने, २-आहृतौ, ३-अभ्यासे, ४-पर्यालोचने। गणइ, गणेइ-कुमा.; महा.।

ङ—√गिण (सक)=गणने। गिणंति-सट्टि. ९७।

छ—√गनना }
छ—√गिनना } (<गणनम्)=संख्याने।

+√गद (गद) १०/३०७ श×	देवशब्दे (प) क्षी-मै-सा-च-जै- काकृ-कात-शा। गर्जे—हे। अभ्रध्वनौ—वो।	√गद् (गद) व्यक्तायां वाचि (प)। √गध् ४/ मिश्रीभावे-निरु. ५,१५। आगधिता परिगधिता-ऋ. १,१२६,६।

ग—गदा-मभार. ९,५६;४५ (गदयति=पीडयत्यनया)=स्वनामख्यातलौह-मयास्त्रम्। (गदायते अश्वः-शब्रा. १२,४,१,१०)।

+√गन्ध् (गन्ध) १०/१५३ (श) च-जै×	अर्दने (आ) क्षी-मै-सा-काकृ-कात- शा-हे। द्रुहि—वो।	√गण्ड् (गडि) १/वदनैकदेशे (प)। गध्यति-निरु. ५,१५।

क—ग्उएध् =प्रेरणे, ताडने, पीडने।

ख—अवे. गन्तय्=दौर्गन्ध्यम्। म. पर्सि.; न. पर्सि. गन्द्=दौर्गन्ध्यम्; गन्दक् =पूतिगन्धि, मलिनम्। पु. पर्सि. गस्त=जुगुप्सितम्।

ग—गन्धो अस्ति-ऋ. १,१६२,१०। त्वं गन्धेन विनाशय-अ.वे. ८,६,१०। गन्धन०-सुश्रु. १,७७,९=हिंसा०। गन्धयति-अ. कौशि. सू. ११५। गन्धर्वः—ऋ. ९,८३,४।

ङ—गंध=वासः-औप.; भग., (२) देवजातिविशेषः-इक.।

छ—√गंधाना†=वासे, दौर्गन्ध्ये।

+√गर्ज् (गर्ज) १०/१०७ क्षी-सा-च-शा-हे×,श — शब्दे (प) मै-जै-काक्ठ। शब्दार्थे—कात। स्वने—वो। कलकलध्वनौ—काक्ठ। — √गर्ज् (गर्ज) १/ शब्दे (प)।

द्रष्ट.√गर्ज् (गर्ज) १/ शब्दे (प)।

+√गर्ज् (गर्ज) १०/१२५ मै-श-च-जै-काक्ठ-कात-शा× — शब्दे (प) इत्येके—क्षी-सा। — <√गर्द् (गर्द) शब्दे (प)।

+√गर्द् (गर्द) १०/१२५ मै-श-च-जै-काक्ठ-कात-शा× — शब्दे (प) क्षी-सा-हे। रवे—वो। — >√गर्ज् (गर्ज) शब्दे (प) इत्येके-क्षी।

छ—√गरदानना (फा.-गरदान)=शब्दरूपसाधने, (२) असकृत् कथने, अभ्यासे। गणने, अवगमने।

+√गर्ध् (गर्ध) १०/१२६ (श)च×(कात-√गर्द्) — अभिकाङ्क्षायाम् (प) क्षी-मै-सा-काक्ठ-कात-शा-हे। अभिकाङ्क्षणे—जै। लिप्से—वो। — √गृध् (गृधु) ४/ अभिकाङ्क्षायाम् (प)।

क—घेल्ध्=अभिकाङ्क्षायाम्। गॉथि. ग्रेदुस्=गर्धः (बुभुक्षा); पु. च. स्लावो. ग्लद=गर्धः-वा. पॉकर्नीः।

+√गर्व (गर्व) १०/३५१ श; (शा-√गर्व [गर्व])	माने (आ) क्षी-मै-सा-च-ज़ै-काकृ- कात-शा-हे। दर्पे—वो।	√गॄ ६/ निगरणे (प)। √गल्ट (गल) १/ अदने (प)।

ग—(स्तौति गर्वायते चापि-मभार. १२,१०३००)।

+√गर्ह (गर्ह) १०/२९२ श-च×	विनिन्दने (प) आधृषाद्वा। क्षी-मै-सा-जै-काकृ- कात-शा-हे। कुत्सने—वो। प्रयो. ह्वि.।	द्रष्ट.√गर्ह (गर्ह) १/ कुत्सने (आ)। √गल्ह (गल्ह) १/ कुत्सने (आ)।

ग—न गर्हयेयुरस्मान् वै-मभार. १,५७३१। दुष्कृतं कर्म गर्हति-मनु. ११, २२९=निन्दति (मन्वर्थ.)।

+√गल्ट (गल) १०/१५८ मै-श-च-जै-काकृ-कात- शा×	स्रवणे (आ) क्षी-सा। स्रावणे—हे। स्रावे—वो। प्रयो. ह्वि.।	√गल्ट (गल) १/ स्रवणेऽपि (प)। √गल्टं १/२४७ x गतौ (प) काकृ। √गल्ल्ट १/२४७ y गतौ (प) काकृ।

ग—तौ भागौ तत्कषायेण गालयेत्-सुश्रु. १, १६६, ६; अवीमूत्रगालितः-२, ५४, ९।

घ—(गळयति=अश्रुविमोचने-सुत्तनिपात ६९१)।

ङ—√गाल (सक)=(१) स्रावणे, (२) नाशे, (३) उल्लङ्घने। गालयइ-विसे. ६४।

+√गवेष (गवेष) १०/३३० श	मार्गणे (प) क्षी-मै-सा-च-जै-काकृ- कात-शा-हे-वो।	गो+√इष् >√एष्= √गवेष। √गेष् (गेषृ) १/ अन्वेषे (आ) वो। √ग्लेष् (ग्लेषृ) १/ अन्वि- च्छायाम् (आ)।

ग—गवां गवेषणपरा–ऋ. १,६,५ । गवेषते–शब्रा. १३,१,४,३। गवेषयन्–मभार. ३,१५५८ । गवेषय–कथासरि. २४,२३० ।

घ—गवेसति–धम्मपद १४६ (गवेस्सथ) ; थेरगाथा १,१८३ ।

ङ—√गवेस (सक)=मार्गणे । गवेसइ–महा. ।

+√गालोड (गालोडित) १०/३८९ ··········(प) >√कालोड (कालोडित)
श-जै-शा-हे-वो× इति गुप्तः—क्षी । अङ्कलोड्य–, >अङ्गलोड्य–, >गलोड्य–, >गालोड्य० ।

ग—"उन्मादशीले रोगार्त्ते मूर्खे गालोडितः स्मृतः"–इति दुर्गसिंहकृतकलापवृत्तिटीकायां त्रिलोचनदासः । गोलोहितोऽपि पाठः । (गाः=इन्द्रियाणि, आलोड्यन्तेऽनेनेति गालोडः सोऽस्त्यस्य) । गालोड्यम् =पद्मबीजम्–राजनिर्घ. । गालोडितम्=वाचां विमर्शः–पीटर्सब. ।

ङ—[कारोडिय (<करोटितः)=कापालिकः, (२) ताम्बूलवाहकः–औप.] ।

+√गुण (गुण) १०/३४० आमन्त्रणे (प) √कुण (कुण) १०/ आमन्त्रणे (प) ।
श-च-जै× क्षी-मै-सा-काकृ-कात-शा-हे । √गोण् १/२१३J गतौ (प) काकृ ।
मन्त्रे—वो ।

क—गेर्=वेष्टने, परिवर्तने । (*गृ–नो–स्)=गुणः ।

क—गेल्=दार्ढ्येन ग्रहणे–वा. पॉकर्नीः ।

ग—गुणयति–बृहत्सं. ८,२० । गोणी–यशस्ति. च., ३ आ., १९८ पृ.=चर्ममयाच्छादनम् ।

घ—गोण=उक्षा–जातक ६,५३८ ।

ङ—√गुण (सक)=गणने, (२) आवृत्तौ । गुणइ–सूक्त. ५१ । गुणेइ–उव. ।

छ—गून (<गुणः)=रज्जुः, यया नावाद्याकृष्यते । गूना—बुं. ख. ।

+√गुण्ठ् (गुठि) १०/४७ वेष्टने (प) √कुण्ठ् (कुठि) १०/ वेष्टने (प) सा ।
मै-सा-श-च-जै-काकृ-कात-शा× क्षी-हे । √कुण्ड् (कुडि) १०/ रक्षणे इत्येके–क्षी ।
वेष्टे—वो ।
प्रयो. आच्छादने—ह्वि. ।

√गुण्ड् (गुडिं) १०/ वेष्टने (प)।
√गुण्ठ् १/१२१ c शोषणे (प) च।
√गुण्ठ् १/१४४ आलस्ये (प) काकृ।

ग—कालपाशेन गुण्ठिताः-मभार. ६,८१९। तदवगुण्ठयाम्यात्मानम्-मृच्छ. ३३,१२।

घ—गुण्ठित-सुत्तनिपात १३१।

ङ—गुठिंअ=आच्छादितम्, व्याप्तम्-दे. १,८५।

छ—√ग्वैंठना*†
छ—√गुमेठना } (<गुण्ठनम्)=वेष्टने, परिवर्तने।

छ—√गोंठना=पक्वान्नादेः प्रान्तभागवेष्टने।

+√गुण्ड् (गुडि) १०/५० वेष्टने (प)
क्षी-श-च-जै-शा× मै-सा-काकृ-कात।
वेष्टने रक्षणे च—हे।
वेष्टे रक्षे च—वो।

√कुण्ठ् (कुठि) १०/ वेष्टने (प) सा।
√गुण्ठ् (गुठि) १०/वेष्टने(प)।
√गुण्ड् १/१८३n हिंसागत्योः (प) काकृ।

ग—गुण्डन०=गुण्ठन०-प्रबोधचन्द्रो. ३०,१७।

ङ—गुण्डण=धूलिलेपः-णाया. १, १-पत्र. ७१।

छ—गोंड़ा=गोष्ठम्, परिवेष्टितं स्थानम्।

+√गुण्ड् (गुडि) १०/४६ रक्षणे (प)
क्षी-सा।
वेष्टने रक्षणे च—हे।
वेष्टे रक्षे च—वो।

√गुड्(गुड) ६/ रक्षायाम् (प)।
√कुण्ठ् (कुठि) १०/ रक्षणे (प) सा।
√कुण्ड् (कुडि) १०/ रक्षणे (प) इत्येके—क्षी।

ङ—गुण्डिअ=आच्छादितम्, प्रावृतम्-आचा., प्रेरितम्-पण्ह. १,३।

छ—पूर्ववत्। वेष्टनेन रक्षणं सम्पद्यत इति वेष्टनपूर्वकरक्षणत्वादुभयोर्धात्वोरैक्यम्।

+√गुन्द्र् (गुद्रि) १०/६ मै-सा-श-च-जै-काकृ-कात-श×
अनृतभाषणे (प) पारायणे-क्षी। क्षी-हे। कुन्द्रे—वो।

<√कुन्द्र् (कुद्रि) अनृतभाषणे (प)। <√कुद् (कुद) अनृतभाषणे (प)। √कुण्ड् १०/१३ अनृतभाषणे (प) काकृ।

कुन्द्रः = मिथ्योक्तिः—दुर्गादासः।

ग—सगुन्द्राः काशाः कुशा वा—बृहत्सं. ५३,१०१, (१०२)। गुन्द्रः = वृक्षविशेष इति भावप्रकाशः (श.क.द्रु.)।

ङ—गुंद (<गुन्द्रः) = वृक्षविशेषः (पाअ.)

+√गुप् (गुपू) १०/२४० मै-सा-च-जै-काकृ-शा-हे-वो×,श
भासार्थः (प) क्षी। भाषार्थः—कात।

+√गुप् (गुप) १०/२३४ भाषार्थः—मै-सा-जै-काकृ। भासार्थः—शा-हे। भासि—वो।

√गुप् (गुपू) १/ रक्षणे(प)।

+√गुद् (गुर्द) १०/१२७ मै-श-च-काकृ-कात×
पूर्वनिकेतने (प) क्षी-सा-जै-शा-हे। निकेतने—क्षी-सा-हे-वो। निकेतने कूर्दे—वो।

गूर्द्धयति—निघ.३/१४=अर्चतिकर्मा।

पूर्वनिकेतनम् = आद्यनिवासः—क्षी। 'आसाद्याभ्यवहारः' इति क्षीरनाम्ना सायण उद्धृतवान्।

छ—गुर्द (फा.) = गुर्दस्थान-(गुर्दिस्तान)-निवासी।

छ—गुर्दिस्तान (<गुर्दस्थानम्) = फारसदेशस्य तस्मादुत्तरस्यां प्रदेशः, यस्यैषद्भागः सम्प्रति रूमराज्यान्तरायाति। कुर्दिस्तानत्वेनाप्ययमभिधीयते जनैः।

+√गूर् (गूरी) १०/१६३ मै-च-जै-काकृ-कात-शा-हे-वो ×,श
उद्यमे (आ) क्षी। उद्यमने—सा।

+√गूर् (गूर) १०/१५५ उद्यमने—मै-सा।

√गुर् (गुरी) ६/ उद्यमे (आ)।

उद्यमे—कात-हे-वो।
जै?

+√गुर् (गुरी) १०/१६० क्षी-मै-श-च-जै-कात-हे-वो×
'उद्यमने' क्वचित् पठ्यते—सा।
सा-शा।
तदात्रेयविरोधादुपेक्ष्यम्—सा।
उद्यमे—काक्र।

+√गृ १०/१७३ क्षी-मै-च-काक्र-हे-वो×, श
विज्ञाने (आ)
सा-कात।
विज्ञापने—जै-शा।
√कॄ १०/ विज्ञाने (आ)।
√गॄ १०/ विज्ञाने (आ)।

ग—द्रष्ट. √गॄ १०/१७५।

+√गृह (गृह) १०/३४३ श×(जै-√ग्रह् [ग्रहै]) स्यान्मुद्रणदोषः।
ग्रहणे (आ)
क्षी-मै-सा-जै-काक्र-कात-शा-हे।
प्रग्रहणे—च।
ग्रहे—वो।
√ग्रह् (ग्रह) ९/उपादाने (उ)।
√गृह् (गृहू) १/ ग्रहणे (आ)।
√ग्लह् (ग्लहू) १/ ग्रहणे (आ)।
√ग्रस् (ग्रस) १०/ ग्रहणे (प)।

+√गॄ १०/१७५ सा-श-च-जै-कात-शा×
विज्ञाने (आ)
क्षी-मै-काक्र-हे।
विज्ञाने विज्ञापे च—वो।
>कॄ (विज्ञाने (आ) इति चन्द्रः—क्षी।

छ—√गारना (वाक्शैली)=तपस्यायाम्। तपसश्च ज्ञानविज्ञाने भवतः—"तव तन गारि बहुत श्रम कीन्हों"—सूरदासः।

+√गोम (गोम) १०/३२३ श-च×
उपलेपने (प)
क्षी-मै-सा-जै-कात-शा-हे।
(उपक्षेपे—जै, मुद्रणदोषः)।
उपलेपे—काक्र।
लेपे—वो।

प्रकृतिप्रत्ययविभागस्य काल्पनिकत्वात् कस्मिंश्चित् काले गोमाद् गोमयसिद्धिः। अद्यत्वे तु-'गोश्च पुरीषे' (४/३/१४५) मयट्। एवं कुमारादावनुमन्तव्यम्-क्षी।

ग—गोमय०-ऋ. १०,६२,२=वसु०। हद०-वा.रा. २,६९,८। तासु गोमयानि च शुम्बलानि-शब्रा. १२,५,२,३।

छ—√ गूमना† = परिवेष्टने, वेष्टने।

+√ ग्रन्थ् (ग्रन्थ) १०/२६७ क्षी-श-च-जै-काकृ-शा-हे ×	बन्धने (प) आधृषाद्वा। मै-सा। बन्धने हिंसायां च—कात।	√ग्रथ् १०/३२८ बन्धने (प) जै;. १०/२४६ शा। ग्रथयति-सार. २७१:८। ग्रथनम्-महो. ३,११।
प्रयो.	ह्वि.।	
+√ ग्रन्थ् (ग्रन्थ) १०/२८५ श-च ×	सन्दर्भे (प) आधृषाद्वा क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। दर्भे—वो।	

ग्रन्थन्ति-सार. २७४:२।

+√ ग्रस् (ग्रस) १०/२१६ श-च-जै-शा ×	ग्रहणे (प) क्षी-मै-सा-काकृ-कात-हे। ग्राहे—वो।	√ग्रस् (ग्रसु) १/ अदने (आ)। √ग्लस् (ग्लसु) १/ अदने (आ)। √ग्रह् (ग्रह) ९/ उपादाने (उ)।
प्रयो.	ह्वि.।	

ग—ग्रासयति (प्रयो.)-शब्रा. १२,४,१,१२; कात्या. श्रौ. २५।

ङ—√ गाह (सक) = ग्रहणे। गाहेइ-औप.। √ ग्रह् इत्यनेनापि भवितुं शक्यते सम्बन्धः।

छ—√ ग्रासना (सक) = ग्रहणे, धारणे। "ग्रासत चित्त गयंद को"-रसनिधिः।

+√ ग्राम (ग्राम) १०/३३७ क्षी-श-च-काकृ-कात-हे-वो ×	आमन्त्रणे (प) मै-सा-जै।	√ग्राम १०/२२३ b आमन्त्रणे (प) काकृ। √ग्राम १०/२०४ b आमन्त्रणे (प) कात। √ग्राम १०/१७३ b आमन्त्रणे (प) शा। √ग्राम १०/३२८ आमन्त्रणे (प) हे, वो।

√ग्रस् (उणा. १/१४२) मन्; धातोराकारान्तादेशश्च ।

ग—ग्रामः-मभार. १३,१७,११३ । ग्रामेषु नगरेषु च-मनु. १०,५४ । क्षेत्रोपयोगभूमध्ये वसतिर्ग्रामसंज्ञिका-मार्क. पु. (श. क. द्रु.)।

+√घट् (घट) १०/१९१ च×,श	हन्त्यर्थः (प) क्षी-जै-शा-हे । 'सङ्घाते' इति दुर्गः— क्षी । क्षी-मै-सा-काकृ-कात । सङ्घाते हिंसे द्युतौ च—वो ।	√हन् (हन) २/ हिंसागत्योः (प)। क्ते-हत->घत-, >√घट् ।

ग—यन्त्रैरुद्घाटयामास-मभार. ३,१७१५८; कथासरि. ४,८०; १५,४३ । घटा=समूहः-कथासरि. १९,९ ।

ङ—√घड (सक)=(१) योजने, (२) निर्माणे, (३) सञ्चालने । भवि-घडिस्सामि-स. ३६४ ।

ङ—√घडाव (सक)=(१) निर्माणे, (नायं प्रयोजकः)। (२) निर्माणे (प्रयोज.)। घडावित्ता-आवम. ।

छ—√घालना=नाशे, विक्रियायाम्। "चित्रकेतु कर घर इन घाला"–तुलसी. ।

+√घट् (घट) १०/२२९ क्षी-च-जै-शा×,श	भाषार्थः (प) मै-सा-काकृ-कात । भासार्थः—हे । द्युतौ—वो ।	√घण् ८/१३ घण्टानादे (उ) काकृ । √घण्ट् (घटि) १०/ भासार्थः (प)। √घण्ट् १/११२ निर्णये ? (प) काकृ ।
+√घट्ट् (घट्ट) १०/९१ श×	चलने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । चाले—वो । प्रयो. घर्षणादौ—ह्वि. ।	√घट्ट् (घट्ट) १/ चलने (आ)। √घुट्ट् १/४३१ चलने (आ) काकृ ।

ग—घट्टयति–मभार. १२,१४१,४५=चालयति (नील.); घट्टयन्तः–६,६४,८५=स्पृशन्तः (नील.);घट्टयन्ती–४,२०,२८=कम्पयन्ती (नील.)। विश्लिष्टं सन्धिं वैद्यो न घट्टयेत्–सुश्रु. २,२८,४; घट्टयन् विपचेत्–२,८८,१९।

घ—घट्टेति–मज्झिम. २,४; सुत्तनिपात ४८।
ङ—√घट्ट (सक)=चालने–दस. ५,१,३०।

+√घण्ट् (घटि) १०/२३४ च×,श
भासार्थः (प) भाषार्थः—मै-सा-जै-काकृ-कात। द्युतौ—वो।
पूर्ववत्।

ग—घण्टाम्–मार्क. पु. ८२,२१ (घण्टयति=दीप्यते, पूजादिकाले वाद्येन शोभते, घण्टयति शब्दायते वा)।
घ—घण्टा–जातक ४,२१५।

+√घर् (घर) १०/१०९ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×
स्रावणे (प) इति दुर्गः–क्षी। क्षी। प्रयो. ह्वि.।
<√घृ स्रावणे (प)। √घृ ३/ क्षरणदीप्त्योः (प)। √गल् (गल) १/ स्रवणेऽपि (प)। √घरट्ट् १/११४ हिंसायाम् (प) काकृ।

ग—आज्येनाभिघारितः–अ.वे. ५,२१,३।

√घुष् (घुषिर्) १०/१९४ श
विशब्दने (प) क्षी-मै-सा-च-कात-शा-हे। विशब्दे—जै-काकृ। 'अविशब्दने' इत्येके—क्षी। हुतौ विशब्दे—वो।
√घुष् (घुष)........ 'विशब्दने' इति कौशिकः—क्षी।
प्रयो. ह्वि.।
द्रष्ट. √घुष् (घुषिर्) १/६४४ शब्दार्थः।

विशब्दनम्=विशिष्टशब्दकरणम्—क्षी।

ग—घोषयः–ऋ. ९,१०८,३। घोषयत्–जै. १,५९,६। घोषयन्–कौ. १,५८३। इति स द्रुपदो राजा स्वयंवरमघोषयत्–मभार. १,६९५६।

घ—घोसेति-('घोस' इत्यस्य नामधातुः !?) जातक २,११२ ; पेतवत्थु २,९ ।

√घृ १०/११० स्रावणे (प) >√घट् (घर) स्रावणे-द्रष्ट. ।
च-काक्ट-कातX,श क्षी-हे ।
सम्प्रस्रवणे—मै-सा ।
सेचने—जै ।
स्रवणे—शा ।
'आवरणे' इति पूर्वे पेठुः—क्षी ।
क्षी-हे ।
सेके छादने—वो ।
प्रयो. —ह्वि. ।

ग—अभिघारयति-तै. २,६,१,६ ; क. ४७, ७ ; मै. ३,१०,२ ।

ग—व्याघारयति (=बघारता है-हि.)-शब्रा. २,४,४,२४ ; काब्रा. १,३,४,१४ ।

ङ—√घार (अक)=(१) विषप्रसरणे, विषव्याप्त्या व्याकुलतायाम्, (२) सक-विषेण व्याकुलीकरणे, (३) विषेण घातने । कर्म-घारिज्जंतो य तओ विसेण-स. १८९ । हेक्ट-घारिज्जिउँ-स. १८९ ।

+√चक्क् (चक्क) १०/५९ व्यथने (प) >√चिक्क् (चिक्क) व्यथने (प) ।
श (काक्ट-√चष्क्) क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे ।
अर्तौ—वो ।
√चक्क् १/४११ b तृप्तौ प्रतिघाते च (आ) काक्ट ।

ग—चक्क०-पञ्चविं. ब्रा. २५,१५ (इन्दिशे स्तूदियन् १,३५ । पीटर्सबर्गकोशे) ।

+√चट् (चट) १०/१८९ भेदे (प)
चX,श क्षी-काक्ट-कात-हे ।
भेदने—मै-सा ।
अन्ये तु आस्फुटौ=आस्फोटने चुरादिरिति व्याख्यन्—
क्षी-, शा ?
वधे भेदे च—वो ।
१/....... गतौ—ह्वि. ।

√चट् (चटे) १/ वर्षावरणयोः (प) सा ।
√चट् १/१०९a प्रैष्ये माने च (प) ।
√कड् १०/३८० भेदे (प) काक्ट ।

ग—चट-चट—वज्रपञ्जरो. ३१२,५। विचटत्-यशस्ति. च., १ आश्वा., १८ श्लो.। विचटन्ती=स्फुटन्ती। सहसोच्चचाट सैव देवी-भा. पु. ५,९,१८। उच्चाटयन्-भर्तृ. ३,९।

[ङ—√चढ (सक)=आरोहणे-सम्मत्त. १५९।]

छ—√चटकना (<चटनम्)='चट' इति शब्दं कृत्वा स्फोटने, भेदने।

छ—√छँटना (<चटनम्=छेदने)=शकलीभूय पार्थक्ये, (२) विकिरणे, (३) साहचर्यत्यागे।

+√चण्ड् (चडि) १०/५०	कोपे (प)	√चण्ड् (चडि) १/ कोपे (आ)।
सा-श-च-जै-काकृ-	क्षी-मै।	√चण्ड् १/१७४ तैक्ष्ण्ये (प) काकृ।
कात-शा-हे×	रोषे—वो।	

√चप् (चप) १०/८८	कल्कने (प) इति	<√चह् (चह) कल्कने (प)।
श-च-जै-शा-हे×	चन्द्रः—क्षी।	
	क्षी-मै-काकृ-कात।	
	परिकल्कने—सा।	
	कल्के—वो।	

+√चम्प् (चपि) १०/८२	गत्याम् (प)	√छम्प् (छपि) १०/८२ गत्याम् (प)।
क्षी, श?,-च-जै-काकृ-	मै-सा।	√कम्प् (कपि) १/ चलने (आ)।
कात-शा-हे-वो×		

ग—अद्यापि तां कनकचम्पकदामगौरीम्—चौरपञ्चा. १।

छ—√चाँपना=पीडने; अतिभारेण विनामने। चापशब्दादपि व्युत्पत्तिः, सा न मनोरमा।

छ—√झाँपना=आच्छादने। 'झाँपवुं' इति गौर्जरी भाषा।

+√चर् (चर) १०/२०५	संशये (प)	√चर् (चर) १/ गत्यर्थः,
च×,श	क्षी-मै-सा-जै-शा-हे।	भक्षणेऽपि (प)।
	(संश्रये—जै, मुद्रणदोषः)	√चल् (चल) १/कम्पने (प)।
	'असंशये' इति दुर्गः—	√चल् (चल) १०/ भृतौ (प)।
	क्षी।	
	क्षी-काकृ-कात-हे।	
	संशीत्यसंशीत्योः—वो।	

छ—√चराना=प्रवञ्चने।

+√चर्च् (चर्च) १०/१८० श
अध्ययने (प) क्षी-मै-सा-च-जै-काक्ठ-कात-शा-हे-वो ।
√चर् (चर) १/ गत्यर्थः, भक्षणेऽपि (प) ।

प्रयो. —ह्वि. ।

ग—चर्चयति-ऋ. प्राति. १५,१०,१२ (=अध्ययने)। चर्चित०-देवीमा. ११,१८ (=लिप्त०)। अङ्गचर्चामरचयम्-कादम्ब. १५७ (मुम्बा. सं.)।

ङ—√चच्च (सक)=चन्दनादिविलेपने। चच्चेइ-धर्मवि. १५।

ङ—√चप्प (सक)=(१) अध्ययने, (२) कथने, (३) भर्त्सनायाम्, (४) चन्दनादिविलेपने। चप्पइ-संक्षि. ३५।

छ—√चरचना (<चर्चनम्)=चन्दनादिलेपने।

छ—√चरजना* (<चर्चनम्)=अनुमाने।

+√चल् (चल) १०/७३ मै-श-च-जै-काक्ठ-कात-शा ×
भृतौ (प) क्षी-सा-हे-वो ।
द्रष्ट.√चर् (चर) १०/ संशये (प)। √चल् (चल) ६/ विलसने (प)।

ग—चालय-पै. ५,३४,७। चालयेत्-काठ. २८,४।

+√चह् (चह) १०/८८ मै-(श)-च-जै-काक्ठ-कात-शा-हे ×
कल्कने (प) मित् क्षी। परिकल्कने—सा। शाठ्ये—वो।
√चह् (चह) १/ कल्कने (प)। √चह (चह) १०/ कल्कने(प)।

+√चह (चह) १०/३१३ श-च ×
कल्कने (प) क्षी-हे। परिकल्कने—मै-सा-जै-काक्ठ-कात-शा। शाठ्ये—वो।
√चह् (चह) १/ कल्कने (प)। √चह् (चह) १०/कल्कने (प)।

कल्कनम्=दम्भः—क्षी।

+√चि (चिञ्)१०/९० मै-श-च-जै-काक्ठ-कात-शा × (हे ५/५ इत्यत्र स्मरति)
चये (उ) मित्—क्षी। चित्याम्—वो। चयने—सा-हे।
√चि (चिञ्)५/ चयने (उ)।

ञित्त्वमनित्यण्यन्तत्वे लिङ्गम्—क्षी।

ग—चयते-ऋ. १,१६७,८; ऐआ. २,७ [चयने, हिंसायाम् इति विवेकः ।]

+√चिक्क् (चिक्क) १०/६० व्यथने (प.) <√चक्क् (चक्क) व्यथने (प)।
मै-श-च-जै-काक्र- इति कौशिकः—
कात-शा× क्षी।
क्षी-सा-हे।
अतौ—वो।

छ—चिक्का=प्रस्तरशकलम्। तद् भवति व्यथनाय।

+√चित् (ञित) १०/१४३ संज्ञाने (आ) √चित् (चिती) १/संज्ञाने(प)।
च×,श क्षी-मै-सा-काक्र। √चिन्त् (चिति) १०/ स्मृत्याम् (प)।
संवित्तौ—जै।
संवेदने—कात-शा-हे।
ज्ञाने—वो।
प्रयो. —ह्वि.।

ग—चेतयते-शब्रा. ८,५,४,३; तैब्रा. २,१,२,३; छान्दोग्यो. ७,५,१।

ङ—√चेअ (सक)=(१) चेतनायाम्, (२) स्मृतौ-चेयइ-स. ५३८, (३) ज्ञाने, (४) अनुभवे—चेयए-आवम.; (५) दाने, (६) निर्माणे। चेएइ-आचा.; सम. ५१।

छ—√चेतना=ज्ञाने, विचारणे। √चिन्त् १०/२ इत्यस्मादस्य व्युत्पत्ति-कल्पना न युक्ता।

+√चित्र (चित्र) १०/३६० चैत्रस्य करणे (प) √चि (चिञ्) ५/चयने(उ)।
श-च×(जै-शा) क्षी। चित्रं चायनीयं मंहनीयं धनम्-निरु. १२,६,१।
चित्रीकरणे कदाचिद् दर्शने च—मै।
चित्रकरणे—सा।
विचित्रदर्शनयोः—काक्र।
विचित्रीकरणे कदाचिद् दर्शने—कात।
(जै-शा—√चित्र्)... चित्रकरणे कदाचिद् दर्शने च—जै-शा।
वैचित्र्यकरणार्थः—हे।
चित्रस्य=आलेख्यस्य करणे—क्षी।
चित्रकरणे=आलेख्यकरणे—सा।

√चित्र (चित्र) १०/३६१ कदाचिद् दर्शने (प) क्षी।
अद्भुतदर्शने—क्षी-सा।
क्षणिकेक्षणे लेख्ये—वो।

क—(स्) काइ (-त्-,-द्)=दीप्तम्, स्पष्टम्।
ख—अवे. चिथ्र=स्पष्टम्, दीप्तम्—वा. पॉकर्नीः।
ङ—√चित्त (सक)=चित्रणे। चित्तेइ—महा.।
छ—√चितरना*(<चित्रणम्)=चित्रणे।
छ—√चीतना (<चित्रणम्)=चित्रणे।

√चिन्त् (चिति) १०/२ स्मृत्याम् (प) क्षी-मै-सा-च-काक्ष-कात-शा-हे। स्मरणे—जै। स्मृतौ—वो। प्रयोज. —ह्वि.।
शः
√चित् (चित) १०/ संज्ञाने (आ)।

क—कुआइ=परीक्षणे। कुआइत् (च्वाइत्)-: वा. पॉकर्नीः।

ग—चिन्तयति-मैत्र्यु. ४,४; गर्भो. ३। चिन्तयेत्-गोब्रा. १,१,३०; मनु. ७,५६=निरूपयेत् (मन्वर्थ.)। चिन्ताम्-गोब्रा. १,१,१६।

घ—चिन्तेन्तो; चिन्तयन्तो-सुत्तनिपात ८६४।

ङ—चिंत=(१) चिन्तने, विचारणे, (२) स्मृतौ, (३) ध्याने, (४) चिन्तायाम्, पश्चात्तापे। चिंतेइ-उव.; कुमा.।

छ—√चिंतना*=(१) चिन्तने, ध्याने, स्मरणे, (२) विचारणे, मनने।

+√चीक् (चीक) १०/२७० च=आमर्षणे (प) आधृषाद् वा। मै-सा-जै-काक्ष-कात-शा-हे। मर्षणे—वो।
क्षी-श-च×
√शीक् (शीक) १०/ आमर्षणे (प) आधृषाद् वा।

+√चीव् (चीव) १०/२४३ भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काक्ष-कात। दीप्तौ—वो।
च×, श
√चीव् (चीव) १/ आदानसंवरणयोः (उ)।

√चुक्क् (चुक्क) १०/६० श (काक्र–√चुष्क्)	व्यथने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे । अतौं—वो ।	<√चिक्क् (चिक्क) व्यथने (प) इति च कौशिकः—क्षी । √चक्क् (चक्क) व्यथने (प) ।
+√चुट् (चुट) १०/७७	छेदने (प) इति चन्द्रः—क्षी ।	<√छुट् (छुट) छेदने (प) ।
√चुट् (चुट) १०/११९ श	छेदने (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे । छेदे—वो ।	>√चुण्ट् (चुटि) छेदने (प) ।

ग—(उच्चोटनम्-क्षी) ।
छ—√चुटयाना=आच्छेदने-बुं. ख. ।
[छ—चोंटिया (<छोटिका)—बुं.ख.] ।

+√चुट्ट् (चुट्ट) १०/२४ श-च×(कात-√छुट्ट्)	अल्पीभावे (प) क्षी-मै-सा-जै-काक्र-शा-हे । तुच्छने—वो ।	>√पुट्ट् (पुट्ट) अल्पीभावे (प) इत्येके—क्षी । √चुट् (चुट) १०/ छेदने (प) । √चुण्ट् (चुटि) १०/ छेदने (प) । √चुण्ड् (चुडि) १०/ छेदने (प) ।
+√चुण्ट् (चुटि) १०/११९ च-कात×,श	छेदने (प) इति नन्दी—क्षी । क्षी-मै-सा-जै-काक्र-शा-हे । छेदे—वो ।	पूर्ववत् ।

छ—√चोंटना=छेदने-बुं. ख. ।

+√चुण्ड् (चुडि) १०/११९ सा-श-च-जै-काक्र-शा×	छेदने (प) इति दुर्गः—क्षी । क्षी-मै-कात-हे-वो । छिदि—वो ।	<√चुट् (चुट) छेदने (प) √चुण् (चुण) ६/९१ a छेदने (प) काक्र, कात-हे ।

शेषः पूर्ववत्।

+√चुद् (चुद) १०/५६ संचोदने (प) क्षी-मै-सा-च-जै-काकृ-शा-हे।
श
संनोदने—कात।
१/ प्रयो. —ह्वि.।
सञ्चोदनम्= प्रेरणम्—क्षी।

√चुड्ड् (चुड्ड) १/ हावकरणे (प)।
√चुन्द् १/६०० निशाने (उ) च।

क—(स) कॉइद् [चॉइद्]=प्रेरणे, क्षेपणे।

ख—न. पर्सि. चुस्त्=स्फूर्तियुक्तम्, तीव्रम्, व्यस्तम्-जू. पॉकर्नीः।

ग—चोदते-ऋ. ९,६९,२; कौ. २,७२१; जै. ३,५९,१३। चोदत्-तैब्रा. २,८, ५,८। चोदयामि-शौ. ३,१५,१। चोदयामास-रघु. ४,२४=प्रेरयामास (संजी.)।

घ—अचोदयि-जातक ५,११२।

ङ—√चोअ (सक)=(१) प्रेरणे, (२) कथने। चोएइ-उव.; स. १५।

ङ—√चोए (सक)=(१) प्रश्ने, (२) शिक्षणे (प्रयो.)। चोएइ; चोएह-वव. १।

छ—√चोदना (सक)=यभने।

+√चुम्ब् (चुबि) १०/९४ हिंसायाम् (प) क्षी-श-च-जै-काकृ-कात- मै-सा।
शा-हे-वो×

>√चुम्भ् (चुभि) हिंसायाम् (प) इत्येके-मै।
√चुब् १/२०६ n मर्दने (प) काकृ।
√चुम्ब् १/२०६ m मर्दने (प) काकृ।
√चुण्ड् १/१८३ g हिंसायाम् (प) काकृ।

√चुम्भ् (चुभि) १०/९४ हिंसायाम् (प) क्षी-सा-श-च-जै-काकृ-कात- इत्येके—मै शा-हे-वो× मै।
छ—√चुभोना=छेदने।
[छ—√चूंथना=विदारणे।]

<√चुम्ब् (चुबि) हिंसायाम् (प)।
शेषः पूर्ववत्

+√ चुर् (चुर) १०/१ श — स्तेये (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। — उत्तरधातुर्द्रष्टव्यः।

यौगिको धातुः '' —ह्वि.।

ग—चोरभयम्-खि. ७,७,१०। यश्चाग्निं चोरयेद् गृहात्-मनु. ८,३३३। अचूचुरच्चन्द्रमसोऽभिरामताम्-शिशु. १,१६।

+√ चुल् (चुल) १०/६८ क्षी-जै-काकृ-कात-शा-हे-वो ×, श — समुच्छ्राये (प) मै। मै-सा। निमज्जने—च

√ पुल् (पुल) १/ महत्त्वे (प)।

√ पुण् (पुण) ६/ कर्मणि शब्दे च (प)।

√ चुल् (चुल) १/२४३ a द्रावकरणे पाकाग्निकुण्डे च (प) काकृ। अग्निना चोपचूलनम्-मनु. ११,१९९ [१० प्रक्षिप्तश्लो.]

√ चुल्ल् (चुल्ल) १/ हावकरणे (प)।

ग—चोलकम्-यशस्तिल. च., ३ आ., ४३९ पृ.=परिधानधौतवस्त्रम्। ममौ स भद्रं चुलुके समुद्रः-नैष. ८,४५।

√ चुलुम्प् (चुलुम्प) १०/३८५ मै-श-च-जै-काकृ-कात-शा-हे × — लोपे (प) (क्षी-सा)-वो।

√ लुप् (लुप्लृ) ६/ छेदने (उ)।

नो गणनिर्देशः— शोषणे—ह्वि.।

ह्वि. सेण्टपीटर्सबर्गकोशोद्धृतं महावीरचरितप्रयोगं प्रमाणत्वेनोपन्यस्यति। एकलमेवोदाहरणं च प्रमाणयति। मया यशस्तिलकचम्प्वामन्यदप्युदाहरणमधिगतम्-उच्चुलुम्पन०-यशस्ति. च., १ आश्वा., ६८ पृ.=उच्चुण्टन०। उच्चुलुम्पन्त्यपो ये-महावीर. ५,८।

+√ चूण् (चूण) १०/१०१ मै-सा-च-जै-शा ×, श (काकृ-√ चुण्) लैपिकी त्रुटिः। — संकोचने (प) क्षी-कात-हे। संकोचे—काकृ-वो।

>√ चूर्ण् (चूर्ण) संकोचने (प)।

√ तूण् (तूण) संकोचने इति चन्द्रः—क्षी।

व्याख्यायाम्—चूणय-
तीति।

√कूण् (कूण) १०/ संको-
चने (आ)।

+√चूर्ण् (चूर्ण) १०/१९ प्रेरणे (प)
श-च×
क्षी-मै-सा-जै-काकृ-
कात-शा-हे।
'पेषणे' इति चन्द्रः—क्षी।
पेषे—वो।
प्रेरणम्=दलनम्—क्षी।

√चूरी् (चूरी) ४/ दाहे (आ)।

ग—चूर्णयित्वा-बृहज्जाबालो. ३,२८।
घ—चुण्णयति=चूर्णने-विनय. २,१०७; जातक ४,४५७।
ङ—√चूर=दलने। चूरेमि-धम्म. ९ टी.।
छ—√चूरना † * (<चूर्णनम्)=पेषणे, दलने, (२) त्रोटने।

+√चूर्ण् (चूर्ण) १०/१०१ संकोचने (प)
श-च-काकृ-कात-
हे-वो×
इत्येके—क्षी।
क्षी-मै-सा-जै-शा।

<√चूण् (चूण) संकोचने
(प)।

+√चृत् (चृत) १०/२६९ संदीपने (प)
मै-सा-श-च-जै-काकृ-
कात-शा×
(सा-√चृप् [चृप])
(सा-√छृप् [छृप])
इत्येके-क्षी।
क्षी-हे-वो।
सा।
सा।

<√तृप् (तृप) संदीपने (प)
आधृषाद्वा।
√छृद् (छृद) संदीपने (प)
इत्येके-क्षी।
√चृत् (चृती) ६/ हिंसा-
ग्रन्थनयोः (प)।

+√चृप् (चृप) १०/२७९ संदीपने (प) इति
क्षी-मै-श-च-जै-काकृ-
कात-शा-हे-वो×
क्षीरस्वामी—सा।
सा।

<√छृद् (छृदी) संदीपने
(प)।
√छृप् (छृप) संदीपने
(प) सा।
√तृप् (तृप) संदीपने
(प) सा।

+√च्यु १०/२०६ सहने (प) √च्यु (च्युङ्) १/ गतौ
शा-च×(काकृ- क्षीः सा-जै-शा-हे। (आ)।
√च्यव्) हसने—क्षी-मै-सा-
काकृ-कात-हे।
हसे सहने—वो।

? ग—च्यावयति-अ. वे. १०,१,१३।

+√च्युस् (च्युस) १०/२०६ सहने (प) इत्येके—क्षी <√च्यु सहने (प)।
मै-श-च-जै-काकृ- क्षी-सा।
कात-शा-हे× 'हसने' च इत्येके—
क्षी-सा।
हानौ—वो।

√छद् (छद) १०/४१ संवरणे (प) √छन्द् (छदि) १/ संवरणे
मै-श-च-वो× क्षी-सा-जै-काकृ- (प) मै।
कात-शा-हे।
प्रयोज. —ह्वि.।

ग—मर्माणि ते वर्मणा छादयामि-ऋ. ६,७५,१८। अग्निमन्तश्छादयसि-अ.वे. ९,३,१४।

घ—छादेति-विनय. २,१११।

ङ—छाजन (<छादनम्)=वस्त्रम्। "छाजन भोजन प्रीति सों दीजै साधु बुलाय"-कबीरदासः।

√छद् (छद) १०/२७२ संवरणे (प) आधृषाद्वा
श× क्षी।
अपवारणे—मै-सा (उ),-
च-जै-काकृ-कात-शा-हे।
संवृतौ (उ)—वो।
१/ प्रयो.—ह्वि.।

क—स्कुद्=आच्छादने। पु. उ. ज. हाज्; म. उ. ज. हएजे=कूटम् (=coat); चण्डातकम्।

ख—अवे. सादयन्ती=कूटम्, चण्डातकम्-जू. पॉकर्नीः।

ग—छदति, ते-ह्वि.। मया नोपलब्धम्। छादयति-शत्रा. ३,५,१,३६। आच्छत्-मा. १५,४; का. १६,१,४।

च—√छाय (सक)=आच्छादने। वक्त-छायंत-पउम. ७,१४।

+√छद (छद) १०/३८१ अपवारणे (प)
मै-श-च-जै-काक्ट- क्षी-सा।
कात-शा× संवरणे—हे।
संवृत्तौ—वो।
प्रयोज. संवृतौ, प्रसादे—ह्वि.।

√छद् (छदिर्) १/ ऊर्जने (प) मित्।
शेषः पूर्ववत्।

ग—एतद् देवेभ्यश्छदयति यत् कृष्णाजिनम्–ऐब्रा. १,३०; छान्दोग्यो. १,४,२।

+√छन्द् (छदि) १०/४३ संवरणे (प)
क्षी-जै-काक्ट-कात-शा- मै-सा-च।
हे-वो×,श
१/ प्रयोज. प्रतीतौ, प्रसादे–ह्वि.।

छन्दति–निघ. ३/१४= अर्चतिकर्मा।

ग—छन्दयति–शांआ. ११,३; दैब्रा. ३,१९। (छन्त्सि–ऋ. १,१६३,४; तै. ४,६,७,२। छन्दति–ऐआ. १,१,३) तस्मादुपच्छन्दयति–रघु. ५,५८=प्रार्थ्यमाने (संजी.)।

ङ—√छंद (सक)=(१) वाञ्छायाम्, (२) अनुज्ञायाम्, (३) निमन्त्रणे। कवक्त–छंदिज्जंताविं–उव.। संक्त–छदिअ–दस. १०।

छ—√छाँदना=रज्ज्वादिना दृढं बन्धने।

+√छम्प् (छपि) १०/८२ गत्याम् (प)
मै-सा-श-च-जै× क्षी-शा।
गतौ—काक्ट-कात-हे।
सर्पे—वो।

√क्षम्प् (क्षपि) १०/ क्षान्त्याम् (प)।
√चम्प् (चपि) १०/ गत्याम् (प) मै।
√छम्ब् (छबि) १०/८० गत्याम् (प) जै।

छ—√झाँपना (<छम्पनम्)=(१) आच्छादने, निलयने, (२) उत्कूर्दने, (३) आक्रमणे, (४) लज्जायाम्। 'झाँपवु'–इति गुर्जरभाषा।

छ—√झूमना=इतस्ततो दोलने।

+√छर्द् (छर्द) १०/५३ वमने (प)
च×,श क्षी-मै-सा-जै-काक्ट-
कात-शा-हे-वो।
प्रयोज. —ह्वि.।

√छृद् (उच्छृदिर्) ७ दीप्तिदेवनयोः (उ)।
√छृद् १०/२४१ वमने (प) शा; २९८ हे,-वो।

क—स्क्रेर=विष्ठा; कुज्झटिका, असारपदार्थः; प्रलापे। म. इरि. श्वेर्दिम् =निष्ठीवने, वमने। पु. बुल्गा. स्करेन्द=घृणितम्, पूतिगन्धि-वा. पॉकर्नीः।

ग—छर्दयन्ति-शब्रा. १२,४,२,९। यः सोमं पीत्वा छर्दयेत्-लाश्या. ८,१०,९। छर्दयन्ति च मानवाः-मभार. ५,९६,४२।

ङ—√छड्ड (सक)=(१) वमने, (२) त्यागे, (३) पातने। छड्डइ-महा.; उवा.।
छ—√छाँड़ना*†=त्यागे।
छ—√छाडनां } =वमने।
छ—√छाड़ना† }

+√छल (छंल) १०/ प्रवञ्चने (उ)?
अपाणिनीयः

ग—छलितुम्-वा. रा. ६,८६,१३। छलयिष्यति-मभार. ३,१५५६०। द्यूतं छलयतामस्मि-गी. १०,३६। शैवालळोलान् छलयन्ति मीनान्-रघु. १६,६१ =प्रादुर्भावयन्ति (संजी.)।

छ—√छल (सक)=प्रवञ्चने। छलिज्जेज्जा-स. २१३।
छ—√छलना=प्रतारणे।

+√छिद्र (छिद्र) १०/३६८ च×, श (जै-शा-√छिद्र्)	भेदे (प) क्षी-कात-शा-हे-वो। भेदने—मै-सा। 'करणभेदे' इति गुप्तः —क्षी,-सा। कर्णभेदने—सा। कर्णभेदे—जै-काक्र।	√छिद् (छिदिर्) ७/ द्वैधीकरणे (उ)। √छेद (छेद) १०/ द्वैधीकरणे (उ)। √छिद्+"स्फायि०" उणा. २/१३ रक्।
√छुट् (छुट) १०/७७ मै-सा-श-च×	छेदने (प) क्षी-जै-काक्र-कात-शा-हे। छेदे—वो। प्रयो. —ह्वि.।	√छुट् (छुट) ६/ छेदने (प)।

ग—छोटिकाभिर्दशदिग्बन्धनं कृत्वा-तन्त्रसारः। छोटिका=तर्जन्यङ्गुष्ठाङ्गुलिध्वनिः।

ङ—√छोड (सक)=बन्धनमुक्तौ। छोडइ, छोडेइ-भवि.; महा.।

+√छृद् (छृद) १०/२६९ मै-श-च-काकृ-कात×	संदीपने (प) इत्येके —क्षी। आधृषाद्वा। क्षी-सा-जै-शा-हे। संदीपे—वो।	<√चृत् (चृत) संदीपने (प)। <√तृप् (तृप) संदीपने (प)।
√छृद् (छृदी) १०/२६२ क्षी-च-जै-शा-वो×	संदीपने (प)-मै,-सा-कात-हे। संदीपे—काकृ।	

+√छृप् (छृप) १०/२७९ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	संदीपने (प) क्षीर-स्वामिनस्तु—सा।	<√छृद्(छृदी) संदीपने (प) सा। <√चृप्(चृप) संदीपने (प) सा।

+√छेद (छेद) १०/३८० च×, (श-च्छिदिर्)	द्वैधीकरणे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। छेदे—वो।	√छिद् (छिदिर्) ७/ द्वैधी-करणे (उ)।
प्रयोज.	—ह्वि.।	

ग—छेदयति-शाङ्खा. श्रौ. १७,१,८; गोगृ. ४,२,९। द्वावोष्ठौ छेदयेन्नृपः -मनु. ८,२८२; छेदयेल्लवशः क्षुरैः-८,२९२।

ङ—√छेअ (सक)=छेदने (अप्रयोज.), (२) छेदने (प्रयोज.)। कर्म—छेइज्जंति-पि. ५४३।

छ—√छेड़ना=(१) स्पर्शे, (२) विलेखने, खनने।

+√जंस्(जसि) १०/१२८ च×,श	रक्षणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। रक्षे—वो।	

+√जभ् (जभ) १०/१८४ मै-श-च-जै-काकृ-कात-शा-वो×	नाशने (प) इति चन्द्रः—क्षी। क्षी-सा-हे।	>√जम्भ् (जभि) नाशने (प)।
प्रयो.	—ह्वि.।	

ग—हनू वृकस्य जम्भय-अ.वे. १९,४७,९। अजीजभम्-शौ. ७,५६,५।

+√जम्भ् (जभि) १०/१८४ नाशने (प)
च×, श
क्षी-मै-सा-जै-कात-शा-हे ।
नाशे—काक्र ।
नशि—वो ।
प्रयो. —ह्वि. ।

>√जभ् (जभ) नाशने (प) ।

ग—जम्भयन्तः—ऋ. ७,३८,७; मा. ९,१६; तै. १,७,८,२; शब्रा. ५,१,५,२२ । जम्भयन्ति—पै. १७,१२,५ ?

+√जल्(जल) १०/१० अपवारणे (प)
च×, श
क्षी-मै-सा-जै-काक्र-कात-शा-हे ।
पिधाने—वो ।

>√लज् (लज) अपवारणे (प) इति नन्दी—क्षी ।
√जल्(जल) १/ घात्ये (प) ।
जलम्, जलाषम्-निघ.१/१२ =उदकनामनी ।
जालं जलचरं भवति जलेभवं वा जलेशयं वा—निरु. ६,२७,१ ।

ग—जालान्तरप्रेषितदृष्टिरन्या—रघु. ७,९ ।

√जस् (जसु) १०/१३१ हिंसायाम् (प)
च×, श
क्षी-मै-सा-जै-काक्र-कात-शा-हे ।
वधेऽनादरे—वो ।
हिंसार्थः—हे ।
प्रयो. ह्वि.. ।

√जस्(जसु) ४/ मोक्षणे (प) ।
√जह् १/३१६ m हिंसागत्योः (प) काक्र ।
जसति—निघ. २/१४= गतिकर्मा ।

ग—जासयति—शब्रा. २,२,२,१९ । अजीजसः—पै. ४,१६,७ । निजौजसोज्जासयितुं जगद्द्रुहाम्—शिशु. १,३७ ।

+√जस् (जस) १०/१८६ ताडने (प)
मै-सा-च×, श
क्षी-जै-काक्र-कात-शा-हे ।
वधेऽनादरे—वो ।

√जस् (जसु) १०/ हिंसायाम् (प) ।
शेषः पूर्ववत् ।

√जस् (जसु) १०/१७७ ताडने (प) मै,-सा ।
क्षी-श-च-जै-काक्र-कात-शा-हे-वो×
प्रयो. —ह्वि. ।

ग—जजस्तम्—ऋ. ४,५०, [११; ७,९७,९] शेषः पूर्ववत् ।

+√जुञ्ज् (जुचि) १०/२५८ भाषार्थः (प) स्वामि-काश्यपमतानुसारेण—सा ।
क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×
√तुञ्ज् (तुजि) १०/२२ भाषार्थः (प) सा ।

+√जुड् (जुड) १०/१०६ प्रेरणे क्षी-मै-सा-च-जै-कात-शा-हे । नोदे—वो । व्यभिचारे—काकृ ।
श
√जुड् (जुड) ६/ बन्धे (प) ।
√जुड् (जुड) ६/ गतौ (प) इति दुर्गः-क्षी ।

+√जुष् (जुष) १०/२८१ परितर्पणे (प) क्षी-मै-जै ।
श-च×
परितर्कणे—सा-कात-शा-हे । परितर्के—काकृ । तर्कतृप्त्योः—वो ।
प्रयोज. —ह्वि ।
√जुष् (जुषी) ६/ प्रीतिसेवनयोः (आ) ।
√जुष् १/२९२ हिंसायाम् (प) काकृ ।

ग—जोषयेत् सर्वकर्माणि—गी. ३,२६ ।
छ—√जोखना (<जोषणम्=परितर्कणे)=तोलने, माने ।
छ—जोष
छ—जोख* } "तुलसी प्रेमपयोधि की तातें माप न जोष"—तुलसीदासः ।
छ—जोखा=आयव्ययविवरणम्, लेखविवरणम् (परितर्कणम्) ।

√जॄ १०/२६५ वयोहानौ (प) आधृषाद्वा । क्षी-मै-सा-जै-काकृ-कात-शा-हे । ज्याने—वो ।
च×, श
>√ज्रि वयोहानौ (प) इति नन्दी-क्षी ।

क—गेर्-, गेर्-, ग्रे=वयोवृद्धौ, जरायाम्, परिपक्वतायाम् । पु. च. स्ला.-जरेति=परिपक्वतायाम्-जू. पॉकर्नीः ।

ग—जारयन्ती-ऋ. १,१२४,१० । जरति-षोढो, १७ । न यं जरन्ति शरदो न मासाः-ऋ. ६,२४,७ । अजीजरत्-पै. ११,२,१ ।

घ—जरयति (प्रयोज.)–जातक ५,५०१=६,३७५।
घ—जीरति, जीरयति (प्रयो.)–विनय. १,२३७=नाशे।
ङ—√जर=जरायाम्। वक्क–जरंत–अच्चु. ७९।
ङ—√जीरव (सक्क)=जीर्णतायाम्। जीरवइ–कुप्र. २६६।
छ—√झड़ना, √झरना (<जरणम्, क्षरणम् ?)=कस्यचन वस्तुनो लघीयसामंशानां विशीर्य पतने। केशानां विशरणे

+√ज्ञप् (ज्ञप) १०/८६ जै-शा-हे×, श (च—√ज्ञा)	मारणतोषणनिशानेषु (प) मित्त्व। क्षी-च। ज्ञापने मारणादिषु चाभिधानमस्यैव—मै। मारणदिषु चाभिधानमस्यैव—सायणः (स्मरति)। मारणतोषणनिशामनेषु—शाकटायनानुसारिणः—सा। ज्ञेये—काकृ। ज्ञप्तौ—वो। कात ?	√ज्ञा १/मारणतोषणनिशानेषु (प)।
प्रयो.	ह्वि.।	

ग—ज्ञपयिष्यामि–कौ. १,१। ज्ञपयते–छान्दोग्यो. २,१३,१। ज्ञपय राजपुत्र–शाङ्खा. श्रौ. १५,२५,२। ज्ञापयते स प्रस्तावः–छान्दोग्यो. २,१३,१।

+√ज्ञा १०/२०० श	नियोजने (प) क्षी-मै-काकृ-कात-शा-हे। नियोगे—सा-जै। तोषणे—च। प्रेरणे—वो। मारणादि-(=मारणतोषणनिशान)–नियोजनेषु—हे।	√ज्ञा ९/ अवबोधने (उ)।
प्रयो.	ह्वि.।	

क—गेन्–,गेनृ–, ग्ने–, क्नो=ज्ञाने, परिचये, विचारणे–वा. पॉकर्नीः।

ग—अज्ञापयत्–जैन्ना. १८६ । भक्ष्यतामिति सुव्यक्तं प्रभुराज्ञापयिष्यति–वा. रा. ५,२५,४८ । परीक्ष्य ज्ञापयन्नर्थान्–मभार. १२,४१४९ ।

ङ—√जाणाव=ज्ञापने । जाणावइ, जाणावेइ–कुमा.; मद्दा. ।

√ज्रि १०/२६५ मै-श-च-जै-काकृ- कात-शा-वो×	वयोहानौ (प) इति नन्दी—क्षी । आधृषाद्वा । क्षी-सा-हे ।	<√जॄ वयोहानौ (प) । √जॄ (जॄष्) ४/ वयोहानौ (प) ।
+√टङ्क् (टकि) १०/९८ च×,श	बन्धने (प) क्षी-मै-सा-जै-काकृ- कात-शा-हे । बन्धे—वो । प्रयो. आवरणे—ह्वि. ।	√टम्ब् १/२०६ z मर्दने (प) काकृ ।

एवमन्यत्रापीदित्त्वं णिज्विकल्पार्थं द्रष्टव्यम्–१०/२ सा ।

ग—टङ्क–टङ्क–लाङ्गूलो. २१४:१७ । जलवतोत्तानेन पात्रेण देहस्थालीं टङ्कयति–का. श्रौ. ४,२,३४ । टङ्कैश्च दात्रैः–वा. रा. २,८०,७=पाषाणदारणैः । (खनित्रम्–मेदि. के २४ ।)

छ—√टाँकना=बन्धने, योजने ।

छ—टाँका (<टङ्कः)=योगः, बन्धनम् ।

छ—टाँग (<टङ्का=जङ्घा–मेदि., के २५)

+√टिप् (टिप) १०/१३९ मै-सा-श-च-जै-काकृ- कात-शा-हे×	क्षेपे (प) क्षी । नुदि—वो ।	√तिप् (तिप) १०/ क्षेपे (प) । √स्तिप् (स्तिप) १०/ क्षेपे (प) । √डिप् (डिप) १०/ क्षेपे (प) । √तिप् (तिपृ) १/ क्षरणार्थः (आ) ।

ङ—टिप्पी=टीका, तिलकम्–दे. ४,३ । टिप्पणय=विवरणम्–सुपा. ३२४ ।

ङ—√टीपना (<टेपनम्=क्षेपे)=मन्दप्रहारे; (२) हस्तेनाङ्गुल्या वा विनामने, (३) अङ्कने, टङ्कने ।

छ—√टिपकना† =बिन्दुक्षेपे ।

+√डप् (डप) १०/१३७ क्षी-च-जै-शा×	संघाते (आ) मै-सा-काकृ-कात-हे । संहतौ—वो (उ) ।	√डम्प् (डपि) १०/ संघाते (प) । √डम्भ् (डभि) १०/ संघाते (प)

छ—डप्पू = स्थविष्ठम् ।

√डम्प् (डपि) १०/१३४ मै-सा-श-च-काकृ-कात×	संघाते (प) क्षी-जै-शा-हे । संहतौ—वो (उ) । अभिमर्दने—हे ।	√डप् (डप) १०/ संघाते (आ) ।
+√डम्ब् (डबि) १०१/३६ मै-सा श-च जै-काकृ कात-शा× १/?, प्रयोज.	क्षेपे (प) इति चन्द्रः—क्षी । क्षी-हे । नोटे—वो । उपहासे, विडम्बनायाम् — 'वि'-उपसर्गसहितः—ह्वि. ।	√डम्ब् (डबि) १/२०६ aa मर्दने (प) काकृ ।

ग—डम्बराडम्बरौ चैव ददौ धाता महात्मने-मभार. ९,२५४१ । ऋतुर्विडम्बयामास-रघु. ४,१७=अनुचकार (संजी.) । विडम्बयत्यस्तनिमग्नसूर्यम्-रघु. १६, ११=अनुकरोति (संजी.) । विडम्बयति-यशस्तिल. च., ५ आश्वा., ११५ श्लो.= विगोपयति । आडम्बरः-यशस्ति.च., २ आश्वा., ९८ श्लो.=शोभा ।

ङ—डम्बर=आडम्बरः, आटोपः-उप. १४२ टी.; पिंग. ।

ङ—डम्बर=घर्मः, औष्ण्यम्, प्रस्वेदः-दे. ४,८ ।

+√डम्भ् (डभि) १०/१३४ मै-सा-श-च-काकृ-कात-शा×	संघाते (प) इति दौर्गाः—क्षी । क्षी-जै-हे । संघे—वो (उ) ।	<√डम्प् (डपि) संघाते (प) । √डम्ब् (डबि) १०/ क्षेपे (प) । √डम्ब् १/२०६ aa मर्दने (प) काकृ । √डम्भ् १०/२०० a संघाते (आ) शा । √डम्भ् १०/२६५ अभिमर्दने—हे ।

+√डिप् (डिप)१०/१३८ क्षी-च-जै-शा×,श	संघाते (आ) मै-सा-काकृ-कात-हे। संहतौ—वो (उ)।	√डिप् (डिप) १०/१४० क्षेपे (प)। √डिम्ब् (डिबि) १०/ क्षेपे (प)। √डिम्भ् १/३५२ d धारणे (प) काकृ।
+√डिप् (डिप) १०/१४० च×,श (काकृ-√दीप्)	क्षेपे (प। क्षी-मै-सा-जै-कात-शा-हे। क्षेपणे—जै। नुदि—वो।	√डिम्ब् (डिबि) क्षेपे (प) इति चन्द्रः—क्षी। √डिप् (डिप) ४/ क्षेपे (प)। √डिप् (डिप) ६/ क्षेपे (प)। √तिप् (तिप) १०/ क्षेपे (प)। √टिप् (टिप) १०/ क्षेपे (प)।

ड—√डेव (सक)=उल्लङ्घने, कूर्दने, अतिक्रमणे। वकृ-डेवमाण-राज.।

+√डिम्प् (डिपि) १०/१३५ मै-सा-श-च-काकृ-कात×	संघाते (प) क्षी-जै-शा-हे। संहतौ—वो (उ)। अभिमर्दने—हे।	√डिप् (डिप) १०/ संघाते (आ) मै। √डम्भ् (डभि) १०/ संघाते (प)। √डिम्भ् (डिभि) १०/ संघाते (प)।
+√डिम्ब् (डिबि) १०/१३७ मै-सा-श-च-जै-काकृ-कात-शा×	क्षेपे (प) इति चन्द्रः-क्षी। क्षी-हे। नोदे—वो।	<√डिप् (डिप) क्षेपे (प)। √तिप् (तिप) १०/ क्षेपे (प)। √स्तिप् (स्तिप) १०/ क्षेपे (प)। √टिप् (टिप) १०/ क्षेपे (प)। √दिम्भ् (दिभि) १०/ क्षेपे (प)।

ङ—डिंब=(१) भयम्-से. २,१९; (२) विघ्नः-णाया. १,१-पत्र. ६; औप.; ३-विप्लवः, डमरः-जं २।

ङ—डिंफिअ=जले पतितम्-दे. ४,९।

+√डिम्भ् (डिभि) १०/१३५ मै-सा-श-च-जै-काकृ-कात-शा×· 	संघाते (प) इति दौर्गाः—क्षी। क्षी-हे। संघे—वो (उ)।	<√डिम्प् (डिपि) संघाते (प)। √डिम् हिंसे-सौ.धा.-वो। √डम्प् (डपि) १०/ संघाते (प)। √डिम्भ् १०/२८० संघाते (आ) जै। √डिम्भ् १०/२०० b संघाते (आ) शा। √डिम्भ् १०/२६६ अभि-मर्दने (आ) हे। √डिम्भ् १/३६२ धारणे (प) काकृ।

ग—डिम्भकोऽनन्तरोऽभवत्-हरिवंशे भविष्यपर्वणि ३२,१८=स्वनामख्यातः शाल्वदेशाधिपतेर्ब्रह्मदत्तस्य पुत्रः।

ङ—√डिंभ (सक)=(१) अधःपातने, (२) ध्वंसे, नाशे। वकृ-डिंभंत-कुमा. ७,४२।

ङ—डिंभ=बालकः, शिशुः-महा.; सुपा. १६।

+√तंस् (तसि) १०/१६७ श-च-जै-काकृ-कात-शा× 	अलङ्कारे (प) इति दुर्गः—क्षी। क्षी-मै-सा-हे अलङ्कृतौ—वो। प्रयोज. कम्पने—ह्वि.।

√तंस (तसि) १/३८५ 	अलङ्कारे (प) क्षी।

ग—अतंसयत्-वा. सं. २३,२४।

+√तट् (तट) १०/४३ मै-सा-च-जै-कात- 	आघाते (प) इत्येके—क्षी। 	<√तड् (तड) आघाते (प)।

शा-हे× क्षी-काक्ठ। √तट् (तट) १/ उच्छ्राये (प)।
आहतौ—वो।
१/ शब्दे—ह्वि.।

ग—करिष्यामि न सन्देहस्ताटकावधमुत्तमम्—वा.रा. १,२६,४ (गी. प्रे. सं.)। भौवादिकस्यैव √तट् धातोरर्थान्तरे प्रयोग इह।

+√तड् (तड) १०/४२ आघाते (प) >√तट् (तट) आघाते (प)।
श क्षी-मै-सा-च-जै-काक्ठ-कात-शा-हे। √तण्ड् (तडि) १/ ताडने (प)।
त्विषि, आहतौ—वो। √तल् (तल) १०/ प्रतिष्ठायाम् (प)। विद्युत् तळिद् भवतीति शाकपूणिः। सा ह्यवताडयति—निरु. ३,११,२।
२/ प्रयो. ताडने—ह्वि.।

ग—ताडय-ताडय—लाङ्गूलो. २१४: १७। तळित्—ऋ. १,९४,७। ताडनम्—बृहज्जाबालो. ५,१३।

ङ—√ताड (सक)=ताडने, (२) प्रेरणे, (३) गुणयुक्ततायाम्। कवक्त—ताडिज्जमाण, ताडीअंत, ताडीअमाण—सुपा. २६; पि. २४०।

ङ—√ताल (सक)=ताडने। तालेइ—पि. २४०।

छ—√ताड़ना=ताडने, दण्डने, (२) भर्त्सने, शासने।

+√तड् (तड) १०/२५३ भासार्थः (प) पूर्ववत्।
मै-च-श-जै-काक्ठ-कात-शा-हे× (सा—√तुड्) इत्येके—क्षी। क्षी-हे।
त्विषि आहतौ—वो।

ग—तळित्—ऋ. १,९४,७; पै. १२, १७। "ताडेर्णिलुक्च"—उणा. १/९८ इति वैयाकरणास्तडिच्छब्दं √तड् आघाते धातुतो व्युत्पादयन्ति। निरुक्तकारोऽपि (३,११,२) तथा प्रतिपेदे। वस्तुतः प्रकृतशब्दे ताडनार्थो भासनार्थश्चेति व्यापारद्वयम्। पाणिनिर्भासनार्थमपि प्रस्तौति धातुम्। ध्वन्यात्मकत्वेन धातुद्वयमभिन्नम्। अर्थभेददर्शनायायं पार्थक्यं नीतः।

+√तन् (तनु) १०/२८७ श्रद्धोपकरणयोः (प)। √वन् (वन) १०/ श्रद्धोपहिंसनयोः (प)।
श-च× क्षी-मै-सा-हे।

	श्रद्धोपहिंसायाम् —जै-शा । श्रद्धोपकारयोः—कात । श्रद्धाघाते—हे । शब्दे—काकृ । उपहतौ श्रद्धाघाते श्रद्धोपकारयोः—वो । उपसर्गाच्च दैर्घ्ये—क्षी,-मै-सा-च-कात-शा-हे । दैर्घ्यके—वो ।	√वन् (वन) १०/ श्रद्धोपकारयोः (प)। √चन् (चन) १८४१ श्रद्धोपहननयोः (प) इत्येके—सि. कौ.। √तन् (तनु) ८/१ विस्तारे (उ)।
√तन्त्र् (तत्रि) १०/१४७ श	कुटुम्बधारणे (आ) क्षी-मै-सा-च-जै,-काकृ-(प),-कात-शा-हे । 'धारणे' इति चन्द्रः —क्षी,-वो । भाषायामस्य विस्तारेण प्रायः प्रयोगः—दुर्गादासः ।	√तन् (तनु) ८/१ विस्तारे (उ)। √तन्त्र् १०/४ दर्शनीये (प) काकृ। √तन्द्र् सादे मोहे—सौ. धा.—वो। √तिन्त्र् १०/८ अम्लकरणे (प) काकृ।

क—तन् = विस्तारे ।

ख—न. पर्सि. तार (अवे. * तत्र-)—वा. पॉकर्नीः ।

ग—येन तन्त्रयतस्तन्त्रं वृत्तिः स्यात् तत् तदाचरेत्—मभार. १२,७८१४; तन्त्रैः—२,१,३१ = उपायैः (नील.) । प्रजाः प्रज्ञाः स्वा इव तन्त्रयित्वा—शाकु. ९१,१३ ।

√तप् (तप) १०/२६८ श-च ×	दाहे (प) आधृषाद् वा । क्षी,-मै(उ),-सा-च-जै-कात-शा-हे (आ)-, काकृ-वो ।	√तप् (तप) १/ संतापे (प)। √तप् (तप) ४/ ऐश्वर्ये (आ)। √पत् (पत) ४/ ऐश्वर्ये (आ)।
१/प्रयो.	—ह्वि. ।	

ग—तपस्व तम्—ऋ. १०,१६,४। शत्रूणां तापयन्मनः—अ. वे. १९,२८,२। तापयन्ति महात्मानम्—वा. रा. ५,३२,३६। मनस्तापयतीव मे—मभार. ४,१७५५।

+√तर्क् (तर्क) १०/२५१ च×, श — भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात। दीप्तौ—वो। वितर्कणेऽप्ययम् (अत्र सक) दुर्गादासः। प्रयो. विचारणे—ह्वि.। — √तॄ १/ प्लवनतरणयोः (प)।

क—तेर्क्-,त्रेक्-(तॉर्क्-, त्रॉक्-)=वेष्टने। लैति. ताकुऐओ-ऐरे=वेष्टने-जू. पॉकर्नीः।

क—तेरेक्-(तेर्क्-, तॉर्क्-ः त्रेक्-) = वेष्टने-वा. पॉकर्नीः।

ग—तर्कयाम्यहम्-वा. रा. ५,१,५६। तर्कयामास-वा. रा. ५,१८,२२; मभार. ३,१७२३। तरङ्गान् को हि तर्कयेत्-कथासरि. २६,१८। मन्ये भ्रातरं तर्कचक्षुषा-मभार. १,१६८,१८-तर्कः=ज्ञानम्। तद् दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः-दे. भा. ८,२,४।

ङ—√तक्क (सक)=तर्कणे, अनुमाने। तक्केमि-मै. १३।

छ—√ताड़ना (<तर्कणम्)=आभासे, अनुमाने।

छ—√तरकना (<तर्कणम्)=तर्कणे, विचारे, अनुमाने।

छ—√ताकना (<तर्कणम्)=चिन्तने, विचारणे, वाञ्छने-"अनभल ताका"-तुलसीदासः।

छ—√ताकना (<तर्कणम्)=दर्शने, लक्षणे, (२) रक्षणे।

[छ—√तरकना (<अनु. ? √तॄ १/ प्लवने)=कूर्दने, उत्प्लवने-"तरकेउ पवनतनय बलभारी"-तुलसीदासः]।

√तर्ज् (तर्ज) १०/१५१ च×,श — संतर्जने (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे। वाग्भर्त्सयोः—वो। — √तर्ज् (तर्ज) १/ भर्त्सने (प)। √तर्ज् १/६७ व्यथने (प) काकृ। √भर्त्स् (भर्त्स)१/संतर्जने (आ)।

"लक्ष्ये तर्जयतीति दृश्यते। एवं निशामयति, भालयति, कोटयति, वञ्चयति निवेदयतीत्यादि। अत एव चुरादिभूतान् स्वरान्वितान् नाकरोत्"-क्षी। क्षीरस्वामिनैवं-वदता नूनं महाभारतं न परिशीलितम्। तत्र 'तर्जयसे' इति प्रयोगो विद्यते। भट्टिकाव्य-कारोऽपि 'तर्जयन्तः' ७/३६ इति लिखंस्तथैव ज्ञेयः।

ग—तर्जयसे महावातमिव द्रुमः–मभार. ५,२४८५; तर्जयसे–१४,९१३। तर्जयन्निव केतुभिः–रघु. ४,२८ = तर्जिभर्त्स्योरनुदात्तत्वेऽपि चक्षिङो ङित्करणेनानुदात्तेत्त्व-निमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात् परस्मैपदमिति वामनः–(संजी.)। वाक्शरैस्तर्जयिष्यन्ति गुरून् शिष्याः–हरिवंश. ११९६६।

+√ तिल् (तिल) १०/६२ श	प्रतिष्ठायाम् (प) क्षी-मै-सा-च-काकृ-कात-हे। प्रतिष्ठाकरणे—जै-शा। प्रतिष्ठितौ—वो।	√ तॄ १/ प्लवनतरणयोः (प)। √ तड् (तड) १०/ भासार्थः (प)।

क—तेल् = तुल्यतला भूः; समीकरणे। अर्मे. तुल् = प्रदेशः, मण्डलम्, राष्ट्रम्, भूतलभागः। पु. इरि. तलम्, तल्मन् = तलिमा, भूः; तलर् = पार्थिवम्। म. इरिशू–तेळ्, तौळ्, तुळ् = भालम्, तटम्–वा. पॉकर्नीः।

क—तेल्प् = स्थानम्, कोष्ठः, सदनम्। लिथु. तेल्पु, तल्प = पूर्वोक्तोऽर्थः–वा. पॉकर्नीः।

ग—महीतलस्पर्शन०–रघु. २,५०। तल्पमुज्झाञ्चकार–रघु. ५,७५। ०तालैः–उत्तरराम. ३,१०। परिशुष्कतालवः–ऋतु. १,११। प्राप तालीवनश्याममम्–रघु. ४,३४।

छ—√ तरियाना (<तले) = अधःकरणे, (२) आच्छादने, पिठरतले मृदादिलेपने, यतस्तत्र कार्ष्ण्यं न संसज्येत। (अक) तलस्थितौ।

+√ तिज् (तिज) १०/११२ श	निशाने (प) क्षी-मै-सा-च-जै-कात-शा-हे।	√ तिज् (तिज) १/ निशाने क्षमायाञ्च (आ)।

ग—संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्—मभार. ५,२७४२। अश्वमुत्तेजयामास–कथासरि. १८,९१। उत्तेजयामि सुहृदः परिमोक्षणाय—मृच्छक. ६७,१९।

+√ तिप् (तिप) १०/१३७	क्षेपे (प) क्षी (यु. मी. सं)।	√ टिप् (टिप) १०/ क्षेपे (प)। √ डिप् (डिप) १०/ क्षेपे (प)। √ स्तिप् (स्तिप) १०/ क्षेपे (प)। √ तिपृ (तिपृ) १/ क्षरणार्थः (आ)।

ग—तिप्य०—राजत. ८,१५४५ (= वैश्य०)।

+√तिल् (तिल) १०/७२ श-च-शा×	स्नेहने (प) क्षी-मै-सा-जै-काकृ-कात-हे । स्निहि—वो ।	√तिल् (तिल) १/ शैथिल्ये (प)। √तिल् (तिल) ६/ स्नेहने (प)।
+√तीर (तीर) १०/३५६ श-च×	कर्मसमाप्तौ (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे । कर्मणां समाप्तौ—वो ।	√तॄ १/ प्लवनतरणयोः (प)।

ग—तीरितं चानुशिष्टं च—मनु. ९,२३३=शास्त्रव्यवस्थानिर्णीतम् (मन्वर्थ.)। तीरुभीरुहराय—हरिवंश. १४८९१।

ङ—√तीर (सक)=समाप्तौ, परिपूर्तौ। तीरइ—भग.। संकृ-तीरित्ता-कप्प.।

+√तुज् (तुज) १०/३२ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	हिंसाबलादाननिकेतनेषु (प) शाकटायनस्तु—सा।	√तुज् (तुज) १/ हिंसायाम् (प)। √तुञ्ज् (तुजि) १/ हिंसायाम् (प)।
√तुञ्ज् (तुजि) १०/२९ श	हिंसाबलादाननिकेतनेषु (प) क्षी-मै-सा। हिंसायाम्—च। हिंसाबलिदाननिकेतनेषु—जै। हिंसाबलदाननिकेतनेषु—काकृ-कात-शा-हे। निकेतने हिंसे बले दाने—वो।	पूर्ववत्। √तुञ्ज् (तुजि) १०/२२४ भासार्थः (प)।

ग—[तुञ्जः=निकेतनम्—क्षी]।

+√तुञ्ज् (तुजि) १०/२२४ च×,श	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात। भा-षट्टार्थे—वो।	पूर्ववत्।

षट्टार्थः = निकेतनहिंसाबलदानानि–दुर्गादासः।

+√तुत्थ् (तुत्थ) १०/३८६ आवरणे (प) मै।
श-च-जै-काकृ- .. क्षी×,-मै-सा-हे।
कात-शा× स्तृतौ—वो।

ग—पांशुर्दिशां मुखमतुत्थयदुत्थितोऽद्रेः—शिशु. ५,११ = आच्छादयति स्म (सर्वङ्कषा)।

+√तुम्प् (तुपि) १०/११७ अर्दने (प) इति <√तुम्ब् (तुबि) अर्दने (प)।
सा-श-च-जै-काकृ- दौर्गाः–क्षी।
कात-शा× क्षी-मै-हे-वो।

+√तुम्ब् (तुबि) १०/११७ अर्दने (प) <√तुम्प् (तुपि) अर्दने (प)।
च×, श क्षी-मै-जै-काकृ-कात-शा-हे। √तुम्ब् (तुबि) १/ अर्दने (प)।
अदर्शने—सा। √लुम्ब् (लुबि) १०/ अर्दने (प)।
अर्दे—वो।

क—तेउ–, तुउ–, तु–, तू = उच्छ्रयने, वृद्धौ—वा. पॉकर्नीः।

ग—सशिक्यतुम्बकरकौ–हरिवंश. ६४,५। (तुम्बति = नाशयत्यरुचिम् इति) [तुम्बिनी = कटुतुम्बी–राजनिर्घण्टः]। तुम्बुरुः–वा. रा. ३,४,१६ (गी. प्रे. सं.)।

+√तुल् (तुल) १०/६३ उन्माने (प) √दुल् (दुल) १०/ उत्क्षेपे (प)।
श क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। √तुल् (तुल) १/ उन्मितौ (प) वो।
उन्मितौ—वो।
[१]/प्रयो. —ह्वि.। √तुल् १/४९६ a द्रवणे (आ) काकृ।
√तुल्ल् १/४९६ b द्रवणे (आ) काकृ।

क—तेल्–, तेलू–, त्ले (इ)–, त्ला = उत्थापने, उन्माने (तोलने)। लैति.–तॉल्लो,–ऍरे = गायकानां नर्तकानां वा मण्डलम्; अट्टालिका, कपोतपालिका। एसन् तेलेःनॉक् = वत्सः, मूर्खो मनुष्यः, हरिणशावः–जू. पॉकर्नीः।

ग—तोलयिष्यामि–वा. रा. १,६९,१५; तोलयन्–४,९,९१। (ततः कृष्ण-स्तुलयामास–हरिवंश. ४५०४। खल्वहं त्वां न तुलये–वा. रा. ४,९,१०० इत्यणिच्पक्षे क्रान्तात् (३/१/३५) तुलशब्दाण्णिच्–क्षी)।

ङ—√तोल (सक)=(१) उन्माने, (२) उत्थापने, (३) सम्यग्रूपेण निश्चये। तोलइ, तोलेइ–पिंग.; महा.।

ङ—√तुल (सक)=(१) उन्माने, (२) उत्थापने, (३) सम्यग्रूपेण निश्चये। तुलइ–उव.।

+√तूण् (तूण) १०/१०१ मै-सा-श-च-जै-काकृ- कात-शा-हे×	संकोचने (प) इति चन्द्रः—क्षी। संकोचे—वो।	<√चूण् (चूण) संकोचने (प)। √कुण् (कुण) १०/ संकोचने (आ)। √कूण् (कूण) १०/ संकोचने (आ)। √चूर्ण् (चूर्ण) १०/ संकोचने (आ)।

ग—तूणकम्=छन्दोविशेषः–छन्दोमञ्जरी।

+√तूण् (तूण) १०/१५८ च×, श	पूरणे (आ) क्षी-मै-सा-जै-कात- शा-हे-वो। पूरणे कौटिल्ये च—काकृ।	>√तूल् (तूल) पूरणे (आ)।

क—तुओ (ऊ)–ः तुएउ–ः तू=वंशी, इषुः, नलिका, प्रणाली। (ab.) तुल=तूणी, तूणीरः–वा. पॉकर्नीः।

ग—तूणखड्गधरः शूरः–मभार. ३,१७,३।

+√तूल् (तूल) १०/१५८ मै-सा-श-च-जै- काकृ-कात-शा×	पूरणे (आ) इति चन्द्रः—क्षी। क्षी-हे-वो।	√तु २/ वृत्तौ हिंसायां पूर्तौ (प) वो। √तूल् (तूल) १/ निष्कर्षे (प)।

ग—तूलम्=पूगः–भावप्रकाशः (श. क. द्रु.)।

+√तृप् (तृप) १०/२६९ श-च×	संदीपने (प) आधृषाद्वा क्षी-हे। प्रीणने—शा-जै।	√तृप् (तृप) ४/ प्रीतौ (प)। √दृप् (दृप) १०/ संदीपने (प)।

संदीपे प्रीणने च—वो।
'संदीपने' इति क्षीरस्वामी
—सा।
तृप्तौ—मै-सा-काकृ-कात।

प्रयोज. —ह्वि.।

ग—सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम्—मभार. १,८१२६; तर्पयन्त्यथ जुह्वति—१४,१०,४०। सर्वान् धातून् प्रतर्पयेत्—सुश्रु. १,२४८,१।

+√त्रंस् (त्रसि) १०/२३१ च×,श

भासार्थः (प) क्षी-शा-हे।
भाषार्थः—मै-सा-जै-काकृ-कात।
भासि—वो (भ्वा. चु.)।

√त्रस् (त्रस) १०/ धारणे (प)।
√त्रस् (त्रसी) ४/ उद्वेगे (प)।

+√त्रस् (त्रस) १०/२१७

वारणे (प) इति दुर्गः—क्षी।
क्षी-मै-सा-जै-कात-शा-हे।
'धारणे' इति नन्दी—क्षी।
क्षी-मै-सा-काकृ-हे।
'ग्रहणे' इत्येके—क्षी-सा।
धृतौ ग्रहे निषेधे—वो।

<√त्रस् (त्रसी) १/ भये (प) वो।
√त्रस् (त्रसी) ४/ उद्वेगे (प)।

प्रयो. भये—ह्वि.।

ग—विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति ह—हरिवंश. ३३७७। वित्रासयितुकामः—वा. रा. ३,६८,८।

छ—√त्रासना * †
छ—√तिरासना
} =त्रासने, भये।

+√त्रुट् (त्रुट) १०/१६७ श ? च-जै-काकृ-कात-शा×

छेदने (आ) —क्षी-मै-सा-हे।
छिदि—वो।

<√त्रुड् (त्रुड) छेदने (आ) इत्येके—क्षी।
√त्रुट् (त्रुट) ६/ छेदने (प)।
√त्रुड् (त्रुड) १/४४५ b छेदने (आ) काकृ।

ग—[तोटयत्यायसान् बन्धान्-राजत. ६,२४८।

ङ—√तिउट्ट (सक)=छेदने, (२) परित्यागे। तिउट्टिज्जा-सूअ. १,१,१,१।

+√त्रुड् (त्रुड) १०/१६७	छेदने (आ) इत्येके	<√त्रुट् (त्रुट) छेदने (आ)।
मै-सा-श-च-जै-काकृ-	—क्षी।	√त्रुड् १/४४५ b त्रोडने (आ) काकृ।
कात-शा-वो×	क्षी-हे।	√त्रुट् (त्रुट) ६/ छेदने (प)।

सुस्पष्टो विकासः।

+√दंश् (दशि) १०/१४५	दंशने (आ)	√दश् (दश) १०/ दशने दर्शने च (आ) जै।
च×,श	क्षी-मै-सा-कात-हे।	√दस् (दस) १०/१४१ दर्शनदंसनयोः (आ) सा।
	दशने—जै-काकृ-शा।	
	दर्शने—कात।	
	दंशने दर्शने च—हे।	
	दर्शे दंशने च—वो।	
प्रयो..	...ह्वि.।	

इह दर्शनार्थो नूनं प्राकृतभाषातो गृहीतो ज्ञायते। तत्र दर्शनं 'दंसण' इति भवति—द्रष्ट.-ङ।

ग—...कृष्णसर्पैः सुप्तं चैनमदंशयत्-मभार. १,२२४३। दंशयति—अ. कौ. सू. ३०,४६।

ङ—दंसण=दंशनम्-से. १,१७।

ङ—दंसण (<दर्शनम्)=अवलोकनम्-पुष्फ. १२४; स्वप्न. २६; (२) नयनम्-से. १,१७।

+√दंश् (दशि) १०/२३३	भासार्थः (प)	पूर्ववत्।
च-जै-सा×,श	क्षी-शा-हे।	
	भाषार्थः—मै-सा-काकृ-कात।	
	त्विषि—वो।	

छ—√धाँसना (<दंशनम्) अनु. ?=पशूनां कासने।

छ—धाँसी (<दंशिका)=अश्वस्य कासः।

छ—धांस (<दंशः)=शुष्कमरिचतमालपत्रादीनां तीक्ष्णो गन्धः, येन भवति कासप्रक्रमः।

√दंस् (दसि) १०/१४६	दर्शनदंसनयोः (आ)	दंसयः कर्माणि दंसयन्त
श-च-जै-काक्ट-कात×	क्षी-मै-सा।	एनानि-निरु. ४,२५,३।
	दर्शने—शा।	दंसयः इत्येतदनेकेषां कर्मणा-
	दंशने दर्शने च—हे।	मभिधानम्। तानि हि दंसय-
	दशौ दंशे—वो।	न्त्युपक्षयन्ति कर्मकराः—
प्रयोज.	आह्रुत्ये—ह्वि.।	दुर्गाचार्यः।
		√दस् (दस) १०/१४१
		दर्शनदंसनयोः (आ) केचित्
		सा।
		√दस् (दस) १०/३४३
		निरवसाने (प) केचित्—
		सा।

ग—दंसयः-ऋ. १०,१३८,१। दंसना-काठ. १०,१२; शौ. २०,७४,२। दंससः—बृहदारण्यको. २,५,१६।

ङ—√दंस (सक)=दर्शने, बोधने। दंसइ-महा.। वक्र-दंसंत, दंसित, दंसअंत-भग.; सुपा. ९२; अभि. १८४। कृ-दंसियव्व-सुपा. ४५४।

+√दंस् (दसि) १०/२३२	भासार्थः (प)	√दंश् (दशि) १०/ भासार्थः
श-च-काक्ट-कात×	क्षी-शा-हे।	(प)।
	भाषार्थः—मै-सा-जै।	
	भासि—वो।	

छ—√धाँसना=पशूनां कासने।

+√दंह् (दहि) १०/१२८	च=रक्षणे (प)	√दङ्घ् (दघि) १/ पालने,
मै-सा-श-च-जै-काक्ट-	क्षी-हे।	च=वर्जने (प)।
कात-शा×	दीप्तौ दाहे—वो	√डम्भ् (डभि) १०/ संघे
√डम्भ् (डभि)	पाठान्तरम्—क्षी।	(उ) वो।

+√दण्ड (दण्ड) १०/३७१	दण्डनिपातने (प)	√दण्ड् १/१८३d हिंसागत्योः
च×, श (जै-शा-	क्षी-मै-सा-जै-काक्ट-	(प) काक्ट।
√दण्ड्)	कात-शा-हे।	√डिण्ड् १/१८३f हिंसागत्योः

तत्पाते—वो।

(प) काक्र।

√डुण्ड् १/१८३e हिंसागत्योः (प) काक्र।

√दम् (दमु) ४/ उपशमे (प) +डः (उणा. १/११४)। 'दण्डो ददतेर्धारयतिकर्मणः''''। दमनादित्यौपमन्यवः–निरु. २,२,२१।

क—दल्=विदारणे, कर्तने–वा. पॉकर्नीः।

ग—तान् सहस्रं च दण्डयेत्–मनु. ९,२४३। स्वमण्डलमदण्डयत्–राजत. ४,६२०।

ङ—√दंड (सक)=दण्डने, निग्रहे। कवक्र–दंडिज्जंत–प्रासू. ६६।

छ—√डाँड़ना=दण्डने (अर्थस्य)। "अदंड ऐसो डाँड़िगो"–तुलसी.।

+√दभ् (दभ) १०/१३६ क्षेपे (प)
मै-सा-श-च-जै-काक्र- क्षी-हे।
कात-शा× नोदे—वो।

√दम्भ् (दभि) १०/नोदे (प) वो।

√दिम्भ् (दिभि) १०/ क्षेपे (प)।

√दम्भ् (दभि) १०/ क्षेपे–(प) इति नन्दी–क्षी।

√दम्भ् (दन्भु) ५/ दम्भे (प)।

[ग—देवा दाभीत्यसुराः–तै. २,४,३,१। दाभ्यनियम०–भा. पु. ४,२३,४।

+√दम्भ् (दभि) १०/१३७ क्षेपे (प) इति नन्दी—क्षी
मै-सा-श-च-जै-काक्र- क्षी-हे।
कात-शा× नोदे—वो।

<√दिम्भ् (दिभि) क्षेपे (प)।

√दभ् (दभ) १०/१३६ क्षेपे (प)।

+√दल् (दल) १०/२१९ विदारणे (प) मित्
च×, श क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
भैदे—वो।
प्रयो ''''''ह्वि.।

√दॄ ९/ विदारणे (प)।

√दल् (दल) १/ विशरणे (प)।

ग—दलयति–ह्वि । मया नोपलब्धम् ।

ङ—√दल (सक)=विचूर्णने, विदारणे । कवक्रु–दलिज्जंत–से. ६,६२ ।

छ—√दलना=विचूर्णने, मर्दने ।

+√दस् (दस) १०/१४१ क्षी-मै-श-च-जै-काकृ-कात-शा-हे×	दर्शनदंसनयोः (आ) इति केचित्—सा । सा । दशौ दंशे—वो ।	<√दंस् (दसि) दर्शन-दंसनयोः (आ) ।
+√दस् (दस) १०/३४३ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	निरवसाने (प) केचित् पठन्ति—सा ।	

ग—"पितेव पुत्रं दसये वचोभिः"–सायणेन समुद्धृतं वाक्यम् । दसये=निरवासयामि ? इति व्याख्यानात् ।

+√दाश् (दाश्रृ) १०/१४४ मै-सा-च-जै-काकृ-कात-शा×	दाने (आ) क्षी-हे-वो ।	दाशति } निघ. ३/२०=दान- दासति } कर्माणौ ।

ग—स वा एतेभ्यस्तत्पुरोऽदाशयत् तस्मात् पुरोडाशः–शब्रा. १,६,२,५ ।

+√दिम्भ् (दिभि) १०/१३७ मै-सा-च-जै-काकृ-कात-शा×	क्षेपे (प) क्षी-हे । नोदे—वो ।	>√दम्भ् (दभि) क्षेपे (प) इति नन्दी—क्षी ।
+√दिव् (दिवु) १०/१७४ च×,श (जै–मर्दे)	परिकूजने (आ) क्षी-मै-सा-काकृ-कात-शा-हे-वो ।	√दिव् (दिवु) ४/१ क्रीडा-विजिगीषा... (प) । √देव् (देवृ) १/ देवने (आ) । √दिव् (दिवु) १०/ अर्दने (प) ।
+√दिव् (दिवु) १०/१९२ च×,श	अर्दने (प) क्षी-मै-काकृ-कात-शा-हे । मर्दने—सा-जै । अर्दे—वो ।	

८१

ग—परिद्यूनम्–वा. रा. २,५७,२४=म्लानम् (तिल.) [यदी विशो मानुषीर्देवयन्तीः–ऋ. ६,३,८१ ; अग्ने देवान् देवयते यज–६,१०,७ ।]

√दुःख (दुःख) १०/३७५ च×,श	तत्क्रियायाम् (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे । तत्कृतौ—वो ।	दुर् +√खन् (खनु) १/ अवदारणे (प)+डः ।

ग—[अङ्गप्रत्यङ्गानि दुःखन्ति–सद्धर्मपु. ४,५ ।]

ङ—√दुक्ख (अक)=वेदनायाम् । (२) (सक)–दुःखने । दुक्खेइ–स. ३०४ ।

ङ—√दुहाव (सक)=दुःखने–प्रामा. ।

ङ—√दूहव (सक)=दुःखने । दूहवेइ–सिरि. १६७ ।

छ—√दुखना=वेदनायाम् ।

छ—√दुखाना (सक)=पीडायाम्, दुःखने ।

छ—√दुखवना (सक)=पीडायाम्, दुःखने । "कै तिनसों दुखवै मुख को री"—केशवदासः ।

+√ दुल् (दुल) १०/६४ श-(जै√डुल्) (काकृ-√दूल्) प्रयो.	उत्क्षेपे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो । —ह्वि. ।	√तुल् (तुल) १०/ उन्माने (प)। आन्दोलयति लोकात्—क्षी १०/६४ ।

क—दॅल्=कम्पने, दोलने । लिथु. दॅरि्स्त=मन्दगतौ, विलम्बे । दुलिनेति । दॅल्ओः–जू. पॉकर्नीः ।

ग—दोलयित्वा–सार. २५४:६ । (अम्बा दुला नितत्निः–तै. ४,४,५,१; काठ. ४०,४) ।

ङ—√डुल् (अक)=दोलने, कम्पने । डुलइ–पिंग. ।

ङ—√दोल (अक)=दोलने, कम्पने । दोलंति–कप्पू. ।

ङ—√डोल (अक)=दोलने, कम्पने । संशये । वकृ–डोलंत–अच्चु. ६० ।

छ—√डोलना=दोलने, (२) चलने ।

+√ दृप् (दृप) १०/२७० मै-श-च-जै-काकृ-कात-शा×	संदीपने (प) आधृषाद्वा क्षी-सा-हे-वो ।	√दृप् (दृप) ४/ हर्षमोहनयोः (प)।

√दृभ् (दृभ) १०/२६४ क्षी श-च-जै-शा-हे×	संदर्भे (प) मै-सा-काकृ-कात। गुम्फने—वो।	√दृभ् (दृभी) ६/ग्रन्थे (प)।
√दृभ् (दृभी) १०/२७१ श-च-काकृ×	भये (प) क्षी-मै-सा-जै-कात- शा-हे-वो।	√दॄ १/ भये (प) मित्।
+√धक्क् (धक्क) १०/५८ श, (काकृ-√धष्क्) लैपिकी त्रुटिः।	नाशने (प) क्षी-मै-सा-च-जै-कात- शा-हे-वो। नाशे—काकृ।	√नक्क् (णक्क) १०/ नाशने (प)।

छ—√धकियाना
छ—√धकेलना } =धक्कने, प्रेरणे।

छ—धक्का (<धक्कः)।

+√धीर् (धीर) १०/ अपाणिनीयः।	धैर्ये, आश्वासने (प)	धियं रातीति धीरः।

क—धी=दर्शने, ज्ञाने, विचारणे-जू. पॉकर्नीः।

ग—कृतवत्यसि नावधीरणाम्-रघुं. ८,४८=अवज्ञाम् (संजी.)।

ङ—√धीर (अक)=(१) धैर्ये, (२) सक-धैर्ये, आश्वासने। धीरेति-गउड.।

+√धू (धून्) १०/२८२ श-च×	कम्पने (उ) क्षी-मै-सा-जै-काकृ- कात-शा-हे। कम्पे—वो। प्रयोज.—ह्वि.।	√धु (धुञ्) ५/९ कम्पने (उ)। √धू (धूञ्) ५/९ कम्पने (उ)। √धू ६/११७ विधूनने (प)। √धू (धूञ्) ९/१५ कम्पने (उ)।

ग—धूनयामास वेगेन-मभार. ३,४४४=४,७६०; यथा शल्यकवानाखुः पदं धूनयते सदा-१२,३३०७। न चैतदवधूनयेत्-मनु. ३,२२९। रावणं स व्यधूनयत्-वा. रा. ६,९०,१०।

ङ—√धुणाव (सक)=कम्पने। धुणावइ-वज्जा. ६।

+√धूप्(धूप)१०/२४१ च×,श	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै- काकृ-कात। दीप्तौ—वो।	√धूप् (धूप) सन्तापे (प)।

ग—धूपयति-तै. ५,१,७,१; मै. ३,१,७; शत्रा. ६,५,३,८-१०; तैआ. ५,३,५। वसवस्त्वा धूपयन्तु-वा. सं. ११,६०। रक्षोघ्नैर्धूपैर्धूपयेत्-सुश्रु. १,१६,९।

+√धूश्(धूश)१०/९९ च-जै-शा×, श (कात—√धृश्)	कान्तिकरणे (प) इत्येके—क्षी। मै-सा। कान्तीकरणे—काकृ- कात-हे। कान्तिकृतौ—वो।	<√धूष् (धूष) कान्तिकरणे (प)।
+√धूष्(धूष)१०/९९ मै-श-च-जै-काकृ-कात- शा×	कान्तिकरणे (प) क्षी-सा। कान्तीकरणे—हे। धूसे (=कान्तिकृतौ) —वो।	>√धूश् (धूश) कान्तिकृतौ (प)।
+√धूस्(धूस)१०/९९ श-च-कात×	कान्तिकरणे (प) इति दौर्गाः—क्षी क्षी-मै-सा-जै-शा। कान्तीकरणे—काकृ-हे। धूशे(=कान्तिकृतौ) —वो।	<√धूष् (धूष) कान्तिकरणे (प)। √धू९/+"कृधूमादिभ्यः कित्" (उणा. ३/७३) इति सरन्। स च कित्।

ग—रजोधूसरकेतु सैन्यम्-रघु. ५,४२। धूसराङ्ग०-कथासरि. १४,३९।

+√धृ १० [१/९४५] मै-श-च-जै-काकृ-कात- शा× (क्षी-सा-हे स्मरन्ति- भ्वादौ)	धारणे (प) क्षी-सा-हे। धृत्याम्—वो।	√धृ (धृङ्) १/ अवध्वंसने (आ)। √धृ (धृङ्) ६/ अवस्थाने (आ)।

प्रयो. —ह्रिं।

ग—स्थूणां पितरों धारयन्तु मे-ऋ. १०,१८,१३; कृष्टीरन्यो धारयति-७,८५,३। धारयते-मनु. ९,३११; सदानन्दो. ३७९ : ११; गी. १८,३३। धारयिष्ये-वा. रा. २,१३,६।

+√धृष् (धृष) १०/१७२ मै-सा-श-च-जै-कात: शा×	सामर्थ्यधारणार्थः (आ) इत्येके—क्षी। क्षी। सामर्थ्यवारणार्थः—हे। शक्तिसम्बन्धे—काकृ। शक्तिबन्धे—वो।	<√वृष् (वृष) शक्तिबन्धने (आ)।

प्रयोज.—ह्वि.।

ग—न चैषा तेजसा शक्या........धर्षयितुं पथि-मभार. ३,२२४६।

+√धृष् (धृष) १०/२९७ श-वो× =२९६	अप्रसहने (प) क्षी-मै-सा-च-जै-हे। धारणे—काकृ।	√दृष् १/२९७ c धारणे (प) काकृ। √धृष् (ञिधृषा) ५/ प्रागल्भ्ये (प)।
√धृष् (धृषा) १०/३०८	प्रसहने—सा-शा-हे। अमर्षे—वो।	√धृष् १/ संहतौ हिंसे (प) वो।

ग—धर्षयन्ति कुबुद्धयः-मभार. ५,१५०८। तमेवैतत् प्रधर्षयति-कौषीतक्या. १,८।

ङ—√धरिस (सक)=क्षोभे, विचलने। धरिसेइ-उत्त. ३२,१२।

छ—√धरषना*=दमने,मर्दने।

छ—√धरसना=भये, दान्तौ।

√ध्रस् (उध्रस) १०/२१४ श-च-जै-शा×, कात ?	उञ्छे (प) क्षी-मै-सा-काकृ-कात-हे। उत्क्षेपे उञ्छे—वो।	√उध्रस् (उध्रस) १०/उञ्छे (प) प्रयोगसमवायीत्येके-क्षी। √ध्रस् (उध्रस) ९/ उञ्छे (प)।
+√ध्वन (ध्वन) १०/३३६ श-जै×	शब्दे (प) क्षी-मै-सा-च-काकृ-कात-सा-हे-वो।	

प्रयोज.—ह्वि.।

ग—ध्वनयति-ह्वि.। मया नोपलब्धम्। ध्वनयन्-तैआ. ४,२४,१।

+√नक्(णक्) १०/५७	नाशने (प)	√नश् (णश) ४/ अदर्शने (प)।
श (काकृ-√नक्क्)	क्षी-मै-सा-च-जै-कात-शा-हे-वो।	√धक्क् (धक्क) १०/ नाशने (प)।
	नाशे—काकृ।	

छ—√नाखना*† = (१) नाशे-"खल नाखत"-सूरदासः। (२) क्षेपणे।

छ—(√ नकना*† = त्यागे।)

छ—नक्क = नाशः-(भार्गव-हिन्दी-इंग्लिश्-कोशः।

+√नट् (नट) १०/१२	अवस्यन्दने (प)	<√नड् (नड) अवस्यन्दने (प) इति नन्दी-क्षी।
श, (काकृ-√नथ् [णथ])	क्षी-मै-सा-जै-शा-हे।	
	अवस्कन्दने—काकृ।	
	अवस्पन्दने—कात।	
	नाट्ये—च।	
	भ्रंशे त्विषि च—वो।	
	हिंसायाम्—हे-वो।	
प्रयोज.	—ह्वि.।	
अवस्यन्दनम्	= भ्रंशनम्—क्षी।	
अवस्यन्दनम्	= नाट्यम्-सा १०/१२	

ग—शरसंधानं नाटयति-शाकु. ६,११। नाटयत्येष शैलः-शिशु. ४,६५।

छ—√नटना = निषेधे—"कहत नटत"-विहारी।

छ—√नाटना = निषेधे, निर्गमे।

छ—√नाटना (<नष्ट० ??) = ध्वंसे-द्रष्ट.—क्षी-,हे-वो।

+√नट् (नट) १०/२५३	भासार्थः (प)	√नड् (नड) १०/२६२ भाषार्थः (प) सा।
मै-श-च-जै-काकृ-	क्षी-हे।	
कात-शा ×	भाषार्थः—सा।	
	भ्रंशे त्विषि च—वो।	

+√नड् (नड) १०/१२	अवस्यन्दने (प) इति	<√नट् (नट) अवस्यन्दने (प)।
मै-सा-श-च-जै-काकृ-	नन्दी—क्षी।	
कात-शा ×	क्षी-हे।	
	भ्रंशे—वो।	

+√नड् (नड) १०/२६२ भाषार्थः (प) इत्यन्ये पठन्तीति स्वामी—सा । <√नट् (नट) १०/ भाषार्थः (प) ।

√नल् (नल) १८०३ भाषार्थः—सि. कौ. ।

+√नद् (णद) १०/२४९ भासार्थः (प) क्षी-शा-हे । भाषार्थः—मै-सा-जै-काकृ-कात । भासि—वो । प्रयो. शब्दे—ह्वि. ।
च×;श (जै—√मद्) मुद्रणदोषः ।

ग—(नदयन्नेति पृथिवीम्–ऋ. ९,९७,१३) सर्वतो विप्रणादितम्–वा. रा. ५,१२,४५ । तुमुलो व्यनुनादयन्–गी. १,१९ ।

छ—√नादना (प्रयो.)=वादने; शब्दे (अप्रयो.), (२) गर्जने ।

+√निवास (निवास) १०/३३२ आच्छादने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा हे । स्तृतौ—वो । √वस् २/ आच्छादने (आ) । √वास १०/३३१ उपसेवायाम् (प) । √वस् (वस) १०/ स्नेहच्छेदापहरणेषु (प) । नि+√वस् २/=√निवास १० ।
श×

अडादिरूपेषूपलब्धेष्वस्य (अलिवासयत्प्रभृति-) स्थितेः (√वस् वासादिभ्यः) पार्थक्यं ज्ञायेत ।

+√निष्क् (निष्क) १०/१५५ परिमाणे (आ) क्षी-मै-सा-जै-,काकृ (प),-कात-शा-हे । माने—वो । √निष्क् १/४१२ गतौ (आ) काकृ । निस्+√कै १/ शब्दे (प), निश्चयेन कायति=शोभते । नि+√सद्
च×,श

(षद्लृ) विशरण-
……(प)।
"नौसदेर्डिच्च"(उणा. ४३/४५) कन्।
"सदिरप्रतेः" (८/३/६६) इति षः।

ग—विभर्षि निष्कम्-ऋ. २,३३,१०; ८,४७,१२। निष्कमिव प्रतिमुञ्चत-अ.वे. ५,१४,३। चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः-मनु. ८,१३७। राजतो निष्कः-पञ्चविंत्रा. १७,१,१४। दास्यः सनिष्काः-मभार. १३,४८५४। उरस्येषां च सर्वेषां निष्काः-वा. रा. ३,९,१२। कण्ठस्थेन निष्केण-हरिवंश. १३८९२ इत्याभरणेऽपि तात्पर्यम्। साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तदा-मभार. ७,२३६५।

+√पंस्(पंसि) १०/७९ श (जै-काकृ√पंश्) | नाशने (प) क्षी-मै-सा-च-जै-कात-शा-हे। नाशे—काकृ-वो। | √पण्ड् (पडि) १०/८० नाशने (प) सा।

ग—कुलपांसनि-वा. रा. २,७३,५ (गी. प्रे. सं.)। राक्षसपांसन-मभार. १, १४४,३२। अपांसुलानां धुरि कीर्तनीया-रघु. २,२।

ङ—√पंस = मालिन्ये। पंसेइ-विसें. ३०५२।
ङ—पांसण (<पांसन०) = दूषकः-सुपा. ३४५।
ङ—पंसुला = कुलटा—कुमा.।

+√पक्ष् (पक्ष) १०/१८ मै-श-च-जै-काकृ-कात-शा× | परिग्रहे (प) इत्येके—क्षी। क्षी-मै-सा-हे-वो। | √पक्ष् (पक्ष) १/ परिग्रहे (प) इत्येके-क्षी।
पक्ष (पक्ष) १०/३८५ मै-सा-श-जै-काकृ-कात-शा-हे× | परिग्रहे (प) क्षी-वो।

ग—दिवि मे अन्यः पक्षः-ऋ. १०,११९,११।

+√पञ्च् (पचि) १०/१११ श | विस्तारवचने (प) क्षी-मै-सा-कात-शा। विस्तारे—च-जै-काकृ-हे। ततौ—वो। | √पञ्च् (पचि) १/ व्यक्तीकरणे (आ)। √पञ्च् १/३१३ g हिंसागत्योः (प) काकृ।

ग—व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमम्–गीतगोवि. १०,१३।

√पट् (पट) १०/२२० च×,श

भासार्थः (प)
क्षी-शा-हे।
भाषार्थः—मै-सा-जै-काकृ-कात।
त्विषि—वो।
प्रयो. विदारणे—ह्वि.।

√फल् (त्रिफला) १/ विशरणे (प)।
√पट्ट् १/१२५ भद्रासने (प) काकृ।

ग—पट्ट-डोरिग्रथितसुवर्णघटिकः–सार. २६७:१८ [=कौशेय-। धा. भासने वृत्तिः] पट्टराज्यः–सार. २४१:१० [=मुख्य-। धा. भासने वृत्तिः]। उत्पाटयाम्यहम्–वा. रा. ६,३७,८७। समुत्पाटयति शिंशपाम्–वा. रा. ५,३९,२३। विपाटयामास–रघु. ६,१७=विदारयामास (संजी.)।

ङ—√पाड (सक)=(विदारणे) पाडंति–सूअनि. ७९।

ङ—√फाड (सक)=विदारणे। वकृ–फाडंत–कुमा.।

ङ—√फाल (सक)=विदारणे। कवकृ–फालिज्जंत–गा. १५३; सम्मत्त. १७४।

+√पट (पट) १०/३०२ श-च×(काकृ√भट) (कात–√पठ)

ग्रन्थे (प)
क्षी-मै-सा-जै-काकृ-कात-हे।
ग्रन्थने—शा।
वेष्टने—वो।

√वृत् ६/३५ ग्रन्थे हिंसायां च (प) काकृ।
√बट् (बट) १०/ ग्रन्थे (प) सा।
√वट (वट) १०/ ग्रन्थे (प)।

ग—पटः [=वस्त्र-। धा. ग्रन्थने वृत्तिः] पैङ्गलो. १,९। वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः–वा. रा. ५,५३,६ (गी. प्रे. सं.)।

छ—पाड़=धौतवस्त्रादेः प्रान्तभागः (तूर्पः)।

+√पण्ड् (पडि) १०/८० क्षी-मै-च-जै-काकृ-शा-हे-वो×

नाशने (प)
सा।

√पंस् (पसि) १०/ नाशने (प)।
√पण्ड् १/१६८ ?, १८२ ? हिंसागत्योः (प) काकृ।

+√पण्ड् (पडि) १०/१३२ मै-सा-च-जै-काकृ-

संघाते (आ) इत्येके–क्षी
क्षी।

<√ पिण्ड् (पिडि) १०/१३२ संघाते (प)।

कात-शा-हे× संहतौ—वो। √पिण्ड् (पिडि) १/ संघाते (आ)।

+√पत (पत) १०/३०८ गतौ वा (प) √पत् (पत्लृ) १/गतौ (प)।
श-च× क्षी-मै-सा-जै-काकृ- √पट् (पट) १/ गतौ (प)।
कात-शा-हे। √पथ् (पथे) १/गतौ (प)।
ऐश्वर्यगत्योः—वो।
'ऐश्वर्ये' इत्यन्ये—क्षी।
प्रयोज. उड्डयने, पतने—ह्वि.।

ग—वयं पतयन्तः–ऋ. १,२४,६ ; मनो जविष्ठं पतयत्स्वन्तः–६,९,५।
छ—√पड़ना } =पतने।
छ—√परना }
छ—√पारना=पातने, (२) लम्बाकारेण विन्यासे, (३) विन्यासे।

+√पथ् (पथ) १०/२१ प्रक्षेपे (प) इति <√पृथ् (पृथ) प्रक्षेपे (प)।
क्षी-मै-श-च-जै-काकृ- स्वामी—सा।
कात-शा-हे-वो×

छ—√पाथना (<स्थापनम् इत्यस्माद् व्युत्पत्तिस्तत्र यत्र गोमयस्य भूस्थापनम्) =भित्त्यादौ गोमयस्य पिण्डितस्य प्रक्षेपणे।

+√पद (पद) १०/३४२ गतौ (आ) √पद् (पद) ४/ गतौ (आ)।
च×, शं क्षी-मै-सा-जै-काकृ- √पद् (पद) १/ स्थैर्ये (प)
कात-शा-हे-वो। इति कण्ठः–क्षी।
प्रयोज. ह्वि.।

[ग—शत्रूयतोऽधरान् पादयस्व–अ.वे. ६,८८,३; पादयामि–१०,५,३६।]

छ—√पदाना (प्रयो.)=(कन्दुकक्रीडायां) दूरङ्गतस्य कन्दुकस्यानयनार्थं त्वरमाणस्य बालकादेर्गतौ–बुं. ख.।

+√पन्थ् (पन्थ) १०/३९ गतौ (प) √स्पन्द् (स्पदि) १/ किञ्चिच्चलने (आ)।
श क्षी-मै-सा-च-जै-काकृ- √पथ् (पथे) १/ गतौ (प)।
कात-शा-हे।
गत्याम्—वो।

क—पेन्त्=गमने, पादविक्षेपे। पन्थाम्=पन्थानम्।
ख—अवे. पन्ताम्=पन्थानम्, मार्गम्–वा. पॉकर्नीः।

ग—चकार सूर्याय पन्थामन्वेतवा उ-ऋ. १,२४,८ ।

कदाचित् पन्था इत्यादिरूपाणि ग्धातोरेतस्मात् स्युर्व्युत्पादितानि । ७/१/८७ इति ग्थादेशस्य कल्पना परवर्तिनी ।

+√पर्ण (पर्ण) १०/३८५ शा-च ×	हरितीभावे (प) क्षी । हरितभावे— मै-सा-च-जै- काक्र-कात-शा-हे । हारित्ये—वो ।	पिपर्तीति— √पॄ+उणा. ३/६ इति नः । √वर्ण (वर्ण) १०/ वर्ण-क्रियाविस्तारगुणवचनेषु (प) ।

क—पेन् = सहसा पतने, क्षेपणे, विपर्यसने । * (पेरू) : पु. उ. ज. फर् (अ)-न् ; फर्म = सुन्दरपत्राणां पादपः । एँग्लो-सैक्सॉ. फीर्न् = सुन्दरपत्राणां पादपः-वा. पॉकर्नीः ।

ख—परून = पर्णम्, जिह्वा-वा. पॉकर्नीः ।

ग—पर्णेभिः शकुनानाम्-ऋ. ९,११२,२ । पर्णः-शब्रा. १,७,१,१ ; तैब्रा. १,१,३,१० । पर्णानि-साब्रा. २,६,११ ।

छ—पान (<पर्णम्) = छदनम् ।

+√पर्थ् (पर्थ) १०/२० मै-सा-च-जै-काक्र- कात-शा-वो ×	प्रक्षेपणे (प) क्षी-हे ।	>√पृथ् (पृथ) प्रक्षेपे (प) इत्येके-क्षी ।

छ—√पलटना (<पलठना<पलथना<परथना<पर्थना<पर्थनम्) । प्रलोठनादस्य व्युत्पत्तौ गौरवं क्लेशश्च ।

+√पल् (पल) १०/७४ सा-शा-च ×	रक्षणे (प) क्षी-मै-जै-काक्र-कात- शा-हे । रक्षे—वो ।	प्रयोजके तु "पातेर्णौ लुग् वक्तव्यः" इति चुरादेर्भेदः । √पा २/ रक्षणे (प) । √पॄ ३/ पालनपूरणयोः (प) । √पार् (पार) १०/ कर्मसमाप्तौ (प) । √पाल् (पाल) १०/ रक्षणे (प) ।

क—पेल् । लैटि. पेलुइस् = अनतिगभीरं पात्रम्-वा. पॉकर्नीः ।

ग—अनुपालयन्ती-शौ. १८,३,१ । त्वां पालयन्ति-वा. रा. २,५०,२ । राजा पालयन् प्रजाः-मनु. ७,८७ ।

ङ—√पल (अक)=प्राणने, (२) अदने। पलइ–पिंग.।

ङ—√पाल (सक)=पालने, रक्षणे। पालेइ–भग.; महा.।

छ—√पालना=रक्षणे।

+√पल्पूल (पल्पूल) १०/३४८ क्षी-मै-सा-च-जै-काकृ-कात-शा-वो× — लवनपवनयोः (प) हे। — √पल (पल) १०/२१३ लवनपवनयोः (प) काकृ। √पप्पूल (पप्पूल) १०/ लवनपवनयोः (प) हे। √पल्यूल (पल्यूल) १०/लवनपवनयोः (प)। √वल्यूल (वल्यूल) १०/लवनपवनयोः (प)।

ग—पल्पूलयति–काठ. १६,६; तैब्रा. १,३,५,२। पल्पूलयेयुः–तै.२,५,५,६। पल्पूलनम्–शौ. १२,४,९; पै. १७,१६ ९।

छ—(√पपोरना†=स्वबाह्वोर्वेष्टने, तयोः पुष्टताया निरीक्षणे च। "कंस... चल्यौ पपोरत बाँह"–व्यासः।)

+√पल्यूल (पल्यूल)१०/३२८ श-च-काकृ× — लवनपवनयोः (प) क्षी-मै-सा-जै-कात-शा-हे। लूनिपूल्योः—वो। 'लवनपतनयोः' इति दुर्गः—क्षी। — >√वल्यूल (वल्यूल) लवनपवनयोः (प) इति दौर्गाः—क्षी। √पल्युल १०/ लूनिपूत्योः (प) वो। √पल्पूल १०/३४८ लवनपवनयोः (प) हे। शेषः पूर्ववत्।

ग—पल्यूलयति–तैब्रा. १,३,५,२।

छ—√परोरना†=शूर्पेण धान्यादिपवने, शोधने–बुं. ख.।

छ—√परोरना†=अभिमन्त्रणे। मन्त्रं पठित्वा मुखवायुदाने।

√पश् (पश)१०/१८७ च-कात×,श — बन्धने (प) क्षी-मै-सा-जै-काकृ-शा-हे। बन्धे—वो। — √पष् (पष) १/ बाधनस्पर्शनयोः (उ) इत्येके—क्षी। √स्पश् (स्पश) १/ बाधनस्पाशनयोः (उ)।

√स्पश् (स्पश) १०/ ग्रहण-संश्लेषणयोः (आ) ।

क—पेकु् = कर्षणे, मेपः ।

ख—अवे. पसु = पशुः-वा. पॉकर्नीः ।

ग—पाशयेत-क. ४८,१४; [सप्र. काठ. ३५,१६ स्पाशयेत इति पाभे.] पाशः-मा. ८,२३ । पाशान्-खि. २,११,४ ।

ङ—पासग (<पाशकः) = वन्धनरज्जुः-उपपृ. १३; सुर. ४,२५० ।

छ—√फँसाना }
छ—√फाँसना } (<पाशनम्) = बन्धने, ग्रहणे ।

+ √पश (पश) १०/३०९ मै-श-च-जै-काकृ-कात-श ✕	अनुपसर्गात् (प) 'गतौ' इत्येवार्थनिर्देशात् —क्षी । क्षी-सा-हे-वो । वन्धबाधयोः स्पर्शगत्योः—वो	पूर्ववत् । √पस् (पस) १०/१८७ बन्धने (प) हे । शुभः पसं युवतीम्—तैब्रा. ३,१,१,१२ ।
+√पष् (पप) १०/१८७ मै-सा-श-च-जै-श ✕	बन्धने (प) इति दुर्गः—क्षी । क्षी-हे । बन्धे—काकृ-कात-वो । बाधे ग्रन्थे (आ)—वो ।	<√पश् (पश) बन्धने (प) । √पष् (पष) १/ बाधनस्पाशनयोः (उ) । √पाष् १/२९७ b धारणे (प) काकृ । √पस् (पस) १०/१८७ बन्धने (प) हे । √पस् (पस) १/ बाधे ग्रन्थे (उ) वो. ।

क—पेल् (ऍ) स् = शिला, पाषाणः-वा. पॉकर्नीः ।

ग—पाष्यारुजः-ऋ. १,५६,६; पाष्यः-९,१०२,१ । पाषाणः-पब्रा.४,४ । वा. रा. ५,६१,११; मभार. १,७११० । रत्नपाषकषट्कैश्च—ब्रह्मवैवर्ते, श्रीकृष्णजन्मखण्डे चतुर्थोऽध्यायः = पादाभरणविशेषः ।

+√पप (पष) १०/३०९ श-च ✕	अनुपसर्गात् (प) इति नन्दी—क्षी ।	<√पश् (पश) अनुपसर्गात् (प) ।

	गतौ—क्षी-मै-सा-जै-काकृ-कात-शा-हे। बन्धबाधयोः स्पर्शगत्योः—वो।	√पाषण्ड् १/१८३ हिंसागत्योः (प) काकृ।
+√पार (पार) १०/३५५ श-च×	कर्मसमाप्तौ (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। तीरवत् (=कर्मणां समाप्तौ)—वो।	√पॄ ३/ पालनपूरणयोः (प)।

√पॄ (प्रयोज.)—पूरणे—ह्वि.।

क—पॅर्=प्रापणे, ग्रहणे, आगमने, उत्कूर्दने—वा. पॉकर्नीः।

ग—व स्वः कामं पीपरत्—ऋ. २,२०,४। स एनं सं पारयति—तै. ३,१,१,४। नानेन सह वोढुं वयं पारयामः—भा. पु. ५,१०,४।

ङ—√पार (सक)=पारं गतौ, पूर्तौ। हेकृ—पारित्तए—भग. १२,१।

छ—√पारना*‡=सामर्थ्ये, शक्तौ।"कहइ न पारइ"—तुलसीदासः।

+√पाल् (पाल) १०/७४ मै-जै-काकृ-कात-शा×	रक्षणे (प) इति—चन्द्रः—क्षी। क्षी-सा-च-हे। रक्षे—वो।	<√पल् (पल) रक्षणे (प)। √पा २/ रक्षणे (प)।

ह्रस्ववतैवेष्टसिद्धेः, णेरनित्यत्वं बोधयति। तेन पालति, पलतीत्यपि सिद्धम्—दुर्गादासः।

ग—पितेव पालयेत् पुत्रान्—मनु. ९,१०८। त्वां पालयन्ति—वा.रा. २,५०,२०।

ङ—√पाल (सक)=पालने। पालेइ—भग.; महा.। वकृ—पालयंत—सुर. २,७,१; सं. ४९।

+√पिंस् (पिसि) १०/२५३ च×(काकृ—√पिंश्)	भासार्थः (प) इत्यन्ये—क्षी। क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात। त्विषि—वो।	√पिंस् १०/३२ d हिंसाबलदाननिकेतनेषु (प)—काकृ।

+√पिच्च् (पिच्च) १०/४० मै-सा-काकृ× (श ?)	कुट्टने (प) क्षी-च-जै-कात-शा-हे । छेदे—वो ।	√पछ् १०/३६ c कुट्टने (प) काकृ । √पिञ्छ् १०/३६a कुट्टने (प) काकृ । √पुछ् १०/३६b कुट्टने (प) काकृ ।

ग—साम्थि तत् पिच्चितं विद्यात्–सुश्रु. २,१९,४ ।
ङ—पिच्चिय (<पिच्चितम्) कुट्टितं वल्कलम्–ठा. ५,३–पत्र. ३३८ ।
छ—√पीचना (<पिच्चनम्)=कुट्टित्वाऽन्तरंशस्य बहिर्निष्कासने । कुट्टने ।
छ—√फीचना=वस्त्रविपोथने, कुट्टने ।

+√पिच्छ् (पिछ) १०/४२ क्षी-श-च-जै-कात-शा-हे-वो×	कुट्टने (प) मै-सा-काकृ।	√पिच्च् (पिच्च) १०/ कुट्टने (प) शेषः पूर्ववत् ।

छ—√पीछना=वस्त्रविपोथने, कुट्टने ।

+√पिज् (पिज) १०/३३ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	हिंसाबलादाननिकेत-नेषु (प) इति शाकटायनः—सा ।	√पिच्छ् (पिछ) १०/ कुट्टने (प) । शेषः पूर्ववत् ।
+√पिञ्ज् (पिजि) १०/३० श	हिंसाबलादाननिकेत-तनेषु (प) क्षी-मै-सा । हिंसायाम्—च । हिंसाबलिदाननिकेत-नेषु—जै । हिंसाबलदाननिकेत-नेषु—काकृ-कात-शा-हे । भा-षट्टार्थे (षट्टार्थे=निकेतने हिंसे बले दाने)—वो ।	पूर्ववत् । कपिञ्जलः·····गमनीयं शब्दं पिञ्जयतीति वा—निरु. ३,१८,८–पिञ्जयति = अभिव्यनक्ति—दुर्गाचार्यः ।

ङ—√पिंज=तूलशोधने, भृशं ताडने । पिंजंत–पिंड. ५७४; ओघ. ४६८ ।
छ—पिंजड़ा (<पिञ्जरम्) ।

+√पिञ्ज् (पिजि) १०/२२५ च×,श	भासार्थः (प) क्षी-शा-हे । भाषार्थः—मै-सा-जै-काकृ-कात । भाषद्दार्थे—वो ।	√पिञ्ज् (पिजि) १०/ हिंसा-बलादाननिकेतनेषु (प) । √पिञ्ज् (पिजि) २/ अव्यक्ते शब्दे (आ) । √पिंस् (पिसि) १०/ भासार्थः (प) ।

ग—पिञ्जरोऽथ महाभद्रः-मा. पु. ५५,९=सुमेरुपश्चिमपार्श्वस्थपर्वतविशेषः ।

ङ—पिञ्जर=(१) पीतरक्तवर्णः, रक्तपीतमिश्रितं रङ्गम्-गउड.; कुप्र. ३०७ ।

ङ—√पिंजर (सक)=रक्तपीतमिश्रितपीतवर्णकस्य करणे-सर्ण. ।

+√पिण्ड् (पिडि) १०/१३२ च×,श	सङ्घाते (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे । संहतौ—वो ।	>√पण्ड् (पडि) संघाते (प) इत्येके—क्षी । √पिण्ड् (पिडि) १/ संघाते (आ) ।

ग—संपिण्डयति यः कालः-मभार. १२,८३१० । संख्यामेकत्र पिण्डयेत्-सूर्यस. १,२३ । पटुपतत्पिण्डितार्कप्रभायाम्-कथासरि. २६,२८३ ।

+√पिल् (पिल) १०/७० सा-श-च-जै×	क्षेपे (प) क्षी-मै-काकृ-कात-शा-हे । तुदि—वो ।	√पील् (पील) १/ प्रतिष्टम्भे (प) । √पिपील् १/२४८ f चलने (प) काकृ । √पेल् (पेल) १/ गतौ (प) । √फेल् (फेल) १/ गतौ (प) ।

ङ—√पेल्ल (सक)=क्षेपणे । कर्म.-पेल्लिज्जइ-उव. ।

ङ—√फेल (सक)=क्षेपणे, (२) अपाकरणे । फेलदि-शौ.;—संकृ-फेलिअ-नाट. ।

छ—√पेलना=प्रेरणे, (२) क्षेपणे, अपनोदने-"राज मराल कौ बालक पेलि कै पालत लालत खूसर को"-तुलसीदासः । पीडधातोरस्य व्युत्पत्तिर्न युक्ता ।

+√पिस् (पिस) १०/३२ श-च× (जै—√पिश्) (काकृ—√पिंस्)	गतौ (प) क्षी-मै-सा-च-जै-काकृ । हिंसाबलिदाननिकेतनेषु —जै ।	√पिस् (पिसृ) १/ गतौ (प) । प्र+√इष्=प्रेषयति ।

हिंसाबलदाननिकेतनेषु
—काक्-कात-शा-हे.।
गत्यां षट्टार्थे—वो।

ङ—√पेसव (<प्र+एषय्?)=प्रेषणे। कृ-पेसवेयव्व-उप. १३६ टी.।
ङ—√पेस (सक.)=प्रेषणे, प्रस्थापने। पेसइ, पेसेइ-भवि.; महा.।

+√पीड् (पीड) १०/११ शः गहने (प) क्षी-जै-शा-हे। अवगाहने—मै-सा-काक्-कात। 'अवगाहने' इति दुर्गः—क्षी (यु. मी. सं.) बाधायाम्—च। बाधगाहे—वो। प्रयो.—ह्वि.। गहनम्=बाधा—क्षी। √पीड् १/१५५ व्यथायाम् (प) काक्.। √पील् (पील) १/ प्रतिष्टम्भे (प)।

ग—पीड़य-शौ. १२,११,९। पीडयानि-जैउ. १,२,१,३; अपीळयन्-३,४,५,२। अपीडयत्-गोब्रा. १,२,२१।

ङ—√पीड (सक)=(१) व्यांकुलत्वे, (२) दमने। पीडइ-पिंग.।
ङ—√पिड्ड (सक)=पीडने। पिड्डइ-आचा.; पि. २७९।
ङ—√पिट्ट (सक)=पीडने। पिट्टंति-सूअ. २,२,५५।
ङ—√पिल (सक)=पीडने। कर्म-पिलिज्जइ-नाट.।
ङ—√पील (सक)=पीडने। पीलइ, पीलेइ-पि. २४०।

+√पुंस् (पुंस) १०/९६ शः-च× अभिमर्दने (प) क्षी-काक्-कात-हे। अभिवर्द्धने—मै-सा-जै-शा। मर्दे—वो। प्र+√उञ्छ्=प्रोञ्छय्। पुंस्, >पुमंस् (पुमान्)।

ङ—√पुंस (सक)=मार्जने, प्रोञ्छने। पुंसण-कुमा.।

+√पुच्छ (पुच्छ) १०/३९१ शः-च-जै-काक्-कात-शा-हे-वो× उदसनादौ (आ) क्षी-मै-सा।

पुच्छादिषु धात्वर्थ इति सिद्धम्-क्षी। पुच्छभाण्डचीवराण्णिङ् ३/१/२०।
ग—पुच्छस्योद्दीपनेन च-वा. रा. ५,५३,१५ (गी. प्रे. सं.)।
छ—पूँछ (<पुच्छः)।

+√पुट् (पुट) १०/७८
मै-सा-श-च-जै-काकृ-
कात-शा-हे ×

संचूर्णने (प)
क्षी।
चूर्णे भासि—वो।

√पुट् (पुट) १०/ भासार्थः (प)।
√पुट् (पुट) ६/ संश्लेषणे (प)।
√पुण्ड् (पुडि) १/ मर्दे (प) वो।

ङ—√फोड (सक) [<स्फोटय् ?]=विदारणे, संचूर्णने। राजिकादिना शाकादेर्व्याघारणे। फोडेज्ज—कुप्र. ६७।

छ—√फोड़ना (<स्फोटनम् ?)=संचूर्णने, विदारणे। √पुट्, √स्फुट् इत्युभयोः संक्रान्तिः।

+√पुट् (पुट) १०/२२१
च ×, श

भासार्थः (प)
क्षी-शा-हे।
भाषार्थः—मै-सा-जै-
काकृ-कात।
चूर्णे भासि—वो।

√पुट्ट् (पुट्ट) १०/ अल्पीभावे (प) इत्येके—क्षी।
शेषः पूर्ववत्।

+√पुट (पुट) १०/३५६
क्षी-श-च-जै-शा ×
प्रयो.

संसर्गे (प)
मै-सा-काकृ-कात-हे-वो।
उन्मानादौ—ह्वि.।

√पुट् (पुट) ६/ संश्लेषणे (प)।
शेषः पूर्ववत्।

च—√संपुड (सक)=सम्बन्धे, संयोजने। संपुडइ-भवि.।
च—पोटलुं=पोटलिका—गुर्जरभाषा।
छ—पुड़िया (<पुटिका)। पुड़ा (<पुटः)।

+√पुट्ट् (पुट्ट) १०/२४
जै-शा ×, श

अल्पीभावे (प)
इत्येके-क्षी।
क्षी-मै-सा-च-काकृ-
कात-हे।
तौच्छ्ये—वो।

<√चुट्ट् (चुट्ट) अल्पीभावे (प)।

ङ—पुट्टल=पोटलिका, ग्रन्थिः-सम्मत्त. ६१।
ङ—पुट्टलिया=लघ्वी पोटलिका-सुपा. ४२; ३४४।
छ—पुटरिया (<पुट्टलिया<पोटलिका)-बुं. ख.।

+√पुण् (पुग) १०/१०२ क्षी-मै-श-च-जै-कात-शा-हे-वो×	संघाते (प) सा-काक्रु।	<√पूल् (पूल) संघाते (प)। √पुट १०/३५६ संसर्गे-मै। √पूर्ण् (पूर्ण) १०/संघाते (प)। √पूण् (पूण) १०/संघाते (प)। √पूण् १०/२०७y शब्दे (प) काक्रु।

पुरुषकारे तु "-'पुर्ण' इति स्वामी, 'पुण' इति शाकटायनः"-इत्युक्त्वा "कोशसिद्धिस्त्वीदृशेऽर्थे कीदृशीति न विद्मः"-इत्युपहसितम्-सा। अस्माकं मतेन तु देशभेदेन भिन्नतां प्राप्ता धातव इमे सर्वे कोशसिद्धा एव।

+√पुण्ट् (पुटि) १०/२५७ क्षी-मै-श-च-जै-काक्रु-कात-शा-हे-वो×	भाषार्थः (प) स्वामिकाश्यपानुसारेण—सा।	√पुट् (पुट) १०. भासार्थः (प)।
+√पुथ् (पुथ) १०/२४६ च×, श (काक्रु-√पुघ्)	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काक्रु-कात। त्विषि—वो।	√पुथ् (पुथ) ४/ हिंसायाम् (प)। √पुट् (पुट) १०/२२१ भासार्थः (प)।

ग—यथा विवाहोत्सवतूर्यनादानपोथयन् दुन्दुभयोऽन्तरीक्षे-कथासरि. ३४, २५७ (भाषार्थः)।

+√पुल् (पुल) १०/६५ काक्रु-कात-शा×	समुच्छ्राये (प) क्षी-हे। महत्त्वे—मै-सा-च। समुच्चये—जै। समुच्छ्रितौ—वो।	√पुल् (पुल) १/ महत्त्वे (प)। √पुर् (पुर) ६/ अग्रगमने (प)। √पुल् १/२४७ jj गतौ (प) काक्रु। √पुल्ल् १/२४७ kk गतौ (प) काक्रु। √चुल् (चुल) १०/ समुच्छ्राये (प) मै-सा।

भ्वादौ क्षीरस्वामी "पुल महत्त्वे" इत्यत्र प्रतिज्ञातवान्–"चुरादौ पोलयतीति।" एवं सत्यपि स चुरादौ महत्त्वार्थकं पुल धातुं न पठित्वा समुच्छ्रयार्थकमेव पठति। मै-सा-चन्द्रास्तु चुरादौ महत्त्वार्थकमेव पठन्ति। समुच्छ्रयार्थे च चुल धातुं नियोजयतो मैत्रेयसायणौ। प्रतीयते चुलधातुमेव 'पुल' इत्यवगतवन्तः क्षीरस्वाम्यादयः, चकारादधस्तनपङ्क्तेर्घृष्टत्वात् तद्ध्रस्वतया पकारभ्रान्तेर्वा।

ग—पुलाकः=तुच्छधान्यम् (पोलति=उच्छ्रितो भवतीति) यथा मनुः—"पुलाकाश्चैव" १०,१२५। पुलाका–यशस्ति. च., ३ आश्वा., ७८ श्लो.=घुर्घुरिका।

+√पुष् (पुष) १०/२१८ च-शा×,श	धारणे (प) क्षी-मै-सा-जै-काक-कात-हे। धृतौ—वो। प्रयो.—वृद्धौ—ह्वि.।	√पुष् (पुष) १/ पुष्टौ (प)। √पुष् (पुष) ४/ पुष्टौ (प)। √पुष् (पुष) ९/ वृद्धौ (प)। √पूष् (पूष) १/ वृद्धौ (प)। √पुष् १/२८६ वृद्धौ (प) काक।

ग—पोषयाति–पै. २,१३,१। पोषयति–शांब्रा. ५,५। पोषयेत्–योशि. १,१२२।
ङ—√पोस=(१) पुष्टौ, (२) पालने। पोसेइ–पंचा. १०,१४।

+√पुस्त् (पुस्त) १०/५४ च-शा×,श	आदरानादरयोः (प) क्षी-मै-सा-जै-काक-कात-हे। संघाते—मै। वन्दे नादृत्यादृत्योः—वो।	√बुस्त् (बुस्त) १०/ आदरानादरयोः (प)।

चित्रपुस्तादिकोविदान्–कथासरि. ३४, १७२। पुस्तमय०–सुश्रु. १,२९,९।
ङ—पुत्थ (<पुस्तम्)=लेप्यादिकर्म।
ङ—पोत्थ (<पुस्तम्)=वस्त्रम्–णाया. १,१३–पत्र. १७९।
छ—√पोतना (<पुस्तनम्)=लेप्यादिकर्मणि। प्लुतशब्दादस्य व्युत्पत्तिर्भृशमसंगता।

छ—पोथा, पोथी।

पुस्तकादिलेखने समादरः। गृहादिलेप्यादिकर्मणि न तथेत्यादरानादरौ संगतौ।

+√पुस्त् (पुस्त) १०/९७ क्षी-सा-श-च-जै-काक-कात-शा-हे-वो×	संघाते (प) मै।	√मुस्त् (मुस्त) १०/ संघाते (प)।

+√पूज् (पूज) १०/१०२ श | पूजायाम् (प) क्षी-मै-सा-च-काक्ृ-कात-शा-हे। पूजने—वो। प्रयो.—ह्वि.। | पूजयति-निघ. ३/१४= अर्चतिकर्मा।

ग—पूजयति-बिल्वो. ३२। पूजयेत्-मैत्रेय्यु. २,१; योशि. ५,५७।

ङ—√पुज्ज (सक)=पूजने, आदरे। पुज्जइ-कुप्र. ४२३; भवि.।

ङ—√पूअ (सक)=पूजने। पूएइ-महा.। पूयंत-सुपा. २२४।

छ—√पूजना=पूजायाम्।

+√पूर् (पूरी) १०/२५४ च×,श | आप्यायने (प) क्षी-मै-सा-जै-काक्ृ-कात-शा-हे। पूर्तौ—वो। प्रयो.—ह्वि.। | √पॄ ३/ पालनपूरणयोः (प)।

ग—उदपात्रं पूरयित्वा-शब्रा. १४,९,४,१८। पूरयामास पांशुना-वा. रा. २,७७,११। तुलां पूरयेतेऽशनैः-मभार. १३,२०७१।

ङ—√पूर (सक)=पूर्तौ। पूरइ, पूरए-औप.; भग.; महा.; पि. ४६२।

छ—√पूरना=पूर्तौ।

+√पूर्ण् (पूर्ण) १०/९५ मै-श-च-जै-काक्ृ-कात-शा-हे-वो× | संघाते (प) इत्येके-क्षी। क्षी-सा। | √पूल् (पूल) १/ संघाते (प)। √पूल् (पूल) १०/ संघाते (प)। √पुण् (पुण) १०/९१ संघाते (प) जै। √पुण् (पुण) १०/ संघाते (प) सा,-काक्ृ। √पॄ ३/ पालनपूरणयोः (पं)+क्षे।

ङ—पुण्ण (< पूर्णम्)=पूर्णम्-औप.; भग.; उवा.।

+√पूर्व् (पूर्व) १०/१२७ च-जै-शा-हे×	निकेतने (प) पारायणे-क्षी क्षी-मै-सा काकृ-कात-वो।	<√पॄ ३/ पालनपूरणयोः (प)। √पूर्व् (पूर्व) १/ पूरणे (प)।
+√पूल् (पूल) १०/९५ च-जै-काकृ-कात शा-हे×.	संघाते (प) क्षी-मै-सा। संहतौ—वो।	<√पूल् (पूल) १/ संघाते (प)। शेषः-√पूर्ण् (पूर्ण) १०/ संघाते (प) वत्।
+√पॄ १०/१५ मै-सा-च-जै-काकृ×श, प्रयो.	पूरणे (प) इति दुर्गः-क्षी क्षी-कात-शा-हे। पूर्तौ—वो। —ह्वि.।	<√पॄ पूरणे (प)। √पॄ ३/ पालनपूरणयोः (प)। √पार् (पार) १०/ कर्मसमाप्तौ (प)।

ग—ज्या इयं समने पारयन्ती-ऋ. ६,७५,३। पारयतु प्रतिज्ञाम्-मभार. ७, २७८७; पारयिष्याम्यहं व्रतम्-३,१६७१९; वा. रा. २,५५,१९।

+√पृच् (पृच) १०/२५० च×,श(क्षी—√पृच् [पृची].) १०/२५८	संयमने (प) मै-सा-जै-काकृ-कात-शा। संयमने संपर्के—वो-पक्षे—भ्वा.। सम्पर्चने—क्षी हे। 'सम्बन्धने' इति क्षीरस्वामी इति पुरुषकारः—५२ पृ.।	√पृच् (पृची) २/ सम्पर्के (आ)। √पृच् (पृची) ७/ सम्पर्के (प)।

ग—[पृचन्ति सु वां पृचः-ऋ. ५,७४,१० तौदादिकः।]

+√पृथ् (पृथ) १०/२० च×,श	प्रक्षेपे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो। प्रक्षेपणे—शा।	द्रष्ट. √प्रथ् १०/१९।

ग—पृथक्-ऋ. १,१५७,१। न पृथेन न मुष्टिना-शब्रा. १२,७,३,१। पृथा=कुन्ती। पृथुः=राजविशेषः।

+√पॄ १०/१५	पूरणे (प)	>√पृ पूरणे (प) इति दुर्गः–क्षी।
श-च-कात-शा ×	क्षी-मै-सा-जै-काकृ- हे ।	√पॄ ३/ पालनपूरणयोः (प) । √पॄ ९/ पालनपूरणयोः (प) ।
..	पूर्तौ—वो ।	√पार् (पार) १०/ कर्मसमाप्तौ (प) ।

√पॄ—प्रयो.—ह्वि. ।

ग—पारयति–तांब्रा. १६,८,८ । पारयते–शब्रा. १८,८,३,३ ।

ङ—√पार=पारङ्गतौ, पूर्तौ । हेक्कु–पारित्तए–भग. १२, १ ।

+√प्रथ् (प्रथ) १०/१९	प्रख्याने (प)	√पथ् (पथ) १०/२१ प्रक्षेपे (प) सा ।
क्षी-च-जै-काकृ- कात ×, श	मै-सा-शा-हे । प्रक्षेपे ख्यातौ—वो । प्रयो. प्रसारणे—ह्वि. ।	√पृथ् (पृथ) १०/२० प्रक्षेपे (प) । √पृथ् (पृथ) १/ प्रख्याने (आ) सा । √पाथ् १०/८६ प्रक्षेपणे(प) हे। √प्रथ् १०/८७ प्रक्षेपणे(प) हे । √प्रथ् १/३१३ प्रख्यातौ (आ) जै ।

ग—अवस्था वस्तूनि प्रथयति च सङ्कोचयति च–नी.श. ४५=विस्तारयति, गुरूकरोति च । (प्रयोजकतेह नास्ति) ।

+√प्री (प्रीञ्) १०/२८३	तर्पणे (उ) आधृषाद्वा	√प्री (प्रीङ्) ४/प्रीतौ (आ)।
श-च ×, काकृ ?	क्षी-मै-सा,-काकृ (प)- कात-शा.-वो (प) । तृप्तौ—जै-हे ।	√प्री (प्रीञ्) ९/ तर्पणे कान्तौ च (उ) ।
प्रयो.	—ह्वि. ।	

ग—प्रीणयन्ति–खि. १,२,९ । (श्राद्धदेवताः) प्रीणयन्ति मनुष्याणां पितॄन्–याज्ञ. १,२६८ । सम्यक् संप्रीणयन्–मार्क.पु. २८,१९ ।

ङ—√पीण (सक)=प्रसादने । कु–पीणणिज्ज (<प्रीणनीयं–)–औप.; कप्प.; पण्ग. १७ ।

+√प्रेङ्खोल (प्रेङ्खोल) १०/६४,३८५ लोकात्-क्षी। प्र+√इङ्ख् (इखि) १/
मै-सा-श-च-जै-काकृ- चापले—वो। गत्यर्थः (प)। ओलचि
कात-शा-हे× प्रत्यये=प्रेङ्खोल इति
वागीशः।
प्रेङ्खदोल—√प्रेङ्खोल—वागीशः।

ग—[प्रेङ्खं हिरण्ययं शुभे कम्—ऋ. ७,८७,५। प्रेङ्खमारुह्य होता महदुक्थमनुशंसति-काठ. ३४,५।] विरेचनप्रेङ्खोलन०-सुश्रुते निदानस्थाने ८ अध्याये (श.क.द्रु.)।

ङ—√पेंखोल (अक)=दोलने, स्पन्दने-णाया. १,१-पत्र. ३१।

ङ—√पिंखोल (सक)=दोलने। वक्त-पिंखोलमाण-राज.।

+√बंह् (बहि) १०/२३८ भासार्थः (प) बंहयते-मै. २,१,५; काठ.
मै-सा-श-च-जै-काकृ- क्षी। ११,५=वृद्धौ।
कात-शा-हे×(वो)

+√बट (बट) १०/३१५ ग्रन्थे (प) <√बट ग्रन्थे (प)।
क्षी-मै-श-च-जै-काकृ- बहवः पठन्ति—सा। √बट् (बट) १/२०६ a परि-
कात-शा-हे-वो। भाषणे (प) शा।
√वृत् ६/३५ ग्रन्थे हिंसायां
च (प) काकृ।
√वट् (वट) १/ वेष्टने (आ)।
√वट् (वट) १/ परिभाषणे
(प) मित्।

छ—√बटना=ग्रन्थे, वेष्टने (रज्ज्वादेः)।

+√बध् (बध) १०/१४ संयमने (प) >√बन्ध् (बन्ध) संयमने (प)
च-शा×(जै— क्षी-मै-सा-जै-काकृ- इति चान्द्राः—क्षी।
√बध्) कात-हे। √बध् (बध) १/ बन्धने (आ)।

ग—स बाधयति लोकांस्त्रीन्-वा. रा. १,१४,१५। यत्रोभौ बाधयिष्यथः-हरिवंश. ५३२६।

√बन्ध् (बन्ध) १०/१४ संयमने (प) इति पूर्ववत्।
मै-श-च-जै-काकृ-कात× चन्द्रः—क्षी। √बन्ध् (बन्ध) ९/ बन्धने
क्षी-सा-शा-हे। (प)।
प्रयो. ह्वि.।

ग—बन्धयामि–वनदुर्गो. ४३४:२१। बन्धयेत्–नबि. ७५; योशि. ५,२८; बन्धयिष्यति वा पाशैः–वा. रा. २,८४,४; (शब्रा. १३,५,४,४–अश्वं बन्धयति ?)।

छ—√ बाँधना = संयमने।

+√ वर्ह् (वर्ह) १०/१२४ श-च-जै-वो×	हिंसायाम् (प) क्षी-मै-सा-काकृ-कात-शा-हे।	√ वर्ह् (वर्ह) १/ परिभाषणहिंसादानेषु (आ)। √ बर्ह् (बर्ह) १/ प्राधान्ये (प)।

+√ बर्ह् (बर्ह) १०/२४४ च-काकृ×(मै-सा-काकृ-कात-हे-वो—√ वर्ह्)	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-कात। दीप्तौ—वो।	√ बल्ह् (बल्ह) १०/ भासार्थः (प)।

ग—यथा ब (व)र्हाणि चित्राणि–मभार. १२,४३५४ (भासार्थः)।

छ—√ बलेना }
छ—√ बरना } (<बर्हणम्) = ज्वलने, अर्चिःक्षेपणेन सह ज्वलने (भासार्थः)।

ज्वलन->वलन->वलना>बरना—इत्यपि व्युत्पत्तिः।

छ—बहराना (<बहरना<बरहना>बर्हणम्) = दुःखविस्मरणाय चित्तप्रसादाय च तथाभाषणे (भाषार्थः)।

+√ बल (बल) १०/८९ श-च-जै-काकृ-कात-शा-हे×	प्राणने (प) मित् क्षी-मै-सा। जीवने—वो।	√ बर्ह् (बर्ह) १०/ भासार्थः (प)। √ बल १०/ नीरूपणे (आ) वो। √ बल् १/ दाने वधे नीरूपणे (आ) वो।

ग—बलवान्–मनु. २,२१५।

छ—√ बलना (<बलनम्) इयमपि व्युत्पत्तिः शक्यते भवितुम्, प्राणनार्थकस्य ज्वलनार्थकत्वात्। ज्वलने सति प्राणनम्, निरुप्तौ सत्यां निष्प्राणतेति।

+√ बल्ह् (बल्ह) १०/२४५ च×(मै-सा-श-जै-कात-हे-वो-√ बल्ह्)	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात।	√ बर्ह् (बर्ह) १०/ भासार्थः (प)।

ग—गच्छ बल्हिकान्-अ.वे. ५,२२,७।

छ—√बहलाना (<बहलना<बलहना<बल्हनम्)=दुःखविस्मरणाय चित्तप्रसादाय च तथाभाषणे।

√बष्क (बष्क) १०/३६९ क्षी-मै-सा-च-काक्र-कात-शा-हे-वो×
(जै√बष्क् १०/१६५)
दर्शने (प) सा-जै।

√बष्क् १/४१२ गतौ (आ) काक्र।
√व्लेष्क (व्लेष्क) १०/ दर्शने (प)।

ग—वत्से बष्कयेऽधि सप्त......ऋ. १,१६४,५।
छ—√बकसना*(फा. बख्श)=सकृपं दाने। क्षमायाम्।
छ—बकसा=घासविशेषः पशूनामतिरुचिप्रदः (देश.)।

+√बस्त् (बस्त) १०/१५२ श-च×(जै-काक्र-कात-हे-वो—√वस्त्)
अर्दने (आ) क्षी-मै-सा-जै-काक्र-कात-शा-हे।

ग—श्वानं बस्तो बोधयितारमब्रवीत्-ऋ. १,१६१,१३; वा. सं. १४,९; शब्रा. १४,४,२,९। बस्ताजिन०-कात्या. श्रौ. १४,५,१५।

ङ—वत्थि (<वस्तिः)=दृतिः-भग. १,६,१८,१०; णाया. १,१८; गुदम्-पण्ह. १,३-पत्र. ५३; छत्रावयवविशेषः (शलाकासंयमनस्थानम्)-औप.।

+√बिल् (बिल) १०/७१ श ?, च-जै-काक्र-कात×
भेदने (प) क्षी-मै-सा। भेदे—शा-हे-वो।

√भिल् (भिल) भेदने (प) इति कौशिकः-क्षी। बिलं भरं भवति बिभर्तेः -निरु. २,१७,१। बिलमं भिल्मं भासनमिति वा-निरु. १,२०,२। बिलमम्-भिलमम्=भेदनम् —दुर्गाचार्यः।

ग—द्रष्ट. √बिल् (बिल) ६/ भेदने (प)।

√बुक्क् (बुक्क) १०/१८१ च×,श (मै-जै—√बुक्क्)
भाषणे (प) क्षी-सा-कात। भाषणे भषणे च—काक्र।

√बुक्क् (बुक्क) १/ भाषणे (प)। 'भषणे'इत्येके-क्षी।

आभाषणे—शा-हे ।
श्वादिशब्दे—वो ।

ग—वुक्कम् (बुक् बुक् इत्यव्यक्तं शब्दं करोतीति)=वक्षोऽभ्यन्तरमांसविशेषः । वुक्करायनृपतिः (विजयनगर-(विद्यानगर-)-पीटर्सबर्गकोशात् । बुक्काघातैर्युवति-निकटे प्रौढवाक्येन राधां-उद्भटसा. ।

+√बुल् (बुल) १०/६६ निमज्जने (प) मै-सा-श-च-जै× क्षी,-काक्र ?-कात-शा-हे । मज्जने—वो । प्रयो. टीकायामुपलम्भात् कृत्रिमोऽयं धातुः —ह्वि. ।

√बुल् १/२४७ll सेचने (प) काक्र । ४९५ ?
√बुल्ल् १/२४७mm सेचने(प) काक्र । २९५ ?

क—बॉल् ,बुल्=पिण्डः । लैति. बुल्ल=गर्तम्, चर्मस्फोटः, कलिका । लिथु.-बुलिस्=बुलिः (हेम. ३,२७३) (>बुरी-हि.)=भगम् (नितम्बः) । म. नि. ज. पॉल्ल्=शिरोभागः (कस्यापि पदार्थस्य), [वराङ्गम्]-वा. पॉकर्नीः ।

ग—बोलयति-कात्या. श्रौ. ५,५,३० । बुल्व०-शब्रा. ११,५,४,१४ ।
ङ—√बोल (सक)=निमज्जने । बोलइ-सार्ध. १४४ ।
छ—√बोरना†=निमज्जने ।
छ—√बूरना*‡=निमज्जने ।
छ—√बूड़ना=निमज्जने । महाराष्ट्रि.-बूल्ना (णॅ) ।
छ—√डूबना (वर्णविपर्ययः)=निमज्जने ।

+√बुस्त् (बुस्त) १०/५५ आदरानादरयोः (प) जै-काक्र-कात×,श (मै-√वुस्त्) क्षी-मै-सा-शा-हे । 'बन्धने' इति चन्द्रः-क्षी । वञ्चने—च । आदृतौ—वो ।

√बुस् (बुस) ४/ उत्सर्गे (प) ।
√पुस्त् (पुस्त) १०/ आदरानादरयोः (प) ।

√पुस्त्>√बुस्त् इति विकासः ।

छ—बूथड़ी=आकृतिः, मुखाकृतिः (क्रयविक्रयसहायकानां ['दलाल' इत्य-भिधेयानाम् इति हिन्दी] भाषा (देश.) ।

+√बृंहू (बृहि) १०/२५३ भासार्थः (प) च×,श (मै-सा-जै- क्षी-शा-हे ।

√बंहू (बहि) १०/ भासार्थः (प) ।

कात-त्रो-√बृंह्) भाषार्थः—मै-सा-जै-
काकृ-कांत।

ग—बृंहयति-अशि. ४,१४; अथर्वशिखो. २; शाण्डिल्यो. ३,१; वटुको.[१८] ३१६:७। बृंहयेत्-बृजा. ३,१७=वृद्धौ ?` निबृंहयति-महाभाष्ये ६,४,२४,१९४।

+√ब्रीस् (ब्रीस) १०/१२३ हिंसायाम् (प)
मै-सा-श-च-जै-काकृ-
कात-शा-हे ×
(वो-√ब्रीस्)
क्षी।
>√ब्रूस् (ब्रूस) हिंसायाम् (प) इत्येके—क्षी।

+√ब्रूस् (ब्रूस) १०/१२३ हिंसायाम् (प)
च-जै-काकृ-कात ×, श
(वो—√(ब्रूस्)।
इत्येके—क्षी।
क्षी-मै-सा-शा-हे।
<√ब्रीस् (ब्रीस) हिंसायाम् (प)।
√बूष् १०/४४६ हिंसायाम् (प) काकृ।
√ब्रूष् १०/५१ हिंसायाम् (प) कात।

+√ब्लेष्क (ब्लेष्क) १०/३५७ दर्शने (प).
मै-सा-श-च-जै-काकृ-
कात ×
(शा—√ब्लेष्क्)
(वो—√ब्लेष्क्)
क्षी-शा-हे।
दृशि—वो।
वि+√लक्ष् (लक्ष) १/ दर्शनाङ्कनयोः (आ)।
√वष्क (वष्क) १०/ दर्शने (प) सा।
√विष्क (विष्क) १०/ दर्शने (प) मै-सा।

ग—अप्सु ब्लेष्केण, अन्येन मृत्युना-काठ. २३,६; ब्लेष्कोऽसि निर्ऋत्याः पाशः-३७,१३।

+√भक्ष् (भक्ष) १०/२२ अदने (प)
च ×, श
क्षी-मै-सा-जै-काकृ-
कात-शा-हे।
भक्षणे—वो।
प्रयो.—ह्वि.।
√भज् (भज) १/ सेवायाम् (उ)।

ग—भक्षयति-तै. ६,४,९,४; शौ. ९,११,७—११; तैब्रा. १,४,१०,७।
ङ—√भक्ख (सक)=भक्षणे। भक्खेइ-महा.। कर्म.-भक्खिज्जइ-कुमा.।

छ—√भकना } =भक्षणे (बुं. ख.)।
छ—√भखना }

+√भज् (भज) १०/२०१ विश्राणने (प)। क्षी-मै-सा-जै-काकृ-कात-शा-हे। पाके—वो।
चX,श

√भज् (भज) १/ सेवायाम् (उ)।
√भञ्ज् (भञ्जो) ७/ आमर्दने (प)।

प्रयो.—ह्वि.।
विश्राणनम्=दानम्—क्षी।
विश्राणे ='विवेचने' इत्यन्ये—क्षी।

ख—अवे. बख्शइति=(भक्षयति)=ददाति-अवे. यस्न९, २२ [राजा चिद् यं भगं भक्षीत्याह-ऋ. ७,४१,२=दाने]। पारस्य.-बख्शीदन, (बख्शना, बख्शीश्)-'अवेस्ता'।

ग—पुष्पभाजनम्-शाकु. ४ (मुम्बा. सं.)। भाजनं विश्वमूर्ते-मालतीमा. १,३।

घ—भजति (=विभाजने)-सुत्तनिपात ९५८; जातक १,२१६,=३,५१०। भाजेति-विनय. ४,२२३।

+√भञ्ज् (भजि)१०/२५३ भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात। भासि—वो।
चX,श

पूर्ववत्।

+√भण्ड् (भडि) १०/५२ कल्याणे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।
श(काकृ—√भन्द् [भदि])

√भण्ड् (भडि) १/ परिभाषणे (आ)।
√भन्द् (भदि) १/ कल्याणे (आ)।
√भन्द् (भदि) १०/ कल्याणे (प) इति दुर्गः—क्षी।

ग—भण्डीरः [=कल्याणे वृत्तिः]=वटः-सार. २५५,४; वा. रा. ३,७५,२४।
ङ—√भंड (सक)=[साधूनां भोजनोत्सवादौ] संग्रहे। भंडेइ-सुख. २,४५।

+√भन्द् (भदि) १०/७९ कल्याणे (प) इति
मै-सा-श-च-जै-काकृ- दुर्गः—क्षी।
शा× क्षी-कात-हे।
शुभे—वो।

√भण्ड् (भडि) १०/५२ कल्याणे (प)।
√भन्द् (भदि) १/ कल्याणे (आ)।

+√भर्त्स् (भर्त्स)१०/१५० संतर्जने (आ)
श-च× क्षी-मै-सा-जै-काकृ-कात-
शा-हे।
भर्त्से—वो (उ)।
प्रयो.—द्वि.।

क—भेर्ध् (अथवा-भ्रेध् (?)=छेदने-वा. पॉकर्नीः।

ग—भर्त्सनात्-सिशि. ३८१:१६। भर्त्सयन्ति स्म वैदेहीम्-वा.रा. ५,२५,१३। त्वा भर्त्स्यामि दूषयिष्यामि-अ. वे. ३,९,५ (पाठदोषः)। उदभर्त्सत-शांब्रा. १२,२३,१। परिभर्त्सन्ती-मभार. ३,१६१४१। लक्ष्ये भर्त्सयतीति दृश्यते-क्षी।

छ—भर्सन*† (<भर्त्सनम्)=निन्दा।

+√भल् (भल) १०/१६९ आभण्डने (आ)
श-काकृ ?,च× क्षी-मै-सा-जै-काकृ-कात-
शा-हे।
नीरूपणे—वो।
यौ. क्रि, प्रयो.—द्वि.।
आभण्डनम् = निरूपणम्—क्षी।

क—भेल्=दीप्तौ-वा. पॉकर्नीः।

ग—न निभालयसे-छान्दोग्यो. ६,१२,२; ६,१३,२। निभालय-कठो. १,६। (विज्ञप्तिम्) संभालयामास-नैष. ६,७६।

ङ—√भल (सक)=सम्भालने। भलिज्जासु-सुपा. ५४६।

छं—√भालना=अवधानेन दर्शने, (२) गवेषणे।

छ—√निहारना (<निभालनम्)=दर्शने।

+√भाज (भाज)१०/३३३ पृथक्कर्मणि (प)
श× क्षी-मै-सा-काकृ-कात-
शा-हे।
पृथक्करणे—जै।

√भज् (भज) १०/ विश्राणने (प)।
√भज् (भज) १/ सेवायाम् (उ)।

पृथक्क्रियायाम्—च ।
पृथक्कृत्याम्—वो ।
प्रयोज.—ह्वि. ।

ग—शिवतमो रसस्तस्य भाजयतेह नः-ऋ. १०,९,२ । रसेन भाजयति-शत्रा. ३,६,१,१२ । राजतं भाजनम्-मभार. १३,१११,१०२ ।

+√भाम (भाम) १०/३१९ क्रोधे (प) √भाम् (भाम) १/क्रोधे (आ) ।
श-च×
क्षी-मै-सा-जै-काक्र-
कात-शा-हे ।
कोपने—वो ।

ग—प्र रुजन्ति भामाः-ऋ. ५,२,१० । तिङ्रूपालाभे निर्णेतुं न शक्यते, कृद्रूपाणां भ्वादेरपि सिद्धेः ।

+√भिल् (भिल) १०/७१ भेदने (प) इति <√बिल् (बिल) भेदने (प) ।
मै-सा-श-च-जै-काक्र-कात-शा×
कौशिकः—क्षी ।
क्षी-हे ।
बादिवत् (=भेदने) —वो ।
बिल्मं भिल्मं भासनमिति वा-निरु. १,२० ।
√भिद् (भिदिर्) ७/विदारणे (उ) ।

ग—अन्त्यजाश्च चर्मकाररजकनटवरुडकैवर्तकभिल्लाः सप्त-प्रायश्चित्तेन्दु. १९,b ।
ङ—[√भेल (सक)=मिश्रणे ['भेलववु' -गुर्जरभा.]-पि. २०६ ।]
छ—भेला * †=(१) युद्धम्, (२) साक्षात्कारः ।
छ—√भेंटना=साक्षात्कारे ।

+√भू (भुवः) १०/२०७ अवकल्कने (प) √भू १/१ सत्तायाम् (प) ।
च×, श
क्षी-मै-सा-कात-हे । √भू १०/२९० प्राप्तौ (आ) ।
अवकल्पने—काक्र-शा ।
भावकरणे—जै ।
'विकल्कने' इति नन्दी —क्षी ।
शुद्धिचिन्तयोर्मिश्रणे [च]—वो ।

अवकल्कनम् = मिश्रीकरणम्-क्षी; पीडनम्-मै १९९ । पुरुषकारे-अवकल्कनम्=चिन्तनम् इति काश्यपः-सा १०/२१२ ।

ग—भावयति—ऐआ. २,५,१; ऐतरेयो. ४,२; हरिवंशे ३,११,१० = (आत्मत्वेन) कल्पयति (नील.); १,१८,६९ = पुनाति (नील.)-द्रष्ट. वोपदेवार्थः। भावितम्-मभार. १२,२१६,९ = संस्कृतम् (नील.)। भावना-नैष. १,२९ = वासना, चिन्तनम् (प्रका.)।

ङ—√भाव (सक) = गुणाधाने, वासितत्वे, (२) चिन्तने। भावेइ-विवे. ९८।

छ—[भावना = रुचौ।]

+√भू १०/२९० श-च-जै-शा-हे×	प्राप्तौ (आ) क्षी-मै-सा-काकृ- कात-वो।	√भू (भुवः) १०/ अवकल्कने (प)।

अन्ये तु पुराणव्याकरणेषु "भुवो णिङ्" इति सूत्रस्य णिङो ङकारः प्रत्ययान्तादात्मनेपदार्थः-सा १०/३०२; लीलाशुक-(पुरुषकार)-धनपालशाकटायनादयो णिजभावपक्षे परस्मैपदमेव ब्रुवते-सा १०/३०२।

ग—भवते-मुण्डको. ३,१,४; श्वे. २,१४; मभार. १३,२९,४७। भवन्ते-इ. १३:१२। भावयस्व-वरा. २,४५। भवे-मभार. १२,३०७,३१ = प्राप्नुयाम् = आत्मानं जानीयामित्यर्थः (नील.)। बुभूषेत्-मभार. ५,१,१५ = प्राप्तुमिच्छेत्। तङ्भाव आर्षः (नील.)।

ङ—√भव = (१) प्राप्तौ, (२) अक-सत्तायाम्। भवइ-कप्प.; महा.।

+√भूष् (भूष) १०/१९७ श-च×	अलङ्कारे (प) क्षी-मै-सा-जै-काकृ- कात-शा-हे। भूषणे—वो। प्रयोज. —हि.।	√भू (भुवः) १०/ अवकल्कने (प)। √भू १०/ प्राप्तौ (प)। √भू १/१ सत्तायाम् (प)।

ग—भूषयन्ति-सार. २६३:१५। स्वर्णेन भूषयिष्यामि ते तनुम्-वा. रा. २,८,४६ (२,३९,१७)।

गुणो भूषयते रूपं शीलं भूषयते कुलम्।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥ वृद्धचाण. ८,१५।

ङ—√भूस (सक) = सज्जायाम्, (२) अलङ्कृतौ। भूसेमि—कुमा.।

+√भृंश् (भृशि) १०/२५२ क्षी-मै-श-च-जै-काकृ- कात-शा-हे-वो×	भासार्थः (प) स्वामिकाश्यपानुसारेण लिख्यते—सा।

+√भ्रूण् (भ्रूण) १०/१५९ श ? च ×(काक्ट-√व्रूण्) (जै-√भ्रूण्) ..	आशायाम् (आ) क्षी-सा-जै-काक्ट-कात-शा-हे-वो। आशंसायाम्—मै। 'आशङ्कायाम्' इत्येके—क्षी-हे। विशङ्कायाम्—वो।	

क—भ्रॉइ=अङ्कुरणे, वृद्धौ, उच्छ्रयने। म. उ. ज. ब्रिउने, ब्रूने=कुक्षिः, उदरम्। लेट्टिश्-ब्रौन=(भ्रूणम्) अन्त्राणि-वा. पॉकर्नीः।

ग—भ्रूण०-ऋ. १०,१५५,२। भ्रूणहत्या-तैआ. २,७,३। अपापस्य भ्रूणस्य-भा. पु. ९,९,३४।

+√मंह् (महि) १०/२३९ मै-श-च-जै-काक्ट-कात-शा ×	भासार्थः (प) क्षी,-हे ? भाषार्थः—सा। त्विषि—वो।	√मंह् (महि) १/ वृद्धौ (आ)। √मह (मह) १०/ पूजायाम् (प)।

ग—[समिथेषु मंहयम्-ऋ. १०,४८,९=वृद्धौ]।

+√मण्ड् (मडि) १०/५१ श यौ. क्रि., प्रयोज.	भूषायाम् (प) क्षी-च-जै-काक्ट-शा-हे। भूषायां हर्षे च—मै-सा-कात। भूषे मोदे—वो। —ह्वि.।	√मण्ड् (मडि) १/ च=विभाजने (आ)। √मण्ड् (मडि) १/ भूषायाम् (प)। √मद् (मदी) १/ हर्षग्लपनयोः (प)। √मद् (मदी) ४/ हर्षे (प)। √मन्द् (मदि) १/ मोदमदस्वप्नगतिषु (आ)।

ग—मण्डयन्ति-त्रिपुरो. ४। [मण्डनात्-गोच. ६८:१४:]।

घ—मण्डेति-जातक ३,१३८।

+√मद् (मद) १०/१७३ च ×,श	तृप्तिशोधने (आ) क्षी-हे।	पूर्ववत्।

'तृप्तियोगे' इति नन्दी
—क्षी।
क्षी-मै-सा-जै-काकृ-
कात-शा-हे-वो।
प्रयोज. —ह्वि.।
शोधनम्=सम्पत्तिः—क्षी।

ग—मादयध्यै-ऋ. १,१६७,१; ते त्वा मदा मादयन्तु-७,२३,५।

+√मन् (मन) १०/१७७ स्तम्भे (आ) क्षी-मै-सा-जै, काकृ (प),-कात-शा-हे। अर्चे गर्वके च—वो। प्रयोज. —ह्वि.।
च×, श

स्तम्भः =गर्वः—क्षी।
पक्षे मनतीति चन्द्रः—क्षी।

√मन् (मन) ४/ ज्ञाने (आ)।
√मन् (मनु) ८/ अवबोधने (उ)।
मनायति-ऋ. १,१३३,४=स्तुतौ।

ग—मानयन्तः-वा. रा. १,१५,७=परिपालयन्तः (तिल.); मानः-२,५७, १९=अहङ्कारप्रयुक्त इतरतिरस्कारकचित्तविकारः (तिल.); विमानशिखराणि-२,५७, १८=सप्तभूमिकगृहाग्रभागाः (तिल.)।

ङ—√मन्न (सक)=(१) सम्माने; (२) अनुभवे-उप. १०३६; धर्मवि. ७९।

+√मन्त्र् (मत्रि) १०/१४८ गुप्तभाषणे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। गुप्तोक्तौ—वो।
श

पूर्ववत्।

ग—मन्त्रयन्ते-ऋ. १,१६४,१०। अनुमन्त्रयते-तै. ५,१,६,४; शौ. ९,१४,१०। मन्त्रयामि-पै. १,९,१। मन्त्रयेत् परमं मन्त्रम्-मनु. ७,५७=निरूपयेत् (मन्वर्थ.); मन्त्रयेत्-७,१४६=चिन्तयेत् (मन्वर्थ.)।

घ—मन्तेति-दीघ. १,९४,१०४।

ङ—√मंत (सक)=(१) गुप्तपरामर्शे, (२) आमन्त्रणे। मंतइ-महा.; भवि.।

छ—√मंतरना }
छ—√मिंतुरना } (<मन्त्रणम्)-चुं. ख.।

+√मर्च् (मर्च) १०/१०८ शब्दार्थः (प)
मै-श-च-जै-काक्ट-कात- क्षी-सा।
शा-वो× शब्दे—हें।
√मृच् ४/ प्रयोज. पीडने, हानौ—ह्वि.।

√मर्क् १/४१० h आदाने (आ) काक्ट।
√मृज् (मृज) १/ शब्दार्थः (प) क्षी (पुरुषकारे ५७ पृ.)।
√मार्ज् (मार्ज) १०/ शब्दार्थः (प)।

क—मेर्क्-ः अमें.-मॉर्च् = नवीनम् ; ललितम्, स्वादिष्टम् ; लिथु. (स्)-स्मेर्कुक्ति।

ख—मुर् न्चैति = विपत्तौ, हानौ—जू. पॉकर्नीः।

ग—अरातीवा मर्चयति द्वयेन-ऋ. १,१४७, ४ = भर्त्सनायाम्, विपत्तौ, संकटे। मर्चयसि-शौ. १३,१,४०।

+√मह (मह) १०/३१४ पूजायाम् (प)
श× क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे।
पूजे—वो।
यौ. क्रि.; प्रयो. ह्वि.।

महयति-निघ. ३,१३ = अर्चतिकर्मा।
√मह् (मह) १/ पूजायाम् (प) चुरादौ स्मरति क्षीरस्वामी।
√मही (महीङ्) कण्ड्वा. ३४ पूजायाम् (आ)।
महीयते-ऋ. १,१८२,३।

क—मेग् (ह्)-ः मेगु् (ह्) = महत्। अल्बे. मथ्, मधि = महत् (मही)-जू. पॉकर्नीः।

ग—महयते-ऋ. ७,३२,१९; शौ. २०,८२,२। महयति-तै. १,७,१,६; शत्रा. १,१,३,७। महयन्ति-तैत्रा. ३,२,८,३।

ङ—√मह (सक.) = पूजायाम्। महइ-कुमा.।

+√मान् (मान) १०/२८९ पूजायाम् (प)
श× (शा-√मन्) आधृषाद्वा।
क्षी-मै-सा-च-जै-काक्ट-कात-शा-हे।
अर्चे—वो।

द्रष्ट. √मन् (मन) १०/ स्तम्भे (आ)।

ग—मानयित्वा च तापसम्—वा. रा. ३,५,२४ (गी. प्रे. सं.)। नास्त्यत्र प्रयोजकता। मानयन्तश्च ते वाक्यम्—वा. रा. १,१४,१५। मानयामास पौरजानपदान्—मभार. १,४४६७। साधु मानयेत्—भा. पु. ७,७,३२। या चैनं नावमानयेत्—मनु. २,५०=प्रत्याख्यानेन नावमन्येत (मन्वर्थ.)।

घ—मानेति-पेतवत्थु ५४।

+√मार्ग् (मार्ग) १०/८० मै-श-च-जै-काक्ष-कात-शा-हे×	संस्कारगत्योः (प) क्षी-सा। सर्पणे संस्कारे च—वो।	√मृज् (मृजूष्) २/ शुद्धौ (प)। √मर्क् (मर्क) सर्प-सौ. धा.—वो। √मृज् (मृजूष् १०/ शौचालङ्कारयोः (प) आधृ०।

ग—अगायतां मार्गविधानसम्पदा—वा. रा. १,४,३६=गानं द्विविधम्—मार्गो देशी च। तत्र प्राकृतावलम्बि गानं देशी। संस्कृतावलम्बि तु गानं मार्गः—(तिल.)। अत्र मार्गधातोः संस्कारोऽर्थः सुस्पष्टः।

+√मार्ग् (मार्ग) १०/२९३ श×	अन्वेषणे (प) आधृ-षाद्वा। क्षी-मै-सा-च-जै-काक्ष-कात-शा-हे। अन्वेषे—वो। संस्कारे चेत्यधिकं क्वचित्—क्षी।	पूर्ववत्।

१/ यौ. क्रि.; प्रयो. —मार्गणे—ह्वि।
वस्तुतः 'मार्ग' इत्यस्य नामधातुः—ह्वि।

ग—मार्गन्तु—वा. रा. ४,४०,२१; मार्गत—२,९९,३; मभार. ३,८८६२; भूय एव स मार्गति—१२,६६१२। मार्गयिष्यति तत्समाम्—शत्रुञ्जयमा. १४,१४६।

ख—मग्गेति—मज्झिम. १,३३४; संयुत्त. २,२७० । प्रयोज.—मग्गापेति—पेतवत्थु ११२।

ङ—√मग्ग (सक)=(१) याचने, (२) अन्वेषणे। मग्गइ—उत्र.।

छ—√माँगना (<मार्गणम्)=याचने।

+√मार्ज् (मार्ज) १०/१०९ (श) च×	शब्दार्थः (प) क्षी-मै-सा।	द्रष्ट.√मर्च् (मर्च) १०/ शब्दार्थः (प)।

शब्दे—जै-शा-हे। शुद्धौ—काकृ। शब्दार्थे—कात। मृजा-ध्वन्योः—वो।

√मृज् (मृजूष्) २/ शुद्धौ (प)।

ग—[ग्रामस्य मार्जनि-लाट्या. ४,३,११।]

+√मिञ्ज् (मिजि) १०/२१८. क्षी-श-च-जै-काकृ-कात-शा-हे-वो×

भाषार्थः (प) मै-सा।

√मज् (मज) १/ शब्दार्थः (प)।

√मुञ्ज् (मुजि) १/ शब्दार्थः (प)।

ग—मिञ्जिकामिञ्जिक०–मभार. ३,१४५२३; १४५२८।

+√मिद् (मिद) १०/८ मै-जै-शा×

स्नेहने (प) इति कौशिकः—क्षी। क्षी-सा-च-काकृ-कात-हे। स्निहि—वो।

<√मिन्द् (मिदि) स्नेहने (प)।

√मिद् (ञिमिदा) १/ स्नेहने (आ)।

√मिद् (ञिमिदा) ४/ स्नेहने (प)।

√मिण्ट् १०/९० स्नेहने (प) हे।

√मिण्ठ् १०/१४५ व्यभिचारे (प) काकृ। मित्रः। मेदयतेर्वा–निरु. १०,२१,४=स्नेहनार्थस्य–दुर्गाचार्यः।

ग—यूयं गावो मेदयथा कृशम्–ऋ. ६, २८,६।

+√मिन्द् (मिदि) १०/८ च-काकृ-कात×, श

स्नेहने (प) क्षी-मै-सा-जै-शा-हे। स्निहि—वो। —ह्वि·]

<द्रष्ट.√मिद् (मिद) स्नेहने (प)।

[प्रयोज.

क—मेन्दू (आ,-ऑम्)=आकाङ्क्षायाम्। लैति. मेन्दुम्, मेन्दू=आकाङ्क्षायाम्–वा. पॉकर्नीः।

ग—मिन्दा–तै. ३,२,५,४। मित्रं मिन्देर्नन्दतेः प्रीयतेर्वा–मभार. ८,१९९२।

√मिश्र (मिश्र) १०/३६५ श (जै-शा-√मिश्र्) | सम्पर्चने (प) क्षी-जै-काक्ष-कात-शां-हे। सम्पर्के—मै-सा-च। युत्याम्—वो। | √मिश् (मिश) १/ शब्दे रोषकृते च (प)।

क—माइकु =मिश्रणे।

ख—अवे. मिस्वन् =मिश्रणम् -वा. पॉकर्नीः।

ग—मिश्रम्–तै. १,७,६,४; शौ. १२,३,४४; पै. १७,४०,४। मिश्राः–तै. ४,६,५,१। आर्यमिश्राणाम्–वा. रा. २,८२,१९=पूज्यानाम् (तिल.)। मिश्रयन् समरे–हरिवंश. १३३०१। व्यामिश्रकेषु–वा. रा. २,१,२७=प्राकृतादिमिश्रितनाटकादिषु (तिल.)।

ङ—√मीस (सक)=मिश्रणे। कर्म.–मीसिज्जइ–पि. ६४।

च—√मिसल (सक)=मिश्रणे [मिसळणें–महाराष्ट्रि.]–मिसलइ–भवि.।

छ—√मिसना*† (<मिश्रणम्)=मिश्रणे (अक)।

छ—√मासना*† (<मिश्रणम्)=मिश्रणे (अक)।

+√मी १०/२७४ | मतौ मनने (प) आघृषाद्वा क्षी। मतौ—हे। गतौ—मै-सा-जै-काक्ष-कात-शा-हे। गत्यां मत्याम्—वो। | मिनोतिः श्रयतिकर्मा–निरु. ७,२९,१। मिनाति–निघ. २/१४=गतिकर्मा।

ग—[आ च परा च मेथ्यन्–ऐब्रा. ४,२०।]

+√मुच् (मुच) १०/२१५ (श) च× | प्रमोचने (प) क्षी-मै-जै-काक्ष-कात-शा-हे। प्रमोचने मोदने च—सा। प्रयोजने—हे। मोक्षे—वो। | √मुच् (मुच) १/ कल्कने (आ) इति चन्द्रः—क्षी। √मुच् (मुच्लृ) ६/ मोक्षणे (उ)।

प्रयो.—ह्वि.।

ग—किं न मोचयते रामम्-वा. रा. २,७८,३। मोचयेदेनसः-मनु. ३,३७।

+√मुट् (मुट) १०/७९ श (क्षी—√पुट्)	संचूर्णने (प) मै-सा-च-जै-काक्ट-कात-शा-हे। क्षुदि—वो।	√मुट्ट् १०/२६ b संचूर्णने (प) काक्ट। √मुट्ट् १/११८ प्रमर्दने (प) काक्ट।

ग—प्रति मोटयतु-छन्दोम. ३७।

ङ—√मोड (सक)=मोटने, कौटिल्ये (२) चूर्णने, आमर्दने। मोडसि-सुर. ७,६।

+√मुद् (मुद) १०/२१३ श-च×	संसर्गे (प) क्षी-मै-सा-जै-काक्ट-कात-शा-हे-वो।	√मुद् (मुद) १/ हर्षे (आ)। √पुट् (पुट) ६/ संश्लेषणे (प)।
+√मुल् (मुल) १०/६७ मै-सा-श-च-जै-काक्ट-कात-शा×	रोहणे (प) इति नन्दी—क्षी। क्षी-हे-वो।	<√मूल् (मूल) रोहणे (प)। √मुल् १/४९८ c धारणे (आ) काक्ट। √मुल्ल् १/४९८ d धारणे (आ) काक्ट।
+√मुस्त् (मुस्त) १०/९७ श-च-काक्ट×(मै-√पुस्त्)	संघाते (प) क्षी-मै-सा-जै-कात-शा-हे। संहतौ—वो।	√मुस्त् १०/४३ गन्धे (प) काक्ट। √मुक्ष् १/२७९ संघाते (प) काक्ट। √मृक्ष् (मृक्ष) १/६५३ संघाते (प) सा। <मुष्ट—(मुष्टिः)।

ग—मुस्तके द्वे प्रकीर्तिते [मुस्तयति=संहतीकरोति रुधिरमिति। √मुस्त्+कः। ततः संज्ञायां कन्]=स्थावरविषभेदः-सुश्रु. कल्पस्थाने २ (श. क. द्रु.)। मुस्तक०-बृहत्सं. ७७,९।

+√सूत्र (मूत्र) १०/३५३ च-जै-शा-×, श (जै-√मूत्र्)	प्रस्रवणे (प) क्षी-मै-सा-जै-काक्ट-कात-हे। प्रस्रवे—वो।	

क—मॉइ=मनाक् क्लिन्नम्। पु. इरिश्-मून् =मूत्रम्-वा. पॉकर्नीः।

ख—अवे. मूथ्र=अपावित्र्यम्, मालिन्यम्, धूलिः। (नीदेर्लै. मादेर्)-वा. पॉकर्नीः।

ग—मूत्रितः-नारदपरिव्राजको. ५,२८। अवमूत्रयतः-मनु. ८,२८२=मूत्रप्रक्षेपेणावमानयतः (मन्वर्थ.)। मूत्रयन्ते-मभार. ५,३४९३। कुण्डेऽवमूत्रयन् केचित्-भाग. पु. ४,५,१५।

ङ—√मुत्त (सक)=मूत्रणे। मुत्तंति-कुप्र. ९२।

+√मूल् (मूल) १०/६७ च×,श	रोहणे (प) क्षी-मै-सा-जै-कात-शा-हे-वो। प्रतिरोहणे—काकृ।	>√मुल (मुल) रोहणे (प)। √मू (मूङ्) १/बन्धने (आ)। √मू+उगा. ४/१०८ (मवते=बध्नाति वृक्षादिकम्)।

ग—मूलं यातुधानस्य वृश्च-ऋ. १०,८७,१०। समुन्मूलयितुं वृक्षान्-इन्दिशे स्मृशे २१४२।

+√मृग (मृग) १०/३४४ श	अन्वेषणे (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। मार्गणे—वो।	'मृग' इति संज्ञाशब्दस्य नामधातुः!

क—मेर्गु =अपनोदने।

ख—अवे. मृर्ग (Merγəa)=पक्षी। न. पर्सि. मुर्ग् (Murγ)=पक्षी, ताम्रचूडः-वा. पॉकर्नीः।

ग—मृगयन्ते-ऋ. ८,२,६; जै. ४,१६,७; शौ. १०,५,४२। मृगयेते-पै. २०,५६,५। मृगयामि-वा. रा. २,११,२०।

घ—मग्गति, मगेति-मज्झिम. १,३३४; संयुत्त. २,२७०।

√मृज् (मृजूष्) १०/२९५ श×(मै-सा√मृंज् [मृजू])	शौचालङ्कारयोः (प) आधृषाद्वा क्षी-मै-सा-जै-काकृ-कात-शा-हे। शौचे—च। शुद्धौ भूषे च—वो।	√मृज् (मृजूष्) २/ शुद्धौ (प)।

१/ प्रयो. ह्वि.।

ग—परिमार्जति–वा. रा. २,७२,३१ = परिमार्ष्टि (तिल.)। यदाश्रु परिमार्जति–मभार. १२,३४४०। ललाटं चाप्यमार्जयत्–मभार. ५,५५८८। [मदन्तीभिर्मार्जयन्ते–तै. ६,२,२,७]; [मृजन्ति वाजिनं घृतेन–ऋ. ५,१,७–तौदादिकः]।

+√ मृण्ड् (मृडि) १०/१२४ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो× — छेदने (प) आधृषाद्वा—सा। — <√ चुण्ट् (चुटि) छेदने (प)।

आद्येषु व्याख्यानेषु न दृश्यतेऽतोऽप्रामाणिकः पाठोऽस्य–सा।

छ—√ मींड़ना (<मृण्डनम्) = मर्दने, छेदने–बुं.ख.।

+√ मृष् (मृष) १०/२९६ श — तितिक्षायाम् (प) आधृषाद्वा क्षी-मै, सा (उ),-जै-कात-शा-हे (आ),-काकृ। क्षान्तौ—च-वो। क्षमायाम्—काकृ-कात। प्रयो. द्वि.। — √ मृष् (मृष) ४/ तितिक्षायाम् (उ)।

ग—मर्षयन्ति–मै. १,५,१२। मीमृषः–शौ. ३,१५,४। यो मर्षयति पार्थिवः–मनु. ८,३४६। मर्षयत्यार्तैः–मनु. ८,३१३ = सहते (मन्वर्थ.)। मर्षयस्व–वा. रा. ४,५८,३; ६,१२,१; हरिवंश. ७१२९।

+√ मृष (मृष) १०/२९६ मै-सा-श-च× — तितिक्षायाम् (प) क्षी-शा। जै ? क्षान्तौ—काकृ-कात-हे-वो।

केचिदमुं (√ मृष् धातुम्) अदन्तत्वोपजीवनार्थं व्यत्यस्य पठन्ति–क्षी।

+√ मोक्ष् (मोक्ष) १०/१९८ च×, श — असने (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। — √ मुच् (मुच्लृ) ६/ मोक्षणे (प)।

क्षेपे—वो।
'सहने' पाठान्त-
रम्—क्षी।

ग—मोक्षयेत्-ऐब्रा. ७,७। मोक्षयध्वम्-वा. रा. १,६४,१०; मभार. १,५३०१। मोक्षयति-सुश्रु, १,१८,३।

+√म्रक्ष् (म्रक्ष) १०/१२१ च×,श	म्लेच्छने (प) क्षी-मै-सा-जै-शा-हे। 'अदने' इत्यपि क्वचित् पठ्यते—सा। क्षरणस्निग्धार्थे—काकृ। म्रक्षणे—कात। म्रक्षणे म्लेच्छने—वो।	√म्लेच्छ् (म्लेछ) १०/ अव्यक्तायां वाचि (प)।

ग—स्नेहपात्राणि म्रक्षयित्वा छोरयति-कात्या. श्रौ. ५७८,१९; ५८३,२।

घ—मक्खेति=म्रक्षणे—जातक ३,२२५; विसुद्धिमग्ग ३४४। (√मृक्ष् इत्यस्य प्रयोगः!)।

+√म्लक्ष् (म्लक्ष) १०/१२६	अदने (प) इत्यपि क्वचित् पठ्यते—सा। क्षरणस्निग्धार्थे—काकृ।	√म्रक्ष् (म्रक्ष) १०/१२१ म्लेच्छने (प)। √भ्लक्ष् (भ्लक्ष) १/ भक्षणे (उ)।
+√म्लेच्छ् (म्लेछ) १०/१२२ श-च×(जै√म्रछ्) मुद्रणदोषः।	अव्यक्तायां वाचि (प) क्षी-मै-सा-जै-काकृ-शा-हे। कात ? देश्योक्तौ—वो। म्लेच्छने—जै-शा-हे।	

ग—द्रष्ट. √म्लेच्छ् १/।

+√यक्ष् (यक्ष) १०/१६१ च×, श	पूजायाम् (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे।	√यज् (यज) १/ देवपूजा-संगतिकरणदानेषु (उ)+ इच्छार्थे सन्-इयक्षति

१/	महि—वो। दमने—ह्वि।	>यक्षति, ते। इयक्षति—निघ. २,१४=गतिकर्मा। इयक्षति—ऋ. ८,३१ (१५-१८); तै. १,८,२२,४। यक्षि=यज-निरु. ८,१४, २; ६,१३,१।

क—इअघ्=अनुसरणे, वाञ्छायाम्।

ख—अवे. यासैति=काङ्क्षायाम्-वा. पॉकर्नीः।

ग—न यासु चित्रं ददृशे न यक्षम्-ऋ. १,१३२,५ (=पूजा); प्र यक्षन्त श्रवस्यवः-१,१३,५। यक्षते-तांत्रा. ९,१०,१। यक्षामः-वा. रा. ७,४,१२। सर्वे सन्नन्ता इमे प्रयोगाः √यज् धातोः प्रायेण। विष्णुपुराणीया यक्षशब्दनिरुक्तिस्तु विलक्षणा। तद्यथा—

मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते।
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु यक्षणात्॥ १,५,४१।

लिङ्गपुराणेऽपि तथा—

एवं च यक्षतिर्धातुर्भक्षणे स निरुच्यते॥ लिङ्गपु. पूर्वा. ७०,२८।

चौरादिकानि रूपाणि नोपलभ्यन्ते।

घ—यक्ख=प्रकाशस्य तीव्रकिरणः, देवजातिविशेषोऽपि—विमानवत्थु २२४।

ङ—जक्ख=व्यन्तरदेवजातिविशेषः-पण्ह. १,४; औप.।

छ—√जकना=आश्चर्ये।

+√यत् (यत) १०/२०३ च×,श	निकारोपस्कारयोः (प) क्षी-मै-सा-जै-शा-हे। खेदबिम्बाच्छादनेषु—काकृ। निकारोपसंस्कारयोः—कात। खेदोपस्करयोः—वो। "निराकारः=परिभवः, इति क्षीरः" इति पुरुषकारः—७६ पृ.। विस्तारे—ह्वि।	यातयति—निघ. २/१९ = वधकर्मा।
प्रयो.		

ग—द्वा जना यातयन्नन्तरीयंते-ऋ. ९,८६,४२; मित्रो जनान् यातयति ब्रुवाणः-३,५९,१; अधियातयमानः-६,६,४। यातनाः-भत्रसंतारणो. १,३। यातनानाम्-भस्सजाबालो. २,२१।

ङ—√जाय (सक)=पीडने, यातनायाम्। जाएइ-उव.।

+√यन्त्र् (यत्रि) १०/३ श

सङ्कोचने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।

√यन् ८/१७ उद्धारे (उ) काकृ।
√जन्त्र् १०/७ सूचने (प) काकृ।
√यम् (यम) १/उपरमे (प)।

ग—सविता यन्त्रैः पृथिवीमरम्णात्-ऋ. १,१४९,१। अयन्त्रितहयद्विपा (राजधानी)-वा. रा. २,८८,१९। उपयन्त्रिता-मनु. ११,१७७=अभ्यर्थिता (मन्वर्थ.)। यन्त्रयति-सुश्रु. १,१५,७; १,३५८,८; २,५८,७; २,३४३,१४। सुयन्त्रितः-मनु. २,११८=शास्त्रनियमितः-(मन्वर्थ.)।

घ—यन्तेति-जातक १,४१८।

ङ—√जंत (सक)=वशीकरणे, (२) बन्धने-उपपृ. १३१।

छ—जाँता (<यन्त्र-)=पेषणी।

+√यम् (यम) १०/८७ च-जै-शा×,श

परिवेषणे (प) मित् क्षी-मै-सा-जै-काकृ-कात-हे-वो। 'अपरिवेषणे' इत्येके पठन्ति—क्षी।

√यम् (यम) च=चकारो मित्त्वमाकर्ष्टुम् (प)। इति दुर्गः—क्षी।

ङ—√जम (सक)=नियमने, (२) आतञ्चने, स्थिरीकरणे। जमेइ-से. १०,७०।

छ—√जमाना=आतञ्चने, स्थिरीकरणे।

+√यु १०/१७८ च-काकृ×,श

जुगुप्सायाम् (आ) क्षी-मै-सा-जै-कात-शा-हे। निन्दने—वो। प्रयोज. पार्थक्ये—ह्वि.।

>√युज् (युजु) कुत्सायाम् (आ) इत्येके—क्षी।

ग—ब्रह्मद्विषः सूर्याद्यावयस्व-ऋ. ५,४२,९; अ.वे. १,२,३; ४,२,६; वा. सं. ५,२६; शब्रा. १३,८,३,१३।

+√युज् (युज) १०/१७८ मै-सा-श-च-जै-कात- शा×	कुत्सायाम् (आ) इत्येके —क्षी। क्षी। जुगुप्सायाम्—काकृ-हे। निन्दे—वो।	<√यु जुगुप्सायाम् (आ)।
+√युज् (युज) १०/२५७ च×, श प्रयोज.	सम्पर्चने (प) आधृषाद्वा क्षी-हे। संयमने—मै-सा-जै- काकृ-कात-शा। संयमे युतौ च—वो। —योगे—ह्रि.।	√युज् (युज) ४/ समाधौ (आ)। √युज् (युजिर्) ७/ योगे (उ)।

ग—अयूयुजन्तुष्ट्रखरान्-वा. रा. २,८२,३१। रथान् योजयत-मभार. १,७९४८। दुःशासनमयोजयत्-मभार. २,१२९०;...............योजितः-५,५३२ (=पीडितः)।

ङ—√जोअ (सक)=योजने। जोएइ-महा.।

ङ—√जोअ (सक)=(१) समाप्तौ, (२) करणे। जोएइ-सुज्ज. १०,१२-पत्र. १८०।

ङ—√जोंज (सक)=[योजने]-कुप्र. १३०।

+√रंहू (रहि) १०/२६१ क्षी-मै-श-च-जै-काकृ- कात शा-हे-वो×	भाषार्थः (प) सा।	√रङ्घ् (रघि) १०/२३५ भासार्थः (प)। √रंह (रहि) १०/३०५ गतौ (प)। √लङ्घ् (लघि) १०/२३६ भासार्थः (प)।
+√रंह (रहि) १०/३०५ मै-सा-श-च-जै-काकृ- कात-शा-हे× यौ. क्रि., प्रयोज.	गतौ (प) क्षी-वो। —ह्रि.।	√रंहू (रहि) १०/२६१ भाषार्थः (प) सा। √रह् (रह) १०/९३ त्यागे (प) मित्—सा। शेषः पूर्ववत्। √रम् (रमु) १/ क्रीडायाम् (आ)।

ग—वाजे अद्रिं रंहयन्तः-ऋ. १,८५,५; रंहयन्त आ शवः-८,१९,६ (=द्रुतगतौ)।

+√रक्(रक) १०/२०९ शा-च×	आस्वादने (प) इति चन्द्रः—क्षी। क्षी-मै-सा-जै-काकृ-कात-शा-हे। स्वाद आपने—वो। 'आस्वादने' इति दुर्गः—क्षी-,हे।	<√रग्(रग) आस्वादने (प)। √रस (रस) १०/ आस्वादने स्नेहने (प)। √लक् (लक) १०/ आस्वादने (प) इति चन्द्रः—क्षी। √रघ् (रघ) १०/ आस्वादने (प) इत्येके—मै। √लग् (लग) १०/ आस्वादने (प)। √लिह् (लिह) २/ आस्वादने (प)।

ग—रकसा-(=क्षुद्रकुष्ठ-) सुश्रु. १,२६८,४; शार्ङ्ग. सं. १,७,६५।

+√रग्(रग) १०/२०९ मै-शा-च-काकृ-कात× (जै-√रज्[रज]) स्यान्मुद्रणदोषः।	आस्वादने (प) क्षी-सा-जै-शा-हे। 'आसादने' इति दुर्गः—क्षी,-हे। रक्वत् (=स्वाद आपने) —वो।	पूर्ववत्।

ङ—[रइगेल्ल=अभिलषितम्-दे. ७,३।]
छ—रगाना†(देश.)=तूष्णीम्भावे।
छ—रगा=मयूरः।
छ—रगी }
छ—रगा } =महीशूर-(मैसूर)-देशोत्पन्नोऽन्नविशेषः।
छ—रग (फा.)=नाडी।

+√रघ्(रघ) १०/२०१ क्षी-शा-च-जै-काकृ-कात-	आस्वादने (प). इत्येके—मै।	√रघ् (रघ) १/४१२ jj गतौ (आ) काकृ।

शा-हे-वो×	मै-सा।	द्रष्ट.√रक् (रक) १०/२०९ आस्वादने (प)।
+√रङ्घ् (रघि) १०/२३५ मै-श-च-जै-काकृ-कात-शा×	भासार्थः (प) क्षी-हे। भाषार्थः—सा। भासि—वो।	√रंह् (रहि) १०/ भाषार्थः (प) सा।
+√रच (रच) १०/३११ श× (काकृ-√चर् [चर]) वर्णविपर्ययः। यौ. क्रि., प्रयोज.	प्रतियत्ने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। कृत्याम्—वो। उत्पादने—ह्वि.।	रजयति—निघ. ३/१४= अर्चतिकर्मा।

क—रेक्-, रेक्=आदेशे, व्यवस्थायाम्। गॉथि.-रहृन्जन्=सङ्कलने, गणनायाम्-वा. पॉकर्नीः।

ग—रचयति-सार. २६८:८; रचयन्ति-२२२:२३। रचयेत्-शि. ६,४३।

घ—रचित-जातक ५,१५७।

ङ—√रय (संक)=निर्माणे, रचने। रयइ, रएइ-महा.।

ङ—√रयाव (सक) प्रयो.=निर्माणे, रचने। रयावेइ-कप्प.।

ङ—√रइआव (सक) प्रयो.=निर्माणे, रचने-ती. ३।

छ—√रचना
छ—√रचाना†* } =आयोजने, निर्माणे।

छ—√राचना *=रचनायाम् (अप्रयो.)।

+√रस (रस) १०/३७६ श-च×	आस्वादनस्नेहनयोः (प) क्षी-मै-सा-काकृ-कात-शा-हे। आस्वादस्नेहनयोः—जै। आस्वादे स्नेहे—वो।	√रस् (रस) १/ शब्दार्थः (प)। √रस्त् १०/४९ सामग्री-वृद्धौ (प) काकृ।
ना. धा.-ह्वि.।		

ग—रसयति-शत्रा. १४,७,१,२५; रसयेत्-१४,७,३,२४। रसयते-प्रश्नो. ४,२। न रसयति (दैवादिकः)-रसती रसना रसान्-मभार. १२,१०१०४ (=आस्वादने); न रसयति (दैवादिकः)-
१२,११३८३।

छ—√रसना
छ—√रिसना† } =शनैर्निश्चयोतने ।

छ—रासन=स्वादु ।

+√रहू (रह) १०/९३ त्यागे (प) मित् । √रहू (रह) १/ त्यागे (प) ।
क्षी-मै-श-च-जै-काकृ- सा ।
कात-शा-हे-वो×
यौ. क्रि.; प्रयोज. ह्वि. ।
√रह (रह) १०/३०४ क्षी-मै-सा-च-जै-काकृ-
श× कात-शा-हे-वो ।

ग—न विरहयेदाचार्यम्-शाङ्खा. गृह्य. ४,११ । रहयत्यापदुपेतमायतिः-किरा. २,१४ । रहयति नृपं स्वार्थपरता-मुद्राराक्ष. ३,४; मालतीमा. ९,८ ।

+√रिच् (रिच) १०/२६६ वियोजनसम्पर्चनयोः (प) √रिच् (रिचिर्) ७/ विरेचने (उ) ।
च×,श(काकृ√चिर्) वर्णविपर्ययः । क्षी-मै-सा-जै-काकृ- कात-शा । √रिञ्च् १०/९२ विस्तारे (प) काकृ ।
सम्पर्चने वियोजने च—हे । √रिज् (रिज) १/ गतिस्थानार्जनोर्जनेषु (आ) ।
सम्पर्कवियोगयोः—वो ।
प्रयोज. ह्वि. ।

ग—अति ह रेचयेद् यदन्यः-शत्रा. ४,६,९,१० । सोमं मातिरीरिचः-शत्रा. ४,४,२,७ । रेचयति कोष्ठागाराणि-दशकुमा. १८७,५ । रेचितपुष्पवृक्षाः (द्विरेफाः)-रघु. ६,७ ।

+√रुंश् (रुशि) १०/२५३ भाषार्थः (प) रुशती—निरु. २,२०,१=
क्षी-मै-श-च-जै-काकृ- सा । रोचनशीला (दुर्गाचार्यः) ।
कात-शा-हे-वो× रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः—निरु. ६,१३,२ ।

+√रुंस् (रुसि) १०/२५४ भाषार्थः (प) √रुंश् (रुशि) १०/ भाषार्थः
क्षी-मै-श-च-जै-काकृ- सा । (प) सा ।
कात-शा-हे-वो×

+√रुज् (रुज) १०/२५१ च×,श	हिंसायाम् (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। हिंसे—वो।	√रुज् (रुजो) ६/ भङ्गे (प)। √रुश् (रुश) ६/ हिंसायाम् (प)।

ग—ताभ्यां (बाहुभ्याम्) वक्षस्यरूरुजत्-भा. पु. १०,६७,२३।

+√रुट् (रुट) १०/१३३ श-च-जै-काकृ-कात-शा×	रोषे (प) क्षी-मै-सा-हे। 'उपघाते' इत्येके—क्षी। रुषि द्युतौ—वो।	√रुट् (रुट) १/ दीप्तौ (आ)। √रुट् (रुट) प्रतीघाते (आ) इत्येके-क्षी। √रुष् (रुष) १/ हिंसार्थः (प)। √रुष् (रुष) ४/ रोषे (प)। √रुठ् (रुठ) १/ रोषे (उपघाते ?) (प) इत्येके —क्षी।

रुषेत्येनं चन्द्रो मत्वा भ्वादिदिवादिभ्यां (१/४५८) सिद्धमाह-क्षी।

+√रुट् (रुट) १०/२२२ मै-सा-श-च-जै-काकृ-कात-शा×	भासार्थः (प) क्षी-हे। रुषि द्युतौ—वो।	√रुट् (रुट) १०/१३३ रोषे (प)। √रुट् (रुट) १/ दीप्तौ (आ)। रुशती—निरु. २,२०,१= रोचनशीला (दुर्गाचा.)।
+√रुठ् (रुठ) १०/१३३ मै-सा-श-च-जै-काकृ-कात-शा-हे-वो×	उपघाते [रोषे] (प) इत्येके—क्षी क्षी।	द्रष्ट.√रुट् (रुट) रोषे (प)।
+√रुठ् (रुठ) १०/२४८ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	भाषार्थः (प) सा।	√रुट् (रुट) १०/ भासार्थः (प)।
+√रुष् (रुष) १०/१३१ च-वो×,श	रोषे (प) इत्येके—मै। (क्षी) मै-सा-जै-काकृ-कात-शा-हे।	√रुष् (रुष) ४/ रोषे (प)। √रुट् (रुट) १०/१३३ रोषे (प)।

रोषणे—जै-शा ।

प्रयोज. ह्वि. ।

ग—रोषयन्निव माम्-वा.रा.५,३६,३६। रोषये त्वां न भीषये-वा. रा. ६,१३,२३। संरोषयेत्-सुश्रु. २,३३४,१२।

+√रूक्ष (रूक्ष) १०/३५४ शा-च×(जै-शा√रूक्ष्) पारुष्ये (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो । √रूष (रूष) १०/३८५ छुरणे (प)।

ग—रूक्षयति-शब्रा. ४,६,७,१२; रूक्षयन्ति-४,६,७,१८। रूक्षः-तांब्रा. २४,१३,२।

+√रूप (रूप) १०/३७९ शा-च× रूपक्रियायाम् (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। तत्कृतौ—वो। रूयते कीर्त्यते रौतीति वा। √रु+उणा. ३/२८ इति पः; दीर्घश्च।

रूपक्रिया=राजमुद्रादिरूपस्य करणम्, रूपदर्शनं वा-क्षी।

ग—अरूपयत्-काठ. २१,९; सामरहस्यो. २६०:१९। रूपम्-ऐब्रा. १,१४; शब्रा. १,१,४,२।

घ—रूपेति-सुत्तनिपात १३२,१४३।

+√रूष (रूष) १०/३८५ मै-सा-शा-च-जै-काकृ-कात-शा-हे× छुरणे (प) क्षी। विच्छुरणे—वो। √ऊष (ऊष) १०/४१३ छुरणे (प) हे।

क्षीरतरङ्गिण्याम् "ऊष क्षुरणे" धातुः पठ्यते। तत्र 'रूष' इति भाव्यम्।

ग—चन्दनरूषितः—वा. रा. २,४२,१५=छुरितः।

+√लक् (लक) १०/२१० सा-शा-च-जै-शा× आस्वादने (प) इति चन्द्रः—क्षी। क्षी-मै-काकृ-कात-हे। 'आसादने' इति दुर्गः—क्षी,-हे। स्वाद आपने—वो। >√लग् (लग) आस्वादने (प)। √रक् (रक) १०/ आस्वादने (प) इति चन्द्रः—क्षी। √रग् (रग) १०/ आस्वादने (प)।

क—लेक्, लेॅक-ः लूक्-(जू. पॉकर्नीः)। इँग्लि. लिक् =आस्वादने, लेहे-वागीशः।

ङ—लउच (<लकुचः)-औप.; पि. ३६८।

+√लक्ष् (लंक्ष) १०/५ श	दर्शनाङ्कनयोः (उ) क्षी-मै,-सा ,-(प) जै,- क्राकृ-कात (प),-शा-हे। दर्शने—च। दर्शनेऽङ्के— वो।	

प्रयोज. हि.।

अङ्कनम् = चिह्नम्-क्षी।

ग—लक्षम्-ऋ. २,१२,४। लक्षयेत्-मै. ४,४,१०; मैत्रि. ६,३४। अङ्कैर्लक्षैश्च ताः सर्वा (गाः) लक्षयामास-मभार. ३,१४८५२। लक्षयेत्-मनु. १२,२७= अनुभवेत् (मन्वर्थ.)।

घ—लक्खेति ('लक्ख' इत्यस्य नाधा.)-नेत्तिप्पकरण ३०।

+√लक्ष् (लक्ष) १०/१६५ च×,श (कात-√लक्ष्म) लैपिकी त्रुटिः।	आलोचने (आ) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। आलोके—वो।	√लक्ष् (लक्ष) १०/ दर्शनाङ्कनयोः (उ)।

प्रयो. हि.।

ग—लक्षयामहे-वा.. रा. १,९,४४। गुणाँल्लक्षयामहे-मभार. १२,८०२९; अवस्थामेव चात्मानं लक्षये-३,१६७५०। वस्तुतः पूर्वधातोरभिन्नोऽयमवसेयः।

ङ—√लक्ख (सक)=(१) ज्ञाने, (२) प्रत्यभिज्ञाने, (३) दर्शने। लक्खइ-महा.।

छ—√लखना*† = अनुमितौ।

छ—√लख़ाना*† = दर्शने (आलोचने)।

छ—√लछना† = दर्शने (आलोचने)।

+√लग् (लग) १०/२१० सा-श-च-जै-काकृ-कात-शा×	आस्वादने (प) क्षी-मै-हे। 'आसादने' इति दुर्गः	>√लक् (लक) आस्वादने (प)। √रक् (रक) १०/ आस्वादने (प)।

—क्षी-हे। √रग्(रग) १०/ आस्वादने
रकौ (=स्वाद आपने) (प)।
—वो।

क—लेक्-,लेक्-ः लूक्-जू.पॉकर्नीः। इँग्लि.-लिक्=लेहे, आस्वादने-वागीशः।

+√लङ्घ्(लघि) १०/२३६ भासार्थः (प)
चX, श
क्षी-शा-हे।
भाषार्थः—मै-सा-जै-काकृ-कात।
त्विषि—वो।

√लङ्घ्(लघि) १/ गत्यर्थः (आ)।
√रङ्घ्(रघि) १/ गत्यर्थः (आ)।
√रङ्ग्(रगि) १/ गत्यर्थः (प)।
√लङ्ग्(लगि) १/ गत्यर्थः (प)।

ग—[लङ्घयेत्-इतिहासो. १६:२; शि. ७,६९।]

+√लज्(लज) १०/१० अपवारणे (प) इति नन्दी—क्षी।
मै-श-च-जै-काकृ-कात-शाX
क्षी-सा-हे।
अन्दद्रौ—वो।

<√जल्(जल) अपवारणे (प)।
लजति—निघ. २/१४= गतिकर्मा।
√लज्(ओलजी) ६/ व्रीडे (आ)।
√लाज् (लाज) १/ भर्जने च (प)।

+√लज (लज) १०/३६१ प्राणने (प)
क्षी-श-च-जै-काकृ-शाX
मै।
प्रकाशे—सा।
प्रकाशने—कात-हे।
भासने—वो।
('प्रकाशने' इति कथादौ—सा १/२३८)।

√लञ्ज्(लजि) १०/ प्रकाशने (प); प्राणने—मै।

+√लञ्ज्(लजि) १०/३२ हिंसाबलादाननिकेतनेषु (प)
क्षी-मै-श-च-जै-काकृ-

<√तुञ्ज्(तुजि) हिंसाबलादाननिकेतनेषु (प)।

कात-शा-हे ×	इत्यपि क्वचिद् दृश्यते—सा । भा–, षष्ट्यर्थे (=निकेतने हिंसे बले दाने)—वो ।	√लुञ्ज् (लुजि) १०/ हिंसाबलादाननिकेतनेषु—सा ।
+√लञ्ज् (लजि) १०/२२६ मै-श-च-जै-काकृ-कात-शा ×	भासार्थः (प) क्षी-हे । भाषार्थः—सा । भायाम्—वो ।	√लञ्ज् (लजि) १०/ प्रकाशने (प) ।
+√लञ्ज (लजि) १०/३६४ श-च-काकृ-कात ×	प्रकाशने (प) क्षी-सा-शा-हे । प्राणने—मै । जै ? भासने—वो ।	√लञ्ज् (लजि) १०/२२६ भासार्थः (प) ।

क—(स्) लेंग्–ः (स्)लुग्=शिथिलम् । नासिक्यम्–(स्)लेंग्–वा. पॉकर्नीः ।

ग—लञ्जिका=वेश्या—अचिः ५३३ ।

+√लड् (लड) १०/७ श	उपसेवायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । उपसेवने—वो । ईप्से—वो ।	√लड् (लड) १/ विलासे (प) । √लल (लल) १०/ ईप्सायाम् (आ) ।

√लल्–यौ. क्रि., प्रयो. क्रीडायाम्, लीलायाम्–ह्वि. ।

ग—लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणाः–मभाष्य. ८,१,८ (लडयोरैक्यम्) ।

घ—लळेति (प्रयो.)-जातक १,३६२; विसुद्धिमग्ग ३६५ ।

ङ—√लाल (सक)=स्नेहेन पालने । लालंति-तंदु. ५० ।

छ—√लड्याना*[1]=लालने ।

+√लण्ड् (ओलडि) १०/९ मै-श-च-जै-काकृ-	उत्क्षेपे (प) क्षी-हे ।	>√लन्द् (लदिं) उत्क्षेपणे (प) इति चान्द्राः—क्षी ।

कात-शा×	उत्क्षेपणे— सा-वो।	√लण्ड् १/१७३ कोपे (प) काक्र।

ग—"इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः"-मेरुतन्त्रे २३ प्रकाशः। (लण्ड्रे तदाख्यदेशे जायत इति) [फ्रेंच्-लोण्ड्रेस्]। पपात लण्डं विसृजन् क्षितौ व्यसुः"-भा. पु. १०,३७,८-लण्डम्=पुरीषम् इति श्रीधरस्वामी।

घ—लण्ड=विष्ठा-जातक २,१९; धम्मपद १,१६३। लण्डिका=अजविष्ठा-गुटिका—जातक १,४१९; पेतवत्थु २८३।

छ—लेंड़ा (<लण्ड-)=विष्ठादण्डः-बुं. ख.।

छ—लेंड़ी (<लण्डिका) =अजविष्ठागुटिका-बुं. ख.।

√+लण्ड् (लडि) १०/२५३ मै-श-च-जै-काक्र-कात-शा×	भासार्थः (प) क्षी-हे। भाषार्थः—सा। भासने—वो।	पूर्ववत्।
+√लन्द् (लदि) १०/९ मै-सा-श-च-जै-काक्र-कात-शा-वो×	उत्क्षेपे (प)चान्द्रा आहुः—क्षी। क्षी-हे।	<√लण्ड् (लडि) उत्क्षेपे (प)। √लद्=भारे—मॉ.विलि.। √लद् >लादना (हि.)।

इत्थं लक्षणमलक्षयताम् अन्धकुक्कुटीन्यायेन लक्ष्यमनुसरतां कियदिव रुष्यामः कियदिव तुष्यामः-क्षी।

ङ—[लन्द (<लन्दः)=कालः, समयः-पा. स. मह.।]

+√लभ (लभ) १०/३८२ मै-सा-श-च-जै-काक्र-कात-शा-हे×	प्रेरणे (प) इति सभ्याः—क्षी। क्षी। क्षेपे—वो।	<√लाभ (लाभ) प्रेरणे (प)।
+√लल (लल) १०/१५६ श,(जै√चल् [चलै]) मुद्रणदोषः। 'ललै' इति भाव्यम्।	ईप्सायाम् (आ) क्षी-मै-सा-च-काक्र-कात-शा-हे-वो।	√लड् (लड) १०/ उपसेवायाम् (प)। √लड् (लड) १/ विलासे (प)।

यौ. क्रि.; प्रयो.-क्रीडायाम्, लीलायाम्-ह्वि.।

ग—लालयेत्-मुक्तिको. २, २, ७। लालसायाम्-महो. २,२५। यो नः सदा लालयति-वा. रा. २,४७,६।

+√लश् (लश) १०/१९६ मै-सा-श-च-जै- कात×	शिल्पोपयोगे (प) इति कौशिकः—क्षी। क्षी। शिलपयोगे—शा-हे-वो। शिलायोगे—काकृ।	<√लष् (लष) शिल्पोपयोगे (प)।

ग—लशुन०-(√अश् धातोर्व्युत्पत्तिः!) मभार.८,२०३४; सुश्रु. १,१४५,६।

+√लष् (लष) १०/१९६ मै-श-च-जै-काकृ-कात- शा×	शिल्पोपयोगे (प) क्षी। शिलपयोगे— सा-हे-वो। शिलायोगे—काकृ।	√लस् (लस) १७२९ शिल्प- योगे (प)-सि. कौ.। √लस् (लस) १/ श्लेषणक्रीड- नयोः (प)। √रस् (रस) १/ शब्दार्थः (प)। √रस् (रस) १०/ आस्वादन- स्नेहनयोः (प)।

छ—√लासना ([त] रासना)।

+√लस् (लस) १०/१८७ क्षी-च-काकृ-शा×,श यौ. क्रि.; प्रयोज.	शिलपयोगे (प) मै-सा-जै-कात-हे-वो। ह्वि.।	पूर्ववत्।

ग—लासयन्त्यस्तथैव च-वा. रा. ७,२,११; लासयन्त्यपरे तथा-२,६९,४।

+√लाभ (लाभ)१०/३८२ श-च×	प्रेरणे (प) क्षी-मै-सा-जै-काकृ- कात-शा-हे। क्षेपे—वो।	>√लभ (लभ) 'प्रेरणे' इति सभ्याः—क्षी।

+√लिङ्ग् (लिगि)१०/२१२ श-च×	चित्रीकरणे (प) क्षी-मै-सा-हे। चित्रकरणे—जै-शा। चित्रे—वो।	√लिङ्ग् (लिगि)१/ गत्यर्थः(प)। √लिङ्ग् १/४१२kk गतौ (आ) काकृ।

ग—(उल्लिङ्गितशात्रवेङ्गित०-किराता. १४,२।)

+√ली (ली) १०/२६२ च×,श (काकृ-√लै ?)	द्रवीकरणे (प) क्षी-मै-सा-जै-काकृ-	√री (रीङ्) ४/ स्रवणे (आ)।

	कात-शा-हे । द्रावणे—वो ।	√ली ९/ श्लेषणे (प) । लीलायताम्-गुह्यकाल्यु.५० ।
+√लुञ्ज् (लुजि) १०/३१	हिंसाबलादाननिकेतनेषु (प) क्षी-सा । हिंसाबलदाननिकेतनेषु—हे । भा,—षट्टार्थे(=निकेतने हिंसे बले दाने)—वो ।	√लुज् ४/११६ विनाशे (आ) च । √लुञ्ज् (लुजि) १०/ भासार्थः (प) ।
+√लुञ्ज् (लुजि)१०/२२७ च-शा×,श	भासार्थः (प) क्षी-हे । भाषार्थः—मै-सा-जै-काक्-कात । भायाम्—वो ।	√लञ्ज् (लजि) १०/ भासार्थः (प) ।
+√लुट् (लुट) १०/२२३ च×,श	भासार्थः (प) क्षी-शा-हे । भाषार्थः—मै-सा-जै-काक्-कात । भासि—वो ।	
+√लुण्ट् (लुण्ट) १०/२६ मै-जै×,श	स्तेये (प) इत्येके—क्षी । क्षी-सा-च-काक्-कात-शा-हे । अवज्ञा-चौर्ये—वो ।	<√लुण्ठ् (लुण्ठ) स्तेये (प) । √लुण्ट् (लुटि) १/ स्तेये (प) ।
+√लुण्ठ् (लुण्ठ) १०/२६ सा-श-च-काक्-कात-शा-हे×	स्तेये (प) क्षी-मै-जै-वो ।	>√लुण्ट् (लुण्ट) स्तेये (प) इत्येके—क्षी ।
+√लुम्ब् (लुबि) १०/११६ च×,श	अर्दने (प) क्षी-मै-जै-काक्-कात-	√तुम्ब् (तुबि) १०/ अर्दने (प) ।

	शा-हे-वो। अदर्शने—सा। 'अर्दने' इति मैत्रेयः—सा। मर्दने—काक्र।	√तुम्प् (तुपि) १०/ अर्दने इति दौर्गाः—क्षी।
+√लूष् (लूष) १०/७१ श (जै-√लुष्)	हिंसायाम् (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। वधे स्तेये च—वो।	√लूष् (लूष) १/ स्तेये (प) इति दुर्गः—क्षी। √रुश् (रुश) ६/ हिंसायाम् (प)।

ङ—√लूस (सक)=वधे, (२) पीडने, (३) दूषणे, (४) चौर्ये, (५) विनाशे, (६) अनादरे, (७) त्रोटने, (८) अल्पस्य दीर्घीकरणे; दीर्घस्य चाल्पीकरणे। लूसंति-सूअ. १,३,१,१४।

+√लोक् (लोकृ) १०/२४७ श×	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काक्र-कात। दर्शने—च। दीप्तौ—वो।	√लोक् (लोकृ) १/ दर्शने (आ)। √लोच् (लोचृ) १/ दर्शने (आ)। √लोच् (लोच) १०/ भासार्थः (प)।

यौ. क्रि.; प्रयोज. दर्शने—ह्वि.।

ग—लोकम्-ऋ. १०,३०,७। वसुधामभिलोकयन्-वा. रा. ६,२,७।

√लोच् (लोचृ) १०/२४८ च×, श (काक्र-√लोछृ)	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काक्र-कात। भासे—वो।	पूर्ववत्।

यौ. क्रि.; प्रयोज. दर्शने, विचारे—ह्वि.।

ग—अन्वालोचयत्-बृहदारण्यको. ४९ शाङ्करभाष्यम्। आलोचयामः-काव्या. श्रौ. (टीकायाम्)-८५,३। उपोषिताभ्यामिव लोचनाभ्याम्-रघु. २,१९। लोचने दीप्तिरिति भासार्थस्य सिद्धिः स्पष्टा।

+√वच् (वच) १०/२९३ श-च×	भाषणे (प) आधृषाद्वा क्षी-मै-शा-हे।	√वच् (वच) २/ भाषणे (प)।

	कात-शा-हे । द्रावणे—वो ।	√ली ९/ श्लेषणे (प)। लीलायताम्–गुह्यकाल्यु.५०।
+√लुञ्ज् (लुजि) १०/३१	हिंसाबलादाननिकेतनेषु (प) क्षी-सा। हिंसाबलदाननिकेतनेषु—हे। भा,–षट्टार्थे (=निकेतने हिंसे बले दाने)—वो।	√लुज् ४/११६ विनाशे (आ) च। √लुञ्ज् (लुजि) १०/ भासार्थः (प)।
+√लुञ्ज् (लुजि) १०/२२७ च-शा×,श	भासार्थः (प) क्षी-हे। भाषार्थः–मै-सा-जै-काकृ-कात। भायाम्—वो।	√लञ्ज् (लजि) १०/ भासार्थः (प)।
+√लुट् (लुट) १०/२२३ च×,श	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात। भासि—वो।	
+√लुण्ट् (लुण्ट) १०/२६ मै-जै×,श	स्तेये (प) इत्येके—क्षी। क्षी-सा-च-काकृ-कात-शा-हे। अवज्ञा-चौर्ये—वो।	<√लुण्ठ् (लुण्ठ) स्तेये (प)। √लुण्ट् (लुटि) १/ स्तेये (प)।
+√लुण्ठ् (लुण्ठ) १०/२६ सा-श-च-काकृ-कात-शा-हे×	स्तेये (प) क्षी-मै-जै-वो।	>√लुण्ट् (लुण्ट) स्तेये (प) इत्येके—क्षी।
+√लुम्ब् (लुबि) १०/११६ च×,श	अर्दने (प) क्षी-मै-जै-काकृ-कात-	√तुम्ब् (तुबि) १०/ अर्दने (प)।

	शा-हे-वो। अदर्शने—सा। 'अर्दने' इति मैत्रेयः—सा। मर्दने—काकृ।	√तुम्प् (तुपि) १०/ अर्दने इति दौर्गाः—क्षी।
+√लूष् (लूष) १०/७५ श (जै-√लुष्)	हिंसायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। वधे स्तेये च—वो।	√लूष् (लूष) १/ स्तेये (प) इति दुर्गः—क्षी। √रुश् (रुश) ६/ हिंसायाम् (प)।

ङ—√लूस (सक)=वधे, (२) पीडने, (३) दूषणे, (४) चौर्ये, (५) विनाशे, (६) अनादरे, (७) त्रोटने, (८) अल्पस्य दीर्घीकरणे; दीर्घस्य चाल्पीकरणे। लूसंति–सूअ. १,३,१,१४।

+√लोक् (लोकृ) १०/२४७ श×	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात। दर्शने—च। दीप्तौ—वो।	√लोक् (लोकृ) १/ दर्शने (आ)। √लोच् (लोचृ) १/ दर्शने (आ)। √लोच् (लोच) १०/ भासार्थः (प)।
यौ. क्रि.; प्रयोज.	दर्शने—ह्वि.।	

ग—लोकम्–ऋ. १०,३०,७। वसुधामभिलोकयन्–वा. रा. ६,२,७।

√लोच् (लोचृ) १०/२४८ च×, श (काकृ-√लोछ्)	भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काकृ-कात। भासे—वो।	पूर्ववत्।
यौ. क्रि.; प्रयोज.	दर्शने, विचारे—ह्वि.।	

ग—अन्वालोचयत्–बृहदारण्यको. ४९ शाङ्करभाष्यम्। आलोचयामः–कात्या. श्रौ. (टीकायाम्)–८५,३। उपोषिताभ्यामिव लोचनाभ्याम्–रघु. २,१९। लोचने दीप्तिरिति भासार्थस्य सिद्धिः स्पष्टा।

+√वच् (वच) १०/२९३ श-च×	भाषणे (प) आधृषाद्वा क्षी-मै-शा-हे।	√वच् (वच) २/ भाषणे (प)।

परिभाषणे—सा.।
संदेशने—कात-हे।
संदेशवचने—जै।
चन्द्रः संदेशे चुरादि-
माह—क्षी।
यौ. क्रि.; प्रयो.—ह्वि.।

ग—वाचयति-शब्रा. २,५,२,२१; काब्रा. १,५,१,१८; ऐब्रा. ८,६। वाचयति-शि. ७,७८।

ङ—√बुझाव (सक)=आकारणे-ठा. ३,२-पत्र. १२८।

+√वज् (वज) १०/८० मै-श-च×
मार्गसंस्कारगत्योः (प)
क्षी-सा।
मार्गगतौ संस्कारगतौ
चेत्येके—क्षी।
मार्गणसंस्कारयोः—जै।
'मार्गणसंस्कारे' इति
दुर्गः—क्षी।
क्षी-काकृ-कात-शा।
मार्गणसंस्कारगत्योः—हे।
गतौ संस्कृतौ च—वो।
प्रयो. दार्ढ्ये—ह्वि.।
√वज् (वंज) १/ गतौ (प)।
√व्रज् (व्रज) १/ गतौ (प)।

ग—वाजेभिः—ऋ. ४,२२,३=अन्नैः (सायणः); वाजमर्वत्सु-५,८५,२=बलम्। वाजं नः स्वदतु-वा. सं. ९,१=घृतम्। वाजयति-तांब्रा. १४,८,६। वाजयन्—ऐब्रा. १,५,२।

+√वञ्च् (वन्चु) १०/१७१ च×,श
प्रलम्भने (आ)
क्षी-मै-सा-जै-काकृ-
कात-शा-हे।
वञ्चने—वो।
यौ. क्रि.; प्रयोज. ह्वि.।
प्रलम्भनम् =मिथ्याफलाख्यानम्—क्षी।
√वञ्च् (वन्चु) १/ गत्यर्थः (प)।

ग—वञ्चयते-ऋ. १,१४२,४। वञ्चयामास-वा. रा. ५,४०,९। वञ्चयानौ पुनश्चैव चेरतुः-भभार. ९,३१,९५। वञ्चयन्ते जनान् ऋजून्-कथासरि. २४,७९; २८,१७५।

छ—√ वंचना*
छ—√ बंचना*† } = प्रवञ्चने ।

छ—बाचना‡ = सुरक्षितत्वे, कष्टात् पार्थक्ये ।

+√ वट (वट) १०/३०३ श-च × (कात-√ वठ)	ग्रन्थे (प) क्षी-मै-सा-जै-काकृ- कात-हे । ग्रन्थने—शा । वेष्टे भागे च—वो ।	√ वट् (वट) १/ वेष्टने (प) । √ वट् (वट) १/ परिभाषणे (प) मित् । √ वृत् ६/३५ ग्रन्थे हिंसायां च (प) । √ वेष्ट् (वेष्ट) १/ वेष्टने (आ) । √ भट (भट) १०/१९३ a ग्रन्थे (प) काकृ ।

ग—द्रष्ट. √ वट् (वट) १/ वेष्टने (आ) ।

+√ वट (वट) १०/३६० क्षी-श-च-जै-शा ×	विभाजने (प) मै-सा-काकृ-हे । कात ? वेष्टे भागे च—वो ।	√ वण्ट् (वटि) १०/४९ विभाजने (प) । √ वण्ड् (वडि) १०/४९ विभाजने (प) ।

+√ वण्ट् (वटि) १०/४९ श-च-जै-काकृ-कात- शा × यौ. क्रि.; कर्मणि	विभाजने (प) इत्येके—क्षी । क्षी-मै-सा-हे । वण्टने—वो । —ह्वि. ।	<√ वण्ड् (वडि) विभाजने (प) ।

छ—√ बाँटना = विभाजने । वितरणशब्दादस्य व्युत्पत्तिरसङ्गता ।
छ—√ बँटाना = विभाजने (प्रयो.) ।

+√ वण्ट (वटि) १०/३६३ श-च-काकृ-कात × (जै-√ वन्त्र्)	विभाजने (प) क्षी-मै-सा-जै-शा-हे । भागे—वो ।	√ वण्ट् (वटि) १०/ विभाजने (प) इत्येके—क्षी । √ वण्ड् (वडि) १०/ विभाजने (प) ।

ग—वण्ट्यते-ह्वि. । द्र. √ वण्ट् १/

छ—पूर्ववत्।

+√वण्ड् (वडि) १०/४९ मै-काकृ-कात×,श	विभाजने (प) क्षी-सा-च-जै-शा-हे। विभागे—वो।	>√वण्ट् (वटि) विभाजने (प) इत्येके—क्षी। √वण्ड् (वडि) १/ विभाजने (आ)। √वण्ट् (वटि) १/ विभाजने (आ) नन्दी तु—क्षी। √वण्ट् (वटि) १/ विभाजने (प)।

ग—द्रष्ट. √वण्ड् (वडि) १/ विभाजने (आ)।

+√वद् (वद) १०/२८८ श-च×	संदेशने (प) क्षी,-मै (उ),-हे-(आ)। संदेशवचने—सा (उ),-शा (आ)। वाक्संदेशयोः—वो (उ)। भाषणे—हे-जै-कात (आ),-काकृ।	√वद् (वद) १/ व्यक्तायां वाचि (प)।
यौ. क्रि.; प्रयो.	—ह्वि.।	

ग—वादयेत्—मभार. ५,१३,७०।

छ—√बजाना=शब्दे।

+√वन् (वन) १०/२८७ मै-श-च-जै-काकृ-कात-शा× (सा-√चन्)	श्रद्धोपहिंसनयोः (प) इति चान्द्रं पारायणम्—क्षी। क्षी-हे। श्रद्धोपहिंसनयोः—अत्र कचित् पठ्यते—सा। उपहतौ श्रद्धाघाते श्रद्धोपकारयोः—वो।	वनुष्यति-निघः २/१२ =क्रुध्यतिकर्मा। √तन् (तनु) १०/ श्रद्धोपकरणयोः (प)।
यौ. क्रि.; प्रयोज.	विजये—ह्वि.।	

ग—गावो घृतस्य मातरोऽमूं सं वानयन्तु (तुल.-अ.वे. प्राति. ४,९३)-अ.वे. ६,९,३।

+√वर (वर) १०/२९८ शX	ईप्सायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे। ईप्से—वो।	√वृ (वृञ्) ५/ वरणे (उ)। √वृ (वृङ्) ९/ संभक्तौ (आ)।
√वृं–यौ. क्रि.; प्रयो.–वरणे—ह्वि.।		√वृ (वृञ्) १०/ आवरणे (उ)।

ग—वरय–अन्नपूर्णो. १,१०; सांर. २७७:२३। वरयेत्–इतिहासो. १९:१७।

+√वर्ण् (वर्ण) १०/१७ च-जै-काकृ-कात-शाX,श	वर्णने (प) क्षी-सा। प्रेरणे—मै-सा। हे ? वर्णे—वो।	पूर्ववत्। वर्णः (व्रियते इति √वृ+ उणा. ३/१० इति नः स च नित्।) वर्णो वृणोतेः–निरु. २,३,३।

वर्णं गृह्णाति—वर्णयतीति व्युत्पत्त्यन्तरम्–मै १०/१७।

ग—वर्णम्–ऋ. १,८६,५; १०,१०४,४। वर्णयन्ति–त्रिपाद्विभूतिमहानारायणो. ६,१; सूर्यतापिन्यु. १,७।

घ—वण्णेति–जातक १,२,२२२।

ङ—√वण्ण (सक)=(१) वर्णने, (२) प्रशंसने, (३) कृष्णादौ रङ्गे। वण्णआमो–पि. ४९०।

ङ—√वन्न (सक)=(१) वर्णने, (२) प्रशंसने, (३) कृष्णादौ रङ्गे वन्नेहि–कुमा.; उव.।

छ—√बनना (<वर्णनम्=चित्रणादौ)=(१) सामग्रीप्रस्तुतौ, (२) रचनायाम्।

छ—√बरनना *† (<वर्णनम्)=वर्णने।

+√वर्ण (वर्ण) १०/३८४ श-चX(जै-शा-√वर्ण्)	वर्णक्रियाविस्तारगुण-वचनेषु (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे।	पूर्ववत्।

पूर्वस्माद् धातोरभिन्नोऽयम्।

ग—यथा हि भारत वर्णैर्वर्णयन्त्यात्मनस्तनुम्–इन्दिशे स्मृशे ४७९६ (याज्ञ.)।

घ—वण्णेति–जातक १,५९,८४।

+√वर्ध् (वर्ध) १०/११४ च×, श (काक्र-√वृध्) | छेदनपूरणयोः (प) क्षी-मै-सा-कात-हे। पूरणे छेदने च—नै-शा। काक्र ? | √वृध् (वृधु) १/ वृद्धौ (आ)। √वड्ड् १/१६१ खनने (प) काक्र।

ग—इमा हि त्वामूर्जो वर्धयन्ति-ऋ. २,११,१। वर्द्धकिः (वर्धयति=छिनत्तीति) =त्वष्टा—वा. रा. १,१३,७। प्राङ् नाभिवर्धनात्-मनु. २,२९=नाभिछेदनात् प्राक्—(मन्वर्थ.)।

घ—वद्धेति=छेदने। जातक ६,५२७।

छ—√बढ़ाना=छेदने, निर्वापणे (दीपपण्यादीनाम्)।

छ—√बढ़ाना=पुष्टौ।

+√वर्ह् (वर्ह) १०/२३२ च-काक्र× (क्षी-श-शा-√बर्ह्) | भाषार्थः (प) मै-सा-जै-कात। भासार्थः—क्षी-शा-हे। वर्हे दीप्तौ—वो।

ग—यथा वर्हाणि चित्राणि बिभर्ति भुजगाशनः—मभार. १२,१२०,४ [ब-(व) र्हयति=दीप्यत इति ब (व) र्हम्]।

+√वल्क् (वल्क) १०/३५ श | परिभाषणे (प) क्षी-मै-सा। भाषणे—च-जै-काक्र-कात-शा-हे-वो। | √श्वल्क् (श्वल्क) १०/ परिभाषणे (प)। √वल् (वल) १/ संवरणे (आ)। √वल्ग् (वल्ग) १/ गत्यर्थः (प)।

ग—[तस्य (यो) वल्कः परापतत्-तैब्रा. १,४,७,६.]।

छ—[बकला (<वल्कलम्)=वल्कलम्]

+√वल्यूल (वल्यूल) १०/३२८ मै-सा-श-च-जै-काक्र-कात-शा× | लवनपवनयोः (प) इति दौर्गाः—क्षी। क्षी-हे। लवनपतनयोरिति | <√पल्यूल (पल्यूल) लवनपवनयोः (प)। √पल्युल (पल्युल) १०/ लूनिपूत्योः (प) वो।

	दुर्गः—क्षी । पल्यूलार्थे (=लूनि-पूत्योः)—वो ।	√वल्युल (वल्युल) १०/ पल्यूलार्थे (प) वो । √पू (पूञ्) ९/ पवने (उ)। √पल १०/२१३ पवने (प) काक्ृ ।

√पल १०/२१३ पवने (प) काक्ृ, +√पू (पूञ्) ९/ पवने (उ) >√पल्पू (ल) >√पल्यूल–इति लक्ष्यते विकासः ।

+√वल्ह् (वल्ह) १०/२३३ च×, श (क्षीं-काक्ृ-शा-√वल्ह्)	भाषार्थः (प) मै-सा-जै-काक्ृ-कात । भासार्थः—क्षी-शा-हे । त्विषि—वो ।	√वर्ह् (वर्ह) १०/२३२ भाषार्थः (प) मै ।
+√वस् (वस) १०/२०४ च×, श	स्नेहच्छेदापहरणेषु (प) क्षी-सा-जै । स्नेहच्छेदावहरणे—काक्ृ । स्नेहच्छेदावहरणेषु—कात-शा-हे । स्नेहच्छेदापहरणेषु—मै । अवहरणे च—मै । वधे स्नेहच्छिदोश्च—वो ।	√वस् (वस) १/ निवासे (प)। √वस् (वस) २/ आच्छादने (आ)। √वस् (वसु) ४/ स्तम्भे (प)।

ग—क्रमतस्तु प्रवासनम्–मनु. ९,२४२=वधः (मन्वर्थ.)।

+√वस (वस) १०/३८५ क्षी-श-च-जै-काक्ृ-कात-शा×	निवासे (प) मै-सा-हे । वासे—वो ।	√वास (वास) १०/ उपसेवायाम् (प)।

ग—[ब्राह्मणं मे पिता पूर्वं वासयामास·····–मभार. ३,१२६१]।

+√वा (वा) १०/३२९ मै-सा-श-च-जै-काक्ृ-शा×	गतिसुखसेवनयोः (प) क्षी । गतौ—कात-हे । सुखाप्तिगतिसेवासु—वो ।	>√वात (वात) गतिसुखसेवनयोः (प) इत्येके—क्षी ।

यौ. क्रि.; प्रयो. वाते—ह्वि. ।

ग—व्रापयति-ह्वि. । मया नावाप्तम् ।

+√वात (वात) १०/३२९ गतिसुखसेवनयोः (प) <√वा गतिसुखसेवनयोः
श-च-कात× इत्येके—क्षी । (प)।
(जै-√वात) क्षी-काक्र-शा-हे । √वा २/ गतिगन्धनयोः
(काक्र—'०सेचनयोः'— (प)।
त्रुटिः)।
सुखसेवनयोः—मै-सा ।
गतिसेवयोः सुखे (च)
—वो ।

ग—वातयति व्यजनेन पतिं पतिव्रता-सैण्टपीटर्स. । वातयन्त्रविमानक०—कथासरि. ४३,४४ ।

+√वास (वास) १०/३३१ उपसेवायाम् (प) √वस् (वस) १/ निवासे
श× क्षी-मै-सा-च-जै-काक्र- (प)।
कात-शा-हे-वो । √वस् (वस) २/ आच्छादने
गतिसुखसेवनयोः—जै। (आ)।
√वस् (वस) १०/२०४
स्नेहच्छेदापहरणेषु (प)।
विवासति—निघ. ३/५=
परिचरणकर्मा ।

उपसेवा तु=गुणान्तराधानम्—दुर्गादासः ।

ग—वासयति-सार. २२२:१५ । (अनिलः) वासयत्यभितो भूमिम्—दे. भा. ८,६,३ । वासितम्-१ योत. ३४ । आवासयन्तः—वा. रा. २,१०३,१४=सुरभी-कुर्वन्तः (तिल.)।

घ—वासेति-विनय. १,२११=सुरभीकरणे ।

च—√वास (सक)=(१) संस्कारे, (२) सुरभीकरणे, (३) निवासे वासइ-भवि. ।

छ—√वसाना † } =सौगन्ध्ये, गन्धे-बुं. ख. ।
छ—√वसाचौ † }

+√विच्छ् (विछ) १०/२४२ भासार्थः (प) √विच्छ् (विछ) ६/ गतौ
च×,शं क्षी-शा-हे । (प)।

भाषार्थः—मै-सा-जै-
काक्र-कात।
त्विषि—वो।

ङ—[√विच्छाय (सक)=निस्तेजस्त्वे। विच्छाएइ-गउड.। (नामधातुरयम्। विगता छाया तेजो यस्मात् तत्)]

+√वित्त (वित्त) १०/३७८
मै-सा-श-च-जै-काक्र-कात-
शा×

समुत्सर्गे (प)
क्षी-हे।
त्यागे—वो।

>√व्यय (व्यय) वित्त-
समुत्सर्गे (प) इति
सभ्याः—क्षी।
√विद् (विद्लृ) ६/
लाभे+क्ते।

समुत्सर्गः=त्यागः—क्षी।

ग—वित्ते रमस्व-ऋ. १०,३४,१३। वित्तैषणा-शब्रा. १४,६,४,१।

+√विद् (विद) १०/१७६
श, (जै-√विष् [विषै]) मुद्रणदोषः। 'विदै' इति स्यात्।

चेतनाख्यानविवादेषु (आ)
क्षी।
वेदनाख्यानविवादेषु—मै।
चेतनाख्याननिवासेषु—सा-कात-
शा-हे।
वेदनायाम्—च।
जै ?
वेतनाख्याननिवासनेषु—काक्र।
'चेतनाख्यान' इति
भाव्यम्।

√विद् (विद) २/ ज्ञाने
(प)।
√विद् (विद) ४/ सत्तायाम् (आ)।
√विद् (विद) ७/ विचारणे
(आ)।
वेदयन्ते-निरु. ५,२,६।

यौ. क्रि.; प्रयोज. ज्ञाने—ह्वि.।

ग—आचार्याय वेदयति-आश्व. श्रौ. ८,१४,३। वेदयन्ति ते-वा. रा. १,७६,१४। तस्य त्वं वेदयस्व ह-मभार. १४,१८,३५; काले वेदयते सदा-२,१७५। वेदये-वा. रा. २,६४,७३।

घ—वेदेति-सुत्तनिपात २११।

ङ—√वेअ (सक)=(१) अनुभवे, भोगे, (२) ज्ञाने। वेअइ, वेएइ—सम्यक्त्वो. ९।

+√विप् (विप) १०/१३८ क्षेपे (प) मै-सा-श-च-जै-काकृ-कात-शा-हे। क्षी-वो।
√विप् १/ ......यौ. क्रि.—कम्पने—ह्वि.।

√टिप् (टिप) १०/१३८ क्षेपे (प)।
√डिप् (डिप) १०/ क्षेपे (प)।
√तिप् (तिप) १०/ क्षेपे (प)।
√वेपृ (वेपृ) १०/ कम्पने (आ)।

ग—वेना अवीविपन्—ऋ. ९,७३,२; चक्रं न वृत्तं व्यतीरवीविपत्—ऋ. १,१५५,६; विपः....विधन्त–३,३,१।

+√विल् (विल) १०/७१ क्षेपे (प) क्षी-मै-च-जै-कात-शा-हे-वो×,श सा-काकृ।

√वी २/ गतिव्याप्तिप्रजनकान्त्यसनखादनेषु (प)।
√विल् (विल) ६/ संवरणे (प)।
√वेलृ (वेलृ) १/ चलने (आ)।

+√विष्क् (विष्क) १०/१५१ हिंसायाम् (आ) क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो× सा।

<>√किष्क् (किष्क) १०/१५४ हिंसायाम् (आ)।
√हिष्क् (हिष्क) १०/ हिंसायाम् (आ) इति दुर्गः—क्षी।
√हिक् १०/११९b हिंसायाम् (आ) काकृ।

क्वचित् कोशे 'हिष्क' इति पठ्यते—सा।

√विष्क (विष्क) १०/३८३ दर्शने (प) क्षी-श-च-जै-काकृ-कात-शा-हे-वो× मै-सा।

वि+√लक्ष (लक्ष) १०/ दर्शनाङ्कनयोः (आ)—विलक्ष>विलष्क्>(ललोपे)>√विष्क्।
√ब्लेष्क् (ब्लेष्क) १०/ दर्शने (आ) क्षी।

√विष्क् (विष्क) १०/१५१
हिंसायाम् (आ) सा।
वि+√ईक्ष् १/ दर्शने (आ)=
√वीक्ष् >√वीष्क्>;
√विष्क् इति वागीशः।

+√वीज (वीज) १०/६४ (प) १०/(१/१७९) क्षी×,हे ? मै-सा-श-च-जै-काकृ-कात-शा× व्यजने—वो। √विज् (विज) १/२१४ गतौ (प) इत्येके—क्षी। वि+√ईज् १/ गतिकुत्सनयोः (आ)=√वीज्। वि+√अज् १/ गतिक्षेपणयोः (प) =√व्यज्, व्यजनम्

वीजेर्लौकिकादवीजयत्-क्षी।

ग—तेषु वेश्मस्ववीजयत्-वा. रा. ५,५०,८; राघवं पर्यवीजयत्-५,४५,९। पक्षाभ्यामभ्यवीजयत्-मभार. १२,६३४७; जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना ७,३०७। (तं) वीजन्ति बालव्यजनैः-हरिवंश. १३०९२।

ङ—√वीज (सक)=व्यजने। वीजइ, वीजेमि-मै. ६६।

ङ—√वीअ (सक)=व्यजने। वीअअंति-अभि. ८९। वीयंति-सुर. १,९६।

च—√विज्ज (सक)=व्यजने। कर्म-विजिज्जइ-भवि.।

छ—बिजना (<व्यजनम् ?)=व्यजनम्-बुं.ख.।

√वीड् १०/ दार्ढ्ये (प.)
अपाणिनीयः

यद् वीळयासि वीळु तत्-ऋ. ८,४५,६। वीळयतिश्च व्रीळयतिश्च संस्तम्भकर्माणौ पूर्वेण संप्रयुज्येते-निरु. ५,१६,१।

+√वीर (वीर) १०/३४७ च×,श विक्रान्तौ (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे। शौर्ये—वो। √वीड् (वीड) दार्ढ्ये-ऋ. ८,४५,६। √अज्+उणा. १/१३ रक्; अजेर्वीभावः। वि+√ईर् १०/ विशेषेण ईरयति दूरीकरोति शत्रून् =√वीर।

√वी २/ गतिव्याप्ति-
प्रजनकान्त्यसनखा-
दनेषु (प)।

ग—इन्द्रमनु वीरयध्वम्–ऋ. १०,१०३,६। वीरयस्व–ऐब्रा. ३,२०; तैब्रा. २,७,८,१। वीरैः स्याम सधमादः–ऋ. ५,२०,४=पुत्रैः। वीरहीनां तथा स्त्रियम्–मार्क. पु. ३५,३१=पतिपुत्रहीनाम्।

छ—बीर, बीरो=पुत्रः। "सो जा, मोरे वीर! वीर की बालैयाँ लैजैं गंगा जी के तीर" बुं. ख. लोकगीतम्।

+√बुक्क् (बुक्क) १०/१७२ च× (क्षी-सा-श-काकृ-कात-शा-हे-वो-√बुक्क्)	भाषणे (प) मै। क्षी-मै-सा-जै-काकृ-कात-शा-हे। भर्त्सने—जै। श्वादिशब्दे—वो।	√बुक्क् (बुक्क) १/ भषणे (प)। √बुख् १/४६० a चलने (आ) काकृ।

छ—√भौंकना।

+√वृ (वृञ्) १०/२६४ च×,श	आवरणे (उ) क्षी-मै-सा-काकृ-कात-हे। जै? वृतौ—वो।	√वृ (वृञ्) ५/ वरणे (उ)। √वॄ (वॄञ्) ९/ वरणे (उ)।

यौ. क्रि.; प्रयोज. वृतौ—ह्वि.।

ग—वारयते–तांब्रा. ९,६,११; तैब्रा. १,८,२,५। वरन्ते–ऐब्रा. ४,२०; जैब्रा. १८०।

घ—वारेति–पेतवत्थु २,७।

ङ—√वार (सक)=रोधे, निषेधे। वारेइ–उव.; महा.।

छ—√वराना (<वारणम्)=सत्यपि प्रसङ्गे कस्या अपि वार्ताया अनुदीरणे, वारणे, (२) त्यागे, (३) रक्षायाम्, (४) क्षेत्रेभ्यो मूषिकादीनामपसारणे।

छ—√बारना=निषेधे।

+√वृंह् (वृंहि) १०/२३१ च× (क्षी-श-काकृ-शा-हे-√बृंह्)	भाषार्थः (प) मै-सा-जै-काकृ-कात। भासार्थः—क्षी-शा-हे। त्विषि—वो।	√बृंह् (बृंहि) १/ शब्दे, च=वृद्धौ (प)। √बृह् (बृहिर्) १/ शब्दे च (प) इति दुर्गः—क्षी।

+√वृज् (वृजी) १०/२६३ श

वर्जने (प) आधृषाद्वा क्षी-मै-सा-च-जै-काक्र-कात-शा-हे। त्यागे—वो।

√वृज् (वृजी) २/ वर्जने (आ)।
√वृज् (वृजी) ७/ वर्जने (प)।
√वृञ्ज् (वृजि) २/ वर्जने (आ)।

यौ. क्रि.; प्रयोज. वेष्टने—ह्वि.।

ग—वर्जयति—छान्दोग्यो. २,२२,१; ऋ. प्राति. ६,१०,१५,८; लाट्या. श्रौ. ३,३,२५। वर्जयसि—वा. रा. २,१००,६७। यत्र वर्जयते राजा—मनु. ९,२४६; वर्जयेत् २,१७७।

ङ—√वज्ज (सक)=त्यागे—काल.; महा.; पंचा. १२,६।

+√वृत् (वृतु) १०/२५२ च×,श

भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-जै-काक्र-कात। दीप्तौ—वो।

√वृत् (वृतु) १/ वर्तने (आ)।
√वृत् (वृतु) ४/ वरणे (आ)।
√वृध् (वृधु) १/ वृद्धौ (आ)।

ग—[वर्तयतं दिवो वधम्—ऋ. ७,१०४,४।]

+√वृध् (वृधु) १०/२५३ च-जै×,श(काक्र—√बृध्)

भासार्थः (प) क्षी-शा-हे। भाषार्थः—मै-सा-काक्र-कात। दीप्तौ—वो।

√वृध् (वृधु) १/ वृद्धौ (आ)।
√वर्ध् (वर्ध) १०/ छेदन-पूरणयोः (प)।

+√वृष् (वृष) १०/१७२ मै-शा-च-कांक्र-कात-वो×

शक्तिबन्धने (आ) क्षी-सा-जै-शा। 'शक्तिसम्बन्धे' इति मैत्रेयः—सा।

√वृष् (वृषु) १/ सेचने (प)।
√धृष् (धृष) १०/ सामर्थ्य-धारणार्थः (आ) इत्येके—क्षी।
वृषायमाणः—तैब्रा.२,५,४,२।
अवृषायिषत—मंब्रा.२,३,७।

शक्तिबन्धनम्=प्रजननसामर्थ्यम्—क्षी।

√वृष् (वृषु) १०/१६३

शक्तिसम्बन्धे (आ) मै-कात। शक्तिबन्धे—हे। प्रजनैश्वर्ये—वो।

यौ. क्रि.; प्रयो. वर्षणे—ह्वि.।

ग—यूयं वृष्टिं वर्षयथ—ऋ. ५,५५,५।

+√ वेल (वेल) १०/३२७　कालोपदेशे (प)
　शा-च×　　　　　　क्षी-मै-सा-जै-काकृ-
　　　　　　　　　　कात-शा।
　　　　　　　　　　हे ?
　　　　　　　　　　कालार्थे—वो।

ग—संवत्सरवेलायाम्-शब्रा. ७,४,२,३८। वारंवेलः-वा. रा. २,५९,३०-
वेला=मर्यादा (तिल.)।

+√ व्यप् (व्यप) १०/९४　व्यये (प) इति　　<√ व्यय् (व्यय) क्षये (प)।
　मै-श-जै-काकृ-कात-　कौशिकः—क्षी।　　वि+अपेत्युपसर्गौ=
　शा-हे×　　　　　　क्षये—सा-वो।　　　√ व्यप्।
　　　　　　　　　　(कूट) दाहे—च।

+√ व्यय् (व्यय) १०/९४　क्षये (प)　　　वि+√ इ (इण्) २/ गतौ (प)
　मै-श-च×　　　　　क्षी-सा-जै-काकृ-　　=√ व्यय्।
　　　　　　　　　　कात-शा-हे　　　वि+√ अय् (अय) १/ गतौ (आ)
　　　　　　　　　　तुदि—वो।　　　　=√ व्यय्।
　　　　　　　　　　　　　　　　　　√ व्यय् (व्यय) १/ गतौ (प)।
　　　　　　　　　　　　　　　　　　√ व्यय (व्यय) १०/वित्तस-
　　　　　　　　　　　　　　　　　　मुत्सर्गे (प)।

√ व्यय (व्यय) १०/३७७　गतौ (प)　　　　पूर्ववत्।
　　　　　　　　　　क्षी-हे।
　　　　　　　　　　गतौ त्यागे—वो।

उत्तरधातोरभिन्नेयं प्रकृतिरिति शेषस्ततोऽवगन्तव्यः।

+√ व्यय (व्यय) १०/३७७　वित्तसमुत्सर्गे (प)　　पूर्ववत्।
　च×, श　　　　　　इति सभ्याः—क्षी।
　　　　　　　　　　क्षी-मै-सा-जै-काकृ-
　　　　　　　　　　कात-शा-हे।
　　　　　　　　　　समुत्सर्गे—हे।
　　　　　　　　　　गतौ त्यागे—वो।
　　　　　　　　　　व्यये—ह्वि.।

ग—पृष्टोऽपव्ययमानस्तु-मनु: ८,६०=अपह्नुवानः (मन्वर्थ.); ह्नुत्वाऽपव्ययते च यत्-८,३३२=अपह्नुते (मन्वर्थ.)।

+√व्युन्द् (व्युदि) १०/९४ मै-सां-शं-च-जै-काकृ-कात-शा-हे-वो×	व्यये (प) इति नन्दी—क्षी।	<√व्यय् (व्यय) क्षये (प)। वि+√उन्द् (उन्दी) ७/क्लेदने (प)।

ग—व्युन्दन०-वां. सं. २,२ (क्लेदने)।

+√व्रज् (व्रज) १०/८० च-काकृ-कात-शा×,श	मार्गसंस्कारगत्योः (प) इति चन्द्रः—क्षी। क्षी-सा। मार्गसंस्कारयोः, गतौ च—मै। मार्गणसंस्कारयोः—जै। मार्गणसंस्कारगत्योः—हे। गतौ संस्कृतौ च—वो।	<√वज् (वज) मार्गसंस्कारगत्योः (प)।

यौ. क्रि.; प्रयो. द्वि.।

ग—रामं प्राव्राजयत् समाः—रघु. १२,६=प्रावासयत् (संजी.)।

+√व्रण (व्रण) १०/३८३ च×,श	गात्रविचूर्णने (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे। अङ्गचूर्णे—वो।	√व्रण् (व्रण) १/ शब्दार्थः (प)। √वृण् १/२०८d क्रिमिभक्षणे (प) काकृ। व्रन्दी व्रन्दतेर्मृदुभावकर्मणः-निरु. ५,१६,१।

क—उएर् =विदारणे। बोहे. व्रन्; रसैन्-वॉरॉन=छिद्रम्-वा. पॉकर्नीः।

ग—साकूतनिर्व्रणित०-कथासरि. ३८,२८। व्रणयति (अधरम्)—इन्दिशे स्पूशे २९९०।

+√शट् (शट) १०/१६० मै-सा-श-च-जै-काकृ-कात-शा×	श्लाघायाम् (आ) इति नन्दी—क्षी। क्षी-हे। श्लाघे—वो।	<√शठ् (शठ) श्लाघायाम् (आ)। √शल् (शल) १०/१६० श्लाघायाम् (आ) इति कौशिकः—क्षी।

		√शल्भ् शल्भ १/ कत्थने (आ)। √शाड् (शाडृ) १/ श्लाघायाम् (आ)।
+√शठ् (शठ) १०/२७ च-जै-शा×,श	असंस्कारगत्योः (प) क्षी-सा। संस्कारगत्योः—मै- काक्त-कात-हे। आलस्ये गत्यसंस्कृत- संस्कृते—वो।	√सठ (सठ) श्वठार्थे= [गत्यसंस्कृत-संस्कृते] (प) वो। √शठ् (शठ)१/ कैतवे (प)।
+√शठ् (शठ) १०/१०४ मै-सा-श-च-काक्त-कात- शा-हे×	आलस्ये (प) इत्येके— क्षी। क्षी-वो।	<√शुठ् (शुठ) आलस्ये (प)।
+√शठ् (शठ) १०/१६० च×,श	श्लाघायाम् (आ) क्षी-मै-सा-जै,-काक्त (प),-कात-शा-हे-वो।	>√शट् (शट) श्लाघायाम् (आ) इति नन्दी—क्षी।
+√शठ (शठ) १०/३०० श×	असम्यगाभाषणे (प) क्षी। सम्यगाभाषणे—मै-च- काक्त-कात। सम्यगवभाषणे— सा-जै-शा। सम्यग्भाषणे—हे। दुर्वाचि—वो।	द्रष्ट. √शट् (शट) १०/१६० श्लाघायाम् (आ)।

"सम्यगाभाषणे=सम्यंग्वचनक्रियायाम् इति क्षीरस्वामी"-पुरुषकारः (६९ पृ.)।

+√शब्द् (शब्द) १०/१८२ च×,श	उपसर्गादाविष्कारे (प) क्षी-मै-सा-काक्त-कात-शा। शब्दक्रियायाम्—मै। आविष्करणे—जै।	पिब्दना-ऋ. ६,४६,६; शौ. २०,८,२। अव्यक्तं शब्दायमाने, रक्षोभेदे- वाचस्पत्यकोशः। अपि

	भाषाविष्कारयोः--हे ।	+शब्द (पृषोदरादीनि)
	आविष्कृतौ--वो ।	=√पिब्द्, पिब्दना ।
	शब्दकृतौ--वो (निरुप-सर्गः) ।	शब्यते-निरु. १, १८,१ ।
	भाषणेऽपि शब्दविशेषेऽस्य वृत्तिं स्मरन्ति--मै ।	

ग—अहरभिशब्दयन्तः-आश्व. श्रौ. ६,१०,२३ । पञ्चरात्रानुशब्दितः-मभार. १२,१२९७६ । नामग्राहमशब्दयत्-कथासरि. ११०,२४ ।

+√शम् (शम) १०/१६४ च×, (जै √सम्).	आलोचने (आ) क्षी-मै-सा-जै-काकृ-कात-शा-हे । आलोचे—वो (उ) ।	√शम् (शमः) १/८०३ अदर्शने-मित् ।
यौ. क्रि.; प्रयो.	ह्वि. ।	

ग—निशामयत-वा. रा. ६,२१,२; निशाम्य-१,६९,१७=दृष्ट्वा (तिल.); निशम्य-२,१०,४=ज्ञात्वा (तिल.) । चित्रमद्य निशामय-मभार. ४,१९६८ ।

+√शम्ब् (शम्ब) १०/२१ शा-च-जै-काकृ-कात-शा-वो×	सम्बन्धे (प) चन्द्र आह—क्षी । क्षी-मै-हे । सम्बन्धने—सा ।	<√साम्ब् (साम्ब) सम्बन्धे (प) । शम्ब इति वज्रनाम, शमयतेर्वा शातयतेर्वा-निरु. ५,२४,२ ।

ग—[शम्बरं पर्वतेषु क्षियन्तम्-ऋ. २,१२,११; शम्बः-१०,४२,७ ।] शम्बूकं नाम नामतः-वा. रा. ७,७६,३ ।

+√शर (शर) १०/३१५ मै-सा-श-च-जै-काकृ-कात-शा-वो×	दौर्बल्ये (प) इति नन्दी—क्षी । क्षी-हे ।	<√शार (शार) दौर्बल्ये (प) । √शॄ (शॄन्) ९/ हिंसायाम् (उ) । शरः शृणातेः-निरु. ५,४,५ ।

ग—[मा युगं विश्परि-ऋः ३,५३,१७० । शर०-ऋ. १,१९१,३ । अग्निहोत्रं शरशरायत्-आश्व. श्रौ. ३,११,१९ । शरस्तम्बाच्च गौतमः-मभार. १,१३८,१५ ।

+√शल् (शल) १०/१६० मै-सा-श-च-जै-काकृ-कात-शा×	श्लाघायाम् (आ) इति कौशिकः--क्षी। क्षी-हे। श्लाघे--वो।	<√शठ् (शठ) श्लाघायाम् (आ)। द्रष्ट. √शाड् (शाडृ) १/ श्लाघायाम् (आ)।
+√शार (शार) १०/३१५ मै-सा-श-च जै-काकृ×	दौर्बल्ये (प) क्षी-कात-शा-हे-वो।	>√शर (शर) दौर्बल्ये (प) इति नन्दी--क्षी। >√सार (सार) दौर्बल्ये (प) इति दुर्गः--क्षी। √शॄ (शॄञ्)९/ हिंसायाम्(उ)।

? ग--विशारि-ऋ. ३,५३,१७।

+√शिष् (शिष) १०/२६७ श-च×	असर्वोपयोगे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो।	√शिष् (शिष) १/ हिंसार्थः (प)। √शिष् (शिष्लृ) १/ विशेषणे (प)।
विपूर्वः- च×	अतिशये--क्षी-मै-सा-जै-काकृ-कात-शा-हे। अतिशायने--वो।	

असर्वोपयोगः=अनुपयुक्तत्वम्--क्षी।
असर्वोपयोगः=परिशेषीकरणम्-दुर्गादासः।

ग--दत्तशेषं न शेषयेत्-मभार. १३,४००। न शेषयेतां युधि शत्रुसेनाम्-३,१४७६०।

+√शीक् (शीक) १०/२५५ क्षी-मै-श-च-जै-काकृ-कात-शा-हे-वो×	भाषार्थः (प) स्वामिकाश्यपानुसारेण--सा।	
+√शीक् (शीक) १०/२७६ श-च×(काकृ-√सीक्)	आमर्षणे (प) आधृषाद्वा क्षी-मै-सा-जै-कात-शा-हे। काकृ ? सेके आमर्षे च--वो।	√शीक् (शीक) १/ सेचने (आ)। √चीक् (चीक) १०/२०७ आमर्षणे (प) मै। √शक् (शक) ४/ विभाषितो मर्षणे (आ)।

ग—शीकित०–तै. ७,५,११,२। शीकाय–तैप्राति. ३,२। शीकायन्तु–वा. सं. २२,२६=सेचने।

+√शील (शील) १०/३२५ उपधारणे (प)
शX क्षी-मै-सा-च-जै-काक्र-कात-शा-हे।
अभ्यासेऽतिशायने—वो।
उपधारणम्=अभ्यासः—क्षी।
उपधारणम्=परिचय इत्येके—क्षी।

ग—शीलयेदुत्तरेण वा–आपस्त. १,३०,७। यतस्व पुण्यशीलने–मभार. १२,३२१,४३=अभ्यसने। नैकमेवातिशीलयेत्–सुश्रु. २,२१२,१७।

ङ—√सील (सक॰)=(१) अभ्यासे, (२) पालने–हित. १९।

+√शुक्ल् (शुक्ल) १०/८४ अतिसर्जने (प) सा।
क्षी-मै-श-च-जै-कात-शा-हे-वोX सर्जने—काक्र।

><√शुल्क् (शुल्क) १०/८१ सर्जने (प)। लकारककारयोर्वर्णविपर्यय इति वागीशः।

+√शुठ् (शुठ) १०/१०४ आलस्ये (प)
चX,श क्षी-मै-सा-जै-काक्र-कात-शा-हे-वो।

+√शुण्ठ् (शुठि) १०/१०५ शोषणे (प)
चX,श क्षी-मै-सा-जै-काक्र-कात-हे-वो।

√शुण्ड् १/१८३ m हिंसा-गत्योः (प)।

ग—द्रष्ट. √शुण्ठ् (शुठि) १/३४१ शोषणे (प)।

+√शुन्ध् (शुन्ध) १०/२८० शौचकरणे (प)
शX-च आधृषाद्वा। क्षी-शा।
शौचकर्मणि—मै (उ),-सा।
शुद्धौ—जै-कात-शा-हे (आ),-काक्र-वो।

√सुन्द् शोभे–सौ. धा.-वो।

यौ. क्रि.; प्रयोज. हि.।

ग—शुन्धयति–वा. सं. ४,२।

+√शुल्क् (शुल्क) १०/८१ सर्जने (प)
मै-श-च-कात-शा-हे× क्षी-काकृ।
(काकृ—√शुक्ल) अतिस्पर्शने—सा।
जै ?
सर्जने वर्जने भापे—वो।

>√शुल्ब् (शुल्ब) असर्जने (प) इत्येके—क्षी।
√शुल्क् १०/३३ भाषणे (प) काकृ।
√श्वल्क् (श्वल्क) १०/ परिभाषणे (प)।
√वल्क् (वल्क) १०/ परिभाषणे (प)।

ग—शुल्काय देयाम्–ऋ. ८,१,५; ७,८२,६। धनुः शुल्कावाप्तम्–मभार. १,७०८८। गृह्णीयाच्छुल्कमण्वपि–मनु. ३,५१।

+√शुल्ब् (शुल्ब) १०/७६ माने (प)
मै-श-च-काकृ× क्षी-सा-जै-कात।
(जै-कात√शुल्व्) सर्जने—कात-शा।
माने सर्जने च—हे।
माने सर्गे—वो।

>√शूर्प् (शूर्प) माने (प) इति चन्द्रः—क्षी।

ग—शुल्ब०–आपस्त. (कात्या. श्रौ.) १,३,१४। शुल्बसूत्रनामको ग्रन्थः।

+√शुल्ब् (शुल्ब) १०/८१ असर्जने (प) इत्येके—क्षी।

<√शुल्क् (शुल्क) सर्जने (प)।

१०/७६ धातोरभिन्नोऽयम्। अर्थभेदात् क्षीरस्वामिनाऽन्यत्र संख्यात इति सर्वेषां वैयाकरणानामर्थादयस्तत एवावसेयाः।

+√शूर् (शूर) १०/३४६ विक्रान्तौ (आ)
च×,श. क्षी-मै-सा-जै-काकृ-कात-शा-हे।
विक्रमे—वो।

√शूर् (शूरी) ४/ हिंसायाम् (आ)।
√शु १/ गतौ (प)+उणा. २/२५ क्रन् दीर्घश्चेति शूरः (शवति वीर्यं प्राप्नोतीति)। शूरः शवतेर्गतिकर्मणः—निरु. ४,१३,१।

ग—शविष्ठं न आ भर शूर शवः–ऋ. ६,१९,६; इमे नरो वृत्रहत्येषु शूराः–७,१,१०। शूराश्च कृतविद्याश्च–मभार. १,१०९,४।

+√शूर्प् (शूर्प) १०/७६ च×, श (काकृ √सूर्प्)	माने (प) इति चन्द्रः—क्षी। क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो।	<√शुल्ब् (शुल्ब) माने (प)। √शॄ (शॄञ्) ९/ हिंसायाम् (उ)+उणा. ३/२६ इति पः; चकारात् स च कित्।

ग—शूर्प०-तैब्रा. १,६,५,४; शब्रा. १,१,१,२२। सशूर्पपिटकाः-मभार. ५, ५२४९। विसृज्य सूर्पवद्दोषान् गुणान् गृह्णन्ति साधवः-इन्दिशे स्पूशे २८७८।

+√शृध् (शृध) १०/२०२ च-जै-वो×, श	अप्रसहने (प) क्षी-हे। 'प्रसहने=अभिभवे' इत्येके—क्षी प्रसहने—क्षी-मै-सा-शा-हे। प्रहसने—काकृ-शा।	√शृध् (शृध) १/ शब्दकुत्सायाम् (आ)। √शृध् (शृध)१/ उन्दे (उ)। √धृष् (धृष) १०/ अप्रसहने (प)। वर्णविपर्ययेण—√शृध्
१/ यौ. क्रि.; प्रयो.	औद्धत्ये—ह्वि.।	प्रहसने—काकृ-कात।

प्रहसनम्=विद्रव इति गोविन्दभट्टः-(श. क. द्रु.)।

ग—शर्धयन्तीति ह्वि. ऋग्वेदोदाहरणं प्रस्तौति। मया नोपलब्धम्।

+√श्रण् (श्रण) १०/४२ श	दाने (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे-वो।	√सन् (षणु) ८/ दाने (उ)।
१/, यौ. क्रि.; प्रयो.	ह्वि.।	

ग—विश्राणय सर्वशः-वा. रा. २,३२,२९; विश्राणितम्-२,३२,३६=दत्तम् (तिल.)। विश्राणयामास यथा वैश्रवणस्तथा-मभार. १३,२८०३। विश्राण्य-रघु. १४,१५=दत्त्वा-(संजी.)।

+√श्रथ् (श्रथ) १०/१३ च×, श(काकृ √श्रन्थ्) (कात—√ग्रन्थ्)	प्रतिहर्षे (प) क्षी-कात-शा-हे। प्रतियत्ने—मै-हे। प्रयत्ने—सा। 'प्रस्थाने' इति मैत्रेयः—सा।	

'अतिहर्षे' इति बहवः—
सा। (बा. ग. प.
प्रतिहर्षे पठति तद्
धातुवृत्तौ नास्ति)।
प्रीतिहर्षे—जै।
प्रतिहर्षणे—काक्र।
यत्ने प्रतिहृषि—वो।
१/, यौ. क्रि.; प्रयोज. शैथिल्ये—ह्वि.।

√श्रथ् (श्रथ) १०/२७३ शा-च कात× — हिंसायाम् (प) आधृषाद्वा क्षी-जै-शा। मोक्षणे—मै-सा-हे। हिंसायां बन्धने च—हे। बन्धे मोक्षे वधे—वो।
१/ यौ. क्रि.; प्रयोज. शैथिल्ये—ह्वि.।
>√श्रन्थ् (श्रन्थ) हिंसायाम् (प) इत्येके—क्षी। √ग्रथ् १०/३२८ हिंसायां बन्धने च (प) जै। √ग्रथ् १०/२४६ हिंसायां बन्धने(प) शा।

ग—श्रथन्ते–ऋ. ५,५९,१। अनु शिश्रथः–ऋ. ५,३२,२२। वि शश्रथे–ऋ. ९,७०,२ (अनु श्रन्थति–तै. ६,१,९,७)।

+√श्रथ (श्रथ) १०/३१७ शा-च× — दौर्बल्ये (प) क्षी-मै-सा-काक्र-कात-शा-हे-वो। शैथिल्ये—जै।
१/, यौ. क्रि.; प्रयो. ह्वि.।

ग—श्रथयति (अद्रिम्)–ऋ. १०,११२,८; ९,६८,२। श्रथयन्ताह सिस्रतः–ऋ. ५,५४,१०। श्रथयन्ति–ऐब्रा. ६,२४। शिश्रथन्–तैब्रा. २,५,४,४।

+√श्रन्थ् (श्रन्थ) १०/२७३ मै-सा-शा-च-जै-काक्र-कातं-शा× — हिंसायाम् (प) आधृषाद्वा इत्येके—क्षी हिंसार्थः—हे। दर्भे वधे—वो।
<√श्रथ् (श्रथ) हिंसायाम् (प)।

+√श्रन्थ् (श्रन्थ) १०/२८४	सन्दर्भे (प) आधृषाद्वा	√श्रथ् (श्रथ) १०/२७३
श-च×.	क्षी-मै-सा-जै-काकृ-	हिंसायाम् (प)।
	कात-शा-हे ।	
	दर्भे वधे—वो ।	

ग—[अनु श्रन्थति-तै: ६,१,९,७ ।]

+√श्लिष् (श्लिष) १०/३८	श्लेषणे (प)	√श्लिष् (श्लिष) ४/
च×, श	क्षी-मै-सा-जै-काकृ-	आलिङ्गने (प)।
	कात-शा-हे ।	
	श्लेषे—वो ।	
यौ. क्रि.; प्रयोज.	ह्वि. ।	

ग—श्लेषयेत् स्वजघनम्—रतिरह.[—किरातार्जु. ९,५०—मल्लि. टीकायाम् ।]

+√श्वठ् (श्वठ) १०/२८	असंस्कारगत्योः (प)	√शठ् (शठ) १०/२७ असं-
श	क्षी-सा ।	स्कारगत्योः (प)।
	संस्कारगत्योः—	
	मै-काकृ-कात-शा-हे ।	
	गतौ—च ।	
	गतिसंस्कारयोः—जै ।	
	गत्यसंस्कृतसंस्कृते—वो ।	

+√श्वठ (श्वठ) १०/३०१	असम्यगाभाषणे (प)	√शठ (शठ) १०/३००
	क्षी ।	असम्यगाभाषणे (प)।
	सम्यगवभाषणे—	
	सा-जै-शा ।	
	सम्यगाभाषणे—मै-च-	
	जै-काकृ-कात ।	
	सम्यग्भाषणे—हे ।	
	दुर्वाचि—वो ।	
	'अभाषणे' इति केचित्	
	—सा ।	

"सम्यगाभाषणे=सम्यग्वचनक्रियायाम् इति क्षीरस्वामी"—पुरुषकारः (६९ पृ.)।

+√श्वण्ठ् (श्वठि) १०/२८ श-च-काक्व-कात×	असंस्कारगत्योः (प) इति दौर्गाः—क्षी। क्षी-सा। संस्कारगत्योः— मै-शा-हे। गतिसंस्कारयोः—जै। गत्यसंस्कृतसंस्कृते—वो।	<√श्वठ् (श्वठ) असंस्कार- गत्योः (प)।
+√श्वभ्र् (श्वभ्र) १०/८५ मै-श-च-जै-काक्व- कात-शा×	गतौ, च=कृच्छ्रजीवने (प) इति दौर्गाः—क्षी। क्षी। गत्याम्—सा। गतौ—हे। विले गतौ तर्के—वो।	<√स्वर्त् (स्वर्त) गत्याम्, च=कृच्छ्रजीवने (प)। √श्वर्त् (श्वर्त) १०/८५ गत्याम् (प) मै।

ग—परि श्वभ्रेव दुरितानि वृज्याम्—ऋ. २,२७,५; शत्रा. ११,२,३,८। श्वभ्रम्—वा. रा. ३,४,११ (गी. प्रे. सं.)। श्वभ्र०—मार्क. पु. ५३,२९=छिद्र०।

+√श्वर्त् (श्वर्त) १०/८५ क्षी-च-कात-हे-वो×,श	गत्याम् (प) मै-सा-काक्व। गत्याम्, च= कृच्छ्रजीवने—शा। गमने, च= कृच्छ्रजीवने—जै।	श्वात्रति—निघ. २/४= गतिकर्मा। √स्वर्त् (स्वर्त) १०/ गत्याम्, च=कृच्छ्रजीवने (प)।
+√श्वल्क् (श्वल्क) १०/३४ श, (काक्व-√शुल्क्)	परिभाषणे (प) आधृषाद्वा क्षी-मै-सा। भाषणे—च-जै- काक्व-कात-शा-हे। भाषे—वो।	√वल्क् (वल्क) १०/परि- भाषणे (प)। √शुल्क् १०/३३ a भाषणे (प) काक्व।
+√श्वेत (श्वेत्) १०/३८७ श-जै-शा-हे-वो×	.........(प) क्षी-मै-सा-च-काक्व- कात× तेनातिक्रामति। तदाचष्टे।	√श्वित् (श्विता) १/ वर्णे (आ)।

+√सङ्केत (सङ्केत) १०/३४९ आमन्त्रणे (प) क्षी-मै-श-च-जै-काक्र-कात-शा-हे-वो× सा। √केत (केत) १०/ आमन्त्रणे (प)।

ग—शिष्याणां सङ्केतयति-जेड्. डी. डी. एम. जी. १४.५७२,१२। सङ्केतित०-प्रायश्चितत. २२,b८।

ङ—√संकेअ (सम्+√केतय्)=इङ्गिते। संक्र-संकेइय-सम्मत्त. २१८।
छ—√सकेतना=सङ्कोचे।
छ—[√संकेतना (<संकीर्ण-?)=संकटे]।

+√सङ्ग्राम (सङ्ग्राम) १०/३६६ श युद्धे (प) क्षी-च,-मै-सा-जै-काक्र-कात-शा-(आ),-हे-वो (उ)। √ग्राम (ग्राम) १०/३५० आमन्त्रणे (प) सा। सम्+√ग्राम=√सङ्ग्राम।

ङ—√संगाम (सक)=युद्धे। संगामेइ-भग.; तंदु. ११। वक्र-संगामेमाण-णाया. १,१६—पत्र. २२३; निर. १,१।

+√सट्ट (सट्ट) १०/९४ श-जै× हिंसायाम् (प) क्षी-मै-सा-च-शा। हिंसाबलदाननिकेतनेषु—काक्र-कात-हे। निकेतने हिंसे बले दाने—वो। √सठ् १०/ गतौ (प) वो।

ग—सट्टक०-सा. द. ४२९; ५४२।

+√सत्त्र (सत्त्र) १०/३५० श-च× संतानक्रियायाम् (आ) क्षी-मै-सा-काक्र-कात। संदानक्रियायाम्—जै-शा-हे। संबन्धे संततौ—वो। √सद् (षद्लृ) १/ विशरण-गत्यवसादनेषु (प)। √सद्+उणा. ४/१६६।

ग—सत्त्र०-ऋ.७,३३,१३। सत्त्रं निषेदुरृषयो नाधमानाः-अं.वे. १७,१,१४।

+√सद् (आङ् षदः)१०/२७९ शं-च×	पद्यर्थे (प) आधृषाद्वा क्षी-मै-सा-कात। गतौ—जै-सा-हे-वो। गत्यर्थे—काक्ष।	√सद् (षद्लृ) १/ विशरणगत्यवसादनेषु (प)।

ग—आसदम्-ऋ. ४,९,१; आसदे-५,२६,८; आसादयति-१,३१,१७। आसादयामास-वा. रा. २,३१,१४। न चाससाद—हरिवंश. ४९१९।

+√सभाज (सभाज)१०/३३४ श-च×	प्रीतिदर्शने (प) क्षी। प्रीतिदर्शनयोः— मै-सा-जै। प्रीतौ—काक्ष- कात-शा-हे। सेवने—काक्ष- कात-शा-हे। सेवनप्रीतिदर्शने —वो।	√भज् (भज) १/ सेवायाम् (उ)। √भाज् (भाज) १०/ पृथक्कर्मणि (प)। स+√भाज=√सभाज।

ग[1]—सभाजयति-वा. रा. ३,३५,१७। सभाजयन्ते-मभार. ५,१७,१८। सभाजयसे-मा. पु. ११०,१३। सभाजयामास-भा. पु. १०,४८,३।

ङ—√सभाज (सक)=पूजने-शौ.; अभि. १६०।

+√सम्ब् (षम्ब) १०/२१ क्षी-च×,श(कात—√सङ्घ्)	संबन्धे (प) मै-सा-जै-काक्ष- कात-शा-हे-वो। संबन्धने—सा।	√सम्ब् (षम्ब) १/ सर्पणे (प) वो। √साम्ब् (साम्ब) १०/२१ संबन्धे (प)। √शम्ब् (शम्ब) १०/ संबन्धे (प)।
√सह् (षह) १०/२६० च×,श	मर्षणे (प) आधृषाद्वा क्षी-मै-सा-च-जै- काक्ष-कात-शा-हे। शक्तौ—वो।	√सह् (षह) १/ मर्षणे (आ)।

[1] यौ. क्रि.; प्रयोज. ह्वि.।

ग—सहन्तम्, सहन्ती-ऋ. १,११,४। स एवायं नागः सहति कलभेभ्यः परिभवम्-सुभाषित. ६,३१।

+√सान्त्व् (सान्त्व) १०/३३ सामप्रयोगे (प) √साम (साम) १०/ सान्त्वने
मै-सा-च × क्षी-जै-काकृ-कात- (प) च।
शा-हे।
सामयोगे—वो।

√सान्त्व् (षान्त्व) १०/३४ सामप्रयोगे—
क्षी-श-च-जै-काकृ- मै-सा-हे।
कात-शा × सामयोगे—वो।

ग—परिसान्त्वय-वा. रा. १,६४,१८; २,३०,२८; २,८०,२१। परिसान्त्वयस्व-मभार. ३,२३४; कानि सान्त्वानि-५,१४०,२-सान्त्वम् =अत्यर्थं मधुरम्। विधिना तेन सान्त्वयन्-मनु. ८,७९=प्रियोक्तिं रचयन् (मन्वर्थ.); सान्त्वेन प्रशमय्यादौ-मनु. ८,७९=प्रीत्या (मन्वर्थ.)। सान्त्वमान०-मभार. ८,२४३।

+√साम् (साम) १०/३३ सान्त्वप्रयोगे (प) इति √साम् (साम) १०/
मै-सा-श-जै-काकृ- चन्द्रः—क्षी। सान्त्वने (प)।
कात-शा × क्षी-हे।
सान्त्वने—च।
सान्त्वे—वो।

ग—सामानं व्याचष्टे-तैब्रा. ३,२,५,४।

+√साम (साम) १०/३२६ सान्त्वने (प) √साम् (साम) सान्त्वप्रयोगे (प)।
श-च × क्षी-मै-जै-काकृ- चान्द्रमते १०/२९ इति क्षी।
कात-शा-हे-वो। √साम् (साम) १०/८९ सान्त्वने
सान्त्वप्रयोगे—वो। (प) च।
क्षी—सान्तने (यु. मी.
सं.) तदयुक्तम्।
सान्वनम् =प्रीणनम्—क्षी।

ग—पूर्ववदुदाहरणमवसेयम्।

+√साम्ब् (साम्ब) १०/२१ सम्बन्धे (प) √सम्ब् (षम्ब) १०/२१ सम्बन्धे
मै-श-च-जै-काकृ-कात- क्षी-सा-हे-वो। (प) मै।
शा × √शम्ब् (शम्ब) १०/२१ सम्बन्धे
(प) इति चन्द्रः—क्षी।
स+अम्ब=√साम्ब्—इति
वागीशः।

+√सार (सार) १०/३१५
शा-च-कात-शा-हे×
(बा.ग.प.-क्षी×)
(जै-√सर)
(काक्र-√स्वार)
सारयतीति व्याख्यातः
कन्नडटीकायाम्।
√सृ१/ शौ. क्रि.; प्रयोज. प्रवाहे—ह्वि.।
? ग—[सारः—रघु. ४,७९]

दौर्बल्ये(प)इति
दुर्गः—क्षी।
क्षी-मै-सा-काक्र
कात-वो।
शैथिल्ये—जै।

<√शार (शार) दौर्बल्ये (प)।
√शर (शर) दौर्बल्ये (प) इति
नन्दी—क्षी।
√सृ १/ गतौ (प)।
राज्ञा हिमवतः सारो राज्ञः सारो
हिमाद्रिणा–रघु.४,७९ = बलम्,
धनम्।

+√सुख(सुख)१०/३७४
च×,श

तत्क्रियायाम् (प)
क्षी-मै-सा-जै-काक्र-
कात-शा-हे।
तत्कृतौ—वो।

√सुघ् १०/१८६ग भाषार्थः(प)
काक्र।

ग—स्थिरं रथं सुखमिन्द्राधितिष्ठ–ऋ. ३,३५,४। न तथा सुखयत्यग्निः–मभार. ३,१८१। मत्संदेशैः सुखयितुमलम्–मेघ. उ. २५।

ङ—√सुह (सक)=सुखने। सुहइ–पिंग.; सुहेदि–शौ.।

+√सुट्ट (सुट्ट) १०/२५
श-च-शा×

अनादरे (प)
क्षी-मै-सा-जै-काक्र-
कात-हे।
अनादरे तौच्छ्ये
च—वो।

>√अट्ट अनादरे (प)
इति दुर्गः—क्षी।
√सट्ट (सट्ट) १०/ हिंसा-
याम् (प)।
√सुण्ट् १/९९ वक्रे (प)
काक्र।

√सुट्ट (षुट्ट) १०/२५
मै-सा-श-च-जै-काक्र-
कात-शा×

अनादरे (प) इति
चन्द्रदुर्गौ—क्षी।
क्षी-हे।
अनादरे तौच्छ्ये
च—वो।

तौच्छ्यम् =अल्पीभावः–दुर्गादासः।

+√सूच (सूच) १०/३२०
श×

पैशुन्ये (प)
क्षी-मै-सा-च-जै-
काक्र-कात-शा-हे-वो।

[सूचि० ऋ. २,३२,४।]
√सिव् (षिवु) ४/ तन्तु-
सन्ताने (प)।
यावद्धि सूच्याः (सीव्यतेऽ-
नया)–मभार. ५,२८,१८।

ग—सूचयसि–मैत्रायण्यु. ३,१; मैत्र्यु.३,१। सूचयन्ति परं तेजः–वा. रा. ४,९,१०५। सूचकोऽशुचिरेव च–मनु. ४,७१=खलः–यः परस्य दोषान् असतः सतो वा ख्यापयति (मन्वर्थ.)।

ङ—√सूअ (सक)=(१) सूचने, (२) ज्ञाने, (३) शरण्ये। सूएइ, सूअंति–विसे. १३६८; स. २४८; गउड.।

+√सूत्र (सूत्र) १०/३५२ शा-च×(जै-शा√सूत्र) विमोचने (प) क्षी-हे। वेष्टने—मै-सा। अवमोचने—जै-काकृ-कात-शा। ग्रन्थे—वो। √सिव् (षिवु) ४/ तन्तुसन्ताने (प)। √सिव् (षिवु)+उणा. ४/१६३=सूत्रम्।

ग—सूत्र०–अ.वे. ३,९,३; शब्रा. ३,२,४,१४। असूत्रयन्–शत्रुञ्जयमाहा. १४,९१, ५५। धर्मेषु सूत्रितम्–मभार. १२,९६७१। धात्रा किं न सूत्रितम्–कथासरि. १००,३०।

ङ—√सुत्त (सक)=निर्माणे। सुत्तइ–सुपा. २३५।

+√सूद् (षूद) १०/१८५ च×,श आस्रवणे (प) क्षी-शा-हे क्षरणे—मै-सा-जै-काकृ-कात-शाः-हे। 'घाते च' इति केचित्—क्षी। आश्रये—काकृ। ('आस्रवे' इति स्यात्)। आश्रवणे—जै-कात। 'आस्रवणे' इति भाव्यम्। केचित् 'आश्रवणे' इति पठन्ति—सा। निरासे आश्रुतिहत्योश्च—वो।

यौ. क्रि.; प्रयोज. व्यवस्थापने—ह्वि.।

ग—असूदयत् सुकृतं गर्भमद्रिः—ऋ. ३,३१,७। सूदयन्ति–वा. रा. ४,९,२०; सूदयसे–६,९५,३८। सर्वा ''ब्रह्मणा सूदयामि–ऋ. १,१६२,१७=व्यवस्थापने।

+√सृ १०/१०९ मै-सा-श-च-जै-काकृ-कात-शा× आवरणे (प) इति पूर्वे पेठुः—क्षी <√घृ स्रावणे (प)।

स्रावणे—क्षी।
स्तृतौ—वो।

+√स्कन्ध (स्कन्ध) १०/३८५ मै-सा-श-च-जै-काकृ-कात-शा× | समाहारे (प) क्षी-हे। समाहृतौ—वो | √स्कन्द् (स्कन्दिर्) १/ गतिशोषणयोः (प)। √स्कन्द्+उणा. ४/२०६= स्कन्धः। स्कन्धो वृक्षस्य समास्कन्नो भवति-निरु. ६,१७,११।

ग—[चस्कन्धे-हरिवंश. १९५८ ('चस्कन्दे' इति भाव्यम्। स्खलतिः)]; स्कन्धांसीव-ऋ. १,३२,९। स्कन्ध०-अ. वे. ६,१३५,१। खर्जूरीस्कन्धनद्धानाम्-रघु. ४,५७-स्कन्धेषु=प्रकाण्डेषु-(संजी.)।

+√स्तन (स्तन) १०/३०६ श× | देवशब्दे (प) क्षी-मै-सा-च-जै-काकृ-कात-शा। गर्जे—हे। अभ्रशब्दे—वो। | द्रष्ट. √स्तन् (स्तन) १/ शब्दे (प)।

१/, यौ. क्रि.; प्रयो.—ह्वि.।

क—द्रष्ट. √स्तन् (स्तन) १/ शब्दे (प)।

ग—स्तनयन्त्-ऋ. १,५८,२; यत्पर्जन्यः स्तनयन् हन्ति-५,८३,२;। स्तनयति-शब्रा. २,२,३,८; छान्दोग्यो. २,३,१। स्तनयन्ति-आर्षेयो. ७ : ३।

+√स्तिप् (स्तिप) १०/१४१ मै-सा-श-च-जै-काकृ-कात-शा-हे× (वो-√स्तेप्) | क्षेपे (प) क्षी-वो। | √स्तिप् (ष्टिप) १/ क्षरणार्थः (आ) √तिप् (तिपृ) १/ क्षरणार्थः (आ)। √तेप् (तेपृ) १/ क्षरणार्थः (आ)। √स्तेप् (ष्टेपृ) १/ क्षरणार्थः (आ)। √टिप् (टिप) १०/ क्षेपे (प)। स्तिपाः-निघ. ४/३। स्तिपा स्तियापालन उपस्थितान् पालयतीति वा-निरु. ६,१७,८।

ग—स्तिपा तनूपा जरितॄणाम्-ऋ. ७,६६,३; स नः स्तिपा उत भवा-१०,६९,४ (=अग्निः)।

+√स्तूप् (स्तूप) १०/१४२ मै-सा(च)जै-काक्र-कात-शा-हे-वो×च ४/७०	समुच्छ्राये (प)क्षी।	>√स्तूप् (ष्टूप) समुच्छ्राये (प) इति चन्द्रः—क्षी।
स्तूप् (ष्टूप) १०/१४२ श-च×(काक्र-√सूप् [षूप]) लैपिकी त्रुटिः। 'ष्टूप' इति भाव्यम्।	समुच्छ्राये (प) इति चन्द्रः—क्षी। क्षी-मै-सा-काक्र-कात-कात-शा-हे। समुच्चये—जै। उच्छ्राये—वो।	√स्तृप् ४/६७ समुच्छ्राये (प) काक्र। स्तूपः स्त्यायतेः, सङ्घातः-निरु. १०, ३३,१।

ग—उप स्पृश दिव्यं सानु स्तूपैः-ऋ. ७,२,१।

+√स्तेन (स्तेन) १०/३४१ श	चौर्ये (प) क्षी-मै-सा-च-जै-काक्र-कात-शा-हे-वो।	स्तेनः कस्मात्? संस्त्यानमस्मिन् पापकमिति नैरुक्ताः-३,१९,१८।

ग—स्तेनो यो दिप्सति नः-ऋ. २,२८,१०; स्तेन इव वव्रमक्रमुः-१०,९७,१०।
ङ—तेण (<स्तेनः)=चौरः-ओघ. ११; कस.।

+√स्तोम (स्तोम) १०/३६७ श-च×	श्लाघायाम् (प) क्षी-मै-सा-जै-काक्र-कात-शा-हे। श्लाघने—वो।	√स्तु (ष्टुञ्) १/ स्तुतौ (उ)+उणा. १/१३९।

ग—स्तोमो अश्विनावजीगः-ऋ. ३,५८,१; अग्नेः स्तोमं मनामहे-५,१३,२। स्तोम०—उत्तरराम. १ अङ्के=समूह०।

छ—√तूमना=(१) पिच्चादिसंहतगुच्छानां विश्लेषे (अपलुञ्चय); (२) मर्दने, दलने, (३) रहस्योद्घाटने।

+√स्थूल (स्थूल) १०/३४८ श	परिबृंहणे (आ) क्षी-सा-काक्र-शा। परिबृंहणे—मै-च-जै-कात-हे।	√स्था (ष्ठा) १/ गतिनिवृत्तौ (प)+उणा. ५/४ इत्युरन्। रलयोश्चैक्यम्। एतां स्थूणां पितरो धारयन्तु

	बृंहणे—वो ।	—ऋ. १०,१८,१३ । स्थूरं ददृशे पुरस्तात्—ऋ. ८,१,३४ । स्थूरः समाश्रितमात्रो महान् भवत्यणुरनुस्थवीयांसमुपसर्गः ....निरु. ६,२२,४ = (स्थूलः) ।

ग—बहुस्पृशापि स्थूलेन—शिशु. २,७८ ।
ङ—थुल्ल (<स्थूलम्) = पीवरम्-प्रामा. ।
ङ—थूल (<स्थूलम्) = पीवरम्-पउम. १४,११३; उत्रा. ।
छ—स्थूर = मनुष्यः, (२) इट्चरः ।
छ—स्थूरी (स्थूरिन्) = भारवाही पशुः ।

छ—थूलना (<स्थूलनम्) = पैवर्ये-बुं. ख. । (रज्जुनिर्माणाय पलाशादिमूलस्य परिबृंहणेऽस्य प्रायेण प्रयोगः) ।

+√स्निट् (स्निट) १०/३६ मै-सा-श-च-जै-काकृ-कात×	स्नेहने (प) क्षी-शा-हे । स्नेहे—वो ।	>√स्मिट् (स्मिट) अनादरे (प) इत्येके—क्षी । ><√स्निह् (ष्णिह) १०/३७ स्नेहने (प) मै ।
+√स्निह् (ष्णिह) १०/३७ क्षी-च-शा× (काकृ-√स्नेह्) यौ. क्रि.; प्रयो.	स्नेहने (प) मै-सा-जै-काकृ-कात-हे-वो । —ह्वि. ।	<>√स्निट् (स्निट) १०/३६ स्नेहने (प) । स्नेहयति—निघं. २/१९ = वधकर्मा । न स्नेहयति—निरु. ७,१४,५ = विरूक्षीकरोतीत्यर्थः (दुर्गाचार्यः) ।

ग—स्नेहयद्य-ऋ. ९,९७,५४ । क्षीरसिद्धो बहुस्नेहः स्नेहयति नरम्—चरक. १,१३

+√स्पश् (स्पश) १०/१४९ च-काकृ-कात-वो× (श-√स्पृश्)	ग्रहणसंश्लेषणयोः (आ) क्षी-मै-सा । ग्रहणश्लेषणयोः—जै-शा-हे ।	√स्पर्श् (स्पर्श) १०/ ग्रहणे श्लेषे (प) वो । √पश् (पश) १०/ बन्धने (प) ।

ग—स्पाशयाश्चक्रे—शब्रा. ७,५,१,२५ ।

छ—√ फाँसना = ग्रहणे । 'पाशः' इत्यस्मादपि व्युत्पत्तिः । पशिस्पशयोर्विकास-सम्बन्धः ।

√ स्पुण्ड् (स्पुडि) १०/४ (क्षी)-मै-सा-श-च-जै-काकृ-कात-शा-हे-चो×	परिहासे (प) क्षी (यु. मी. सं. एव) तदयुक्तम् ।	√ स्फुण्ट् (स्फुटि) परिहासे (प) इति दुर्गः—क्षी । √ स्फुण्ड् (स्फुडि) परिघाते (प) इत्येके—क्षी ।
+√ स्पृह् (स्पृह) १०/३१८ श	ईप्सायाम् (प) क्षी-मै-सा-च-जै-काकृ-कात-शा-हे । ईप्से—वो ।	√ स्पृ ५/ प्रीतिबलनयोः (प) √ स्पृश् (स्पृश) ६/ संस्पर्शे (प) ।

यौ. क्रि.; प्रयोज. ह्वि. ।

क—स्पेर्घु-(स्पेर्घु)-नासिक्यम्-स्प्रेंघ् = कूर्दने, उच्छलने ।

ख—अवे. आ-स्पूर् जत-वा. पॉकर्नीः ।

ग—न स्वप्नाय स्पृहयन्ति-ऋ. ८,२,१८; तस्मा अस्पृहयं पुनः-१०,१३५,२ । स्पृहयन्ति-शब्रा. २,२,३,५; काब्रा. १,२,३,४ ।

ङ—√ पिह (सक)=वाञ्छायाम् । पिहाइ-भग. ३ ।

ङ—√ पीह (सक)=वाञ्छायाम् । पीहंति, पीहेज्जा-औप.; ठा. ३,३-पत्र. १४४ ।

ङ—√ सिह (सक)=वाञ्छायाम् । कृ-सिहणिज्ज-देवे. ८,३१ टी. ।

+√ स्फिट् (स्फिट) १०/३७ मै-श-जै-काकृ-कात-शा×	अनादरे (प) क्षी-च-हे । 'स्नेहने' इति कचित् कोशे—सा । वृत्त्यां हिंसेऽनादरे च—वो ।	√ स्फिट् (स्फिट) १०/ हिंसायाम् (प) मै । √ स्मि (स्मिङ्) १०/ अनादरे (प) 'इत्येके' इति मैत्रेयः —सा । √ स्निह् (ष्णिह) १०/ स्नेहने (प) । √ स्मिट् (स्मिट) १०/ अनादरे (प) । √ स्मिट् (स्मिट) १०/ गतौ

(प) इति शाकटायनः—सा।

ग—[संस्फेटः=तुमुलयुद्धम्-क्षी]

ङ—√फेड (सक.)=(१) विनाशे, (२) अपनयने, (३) परित्यागें, (४) उद्घाटने। फेडइ, फेडेइ-उव.।

छ—√(सर) सेटना-(<फ-लोपे<स्फेटनम्)=तिरस्कारे, अनादरें।

+√स्फिट् (स्फिट) १०/९३ क्षी-सा-श-च-जै-काक्ष×	हिंसायाम् (प) मै-कात-शा-हे। वृत्त्यां हिंसेऽनादरे च—वो।	√स्फिट् (स्फिट) १०/३७ अनादरे (प)।
√स्फिट्ट् (स्फिट्ट) १०/१००	हिंसायाम् (प) सा।	

मैत्रेयादीनामनुरोधादेवेह स्फिट्टिश्च पठितः-सा।

ङ—स्फिट् (स्फिट) १०/३७ वत्।

छ—स्फिट् (स्फिट्) १०/३७ वत्।

+√स्फुट् (स्फुट) १०/१९० श-च×	भेदे (प) क्षी-काक्ष-कात-हे। भेदने—मै-सा। भिदि—वो।	√स्फुट् (स्फुट) १०/५ परिहासे (प) जै। √स्फुट् (स्फुट) १०/९ परिहासे (प) काक्ष।
आ+√स्फुट् (स्फुट)	हन्त्यर्थः—क्षी-जै-शा-हे।	√स्फुट् (स्फुट) १०/४५ परिहासे (प) हे। √स्फुट् १०/७५a हिंसायाम् (प) काक्ष।

ग—स्फोटयति तलघोषेण पर्वतान्-मभार. ५,५७७८। स्फोटयति कराग्रेण पञ्जरम्-हरिवंश. १०२६८। स्फोटनम्-सुश्रु. ६,४२; प्रस्फोटयति-हरिवंश. १३८९४। आस्फोटयिष्यंश्चग्राह पदे-कथासरि. २५,१५०।

ङ—√फोड (सक)=भेदे, विदारणे। फोडेज्ज-कुप्र. ६७।

ङ—√फोडाव (सक)=भेदे, विदारणे, उद्घाटने-स. ४६०।

+√स्फुट (स्फुट) १०/३८५ श-च-जै-काक्ष-कात-शा×	प्रकटभावे (प) क्षी-हे। मै-सा× विशरणे—वो।	√स्फुट् (स्फुट) ६/ विकसने (प)। शेषः पूर्ववत्।

यौ. क्रि.; प्रयोज.···ह्वि.।

विशरणम् = विकसनम्—दुर्गादासः।

ग—नास्फोटयेत् -मनु. ४,६४=पाणिना बाहौ ध्वनिरूपमास्फोटनं न कुर्यात् (मन्वर्थ.)।

ङ—√फोडाव (सक)=भेदे, विदारणे, उद्घाटने-स. ४६०।

+√स्फुण्ट् (स्फुटि) १०/४ मै-सा-श-च-जै-काक्व-कात×	परिहासे (प) इति दुर्गः—क्षी क्षी-शा-हे। नर्म्मणि—वो।	<√स्फुण्ड् (स्फुडि) परिहासे(प)। √स्फुट् (स्फुट) १०/५ परिहासे (प) जै। √स्फुट् (स्फुट) १०/९ परिहासे (प) काक्व। √स्फुट् (स्फुट) १०/४५परिहासे (प) हे। √स्फुट (स्फुट) १०/३८५ प्रकटभावे (प)।
+√स्फुण्ड् (स्फुडि) १०/४	परिघाते (प) इत्येके—क्षी। नर्म्मणि—वो।	<√स्फुण्ड् (स्फुडि) परिहासे (प) क्षी। शेषः पूर्ववत्।
+√स्मि (स्मिङ्) १०/३९ क्षी-श-च-जै-काक्व-कात-शा-हे×	अनादरे (आ) इत्येके—मै। मै-सा-वो।	<√स्मिट् (स्मिट)१०/३८अनादरे (प) मै। √स्मिट् (स्मिट)१०/३६ अनादरे (प) क्षी।

ग—स्मयावेशविवर्जिताय-रघु. ५,१९=गर्वाभिनिवेशशून्याय (संजी.)।

+√स्मिट् (स्मिट) १०/३६ श-च-जै-काक्व×	अनादरे (प) क्षी-मै-सा-कात-शा-हे। अनादरे स्नेहे च—वो।	>√स्मि (स्मिङ्) अनादरे (आ) इत्येके—मै। स्मित—इति वागीशः। √स्मिट्, १०/२७ a अनादरे (प) काक्व।

+√स्यम् (स्यम) १०/१६२ च×,श (काक्ृ- √श्यम्) वितर्के (आ). क्षी-मै-सा-काकृ-कात- शा-हे-वो। वितर्कणे—जै। √स्यम् (स्यमु) १/ शब्दे (प) मिन्। √स्यम १०/ ध्याने (प) वो। 'स्मय' इत्यस्य वर्णविपर्ययः- इति वागीशः।

√स्य (श्य) ल् (स्य[श्य] ल) १०/१५४ वितर्के (आ) इति न्यासकृत्–मै। ६/२/१३३ इति स्वरसूत्रे स्या(श्या)लसंप्रतिपत्त्यर्थं पठितवान्–"स्या(श्या)लपुत्र इति। स्य(श्य)ल वितर्के इत्यस्माच्चुरादिणिजन्तात् पचाद्यच्। तेन स्या(श्या)-लशब्दोऽन्तोदात्तः"–इति न्यासकारः।

+√स्वद् (ष्वद) १०/२५६ च×,श संवरणे (प) क्षी-जै-शा-हे। आस्वादने—मै-सा-काकृ-कात। स्वादे छदे—वो। स्वादे—ह्वि। √स्वद् (ष्वद) १/ आस्वादने (आ)। सु+√अद्=√स्वद्— इति वागीशः।

यौ. क्रि.; प्रयोज.

ग—मूलफलं समास्वाद्य–वा. रा. ५,७,३१ [अग्निरस्वदयत्–ऋ.२,४,७]।

+√स्वर (स्वर) १०/३१० श-च× आक्षेपे (प) क्षी-मै-सा-जै-काकृ-कात-शा-हे-वो। √स्वृ १/ शब्दोपतापयोः (प)। सु+√ऋ १/ गतिप्रापणयोः(प)।

स्वरयति–लाट्या. श्रौ. १,६,३।

+√स्वर्त् (स्वर्त) १०/८५ मै-सा-श-च-जै-काकृ-कात-शा-वो× गत्याम्, च=कृच्छ्र-जीवने (प) क्षी। कृच्छ्रजीवने—हे। >√श्वभ्र् (श्वभ्र) गतौ, च= कृच्छ्रजीवने (प) इति नन्दी—क्षी। सु+अर्त—वागीशः।

√स्वर्त् (ष्वर्त) मै-सा-श-च-जै-काकृ-शा-वो× गत्याम्, च=कृच्छ्र-जीवने–इति नन्दी—क्षी। क्षी। गतौ—कात-हे।

+√हिंस् (हिसि) १०/२७८ श-च-काक्ट×	हिंसायाम् (प) क्षी-मै-सा-जै-कात- शा-हे। हिंसने—जै। हिंसे—वो। यौ. क्रि.; प्रयो. ह्रि.।	√हिंस् (हिसि) ९/ हिंसायाम् (प)।

ग— न चात्मानं विहिंसयेत्-मभार. १२,११०१६।

+√हिष्क् (हिष्क) १०/१५४ च-जै-कात-शा×	हिंसायाम् (आ) इति दुर्गः—क्षी क्षी-मै-सा-काक्ट-हे। हिंसे—वो।	<√किष्क् (किष्क) हिंसायाम् (प)। √हिक्क १०/११९b हिंसायाम् (प) काक्ट।
+√ह्लप् (ह्लप) १०/११८a क्षी-सा-श-च-जै-काक्ट- कात-शा-हे-वो×	व्यक्तायां वाचि (प) मै।	√रप् (रप) १/ व्यक्तायां वाचि (प)। √लप् (लप) १/ व्यक्तायां वाचि (प)। √ह्लप् (ह्लप) १०/११८ व्यक्तायां वाचि (प)।
+√ह्लप् (ह्लप) १०/११८ श-च×	व्यक्तायां वाचि (प) क्षी-मै-सा-जै-काक्ट- कात-शा-हे। भाषणे—वो।	√ह्लप् (ह्लप) १०/११८a व्यक्तायां वाचि (प) मै। शेषः पूर्ववत्। √क्लप् (क्लप) १०/१२३ व्यक्तायां वाचि (प) इत्येके—सा।

श्रीयमुनाप्रसादस्य प्रणिपत्य पदाम्बुजम्।
शुकदेवं गुरुं नत्वाऽनन्तरं मुरलीधरम्॥
धातुपाठसमीक्षेयं श्रावणे शनिवासरे।
अमायां वैक्रमे व्योमहस्ताकाशकरेऽब्दके॥
जेजाकभुक्तिवासेन स्थित्वा काश्यां विवित्सया।
वागीशेत्यभिधेयेन पूर्यते प्रीयतां शिवः॥

ह्विट्नीमहोदयेन न्यक्कृता ग्रन्थेऽस्मिंश्च प्रयोगैः साधिता धातवः

अङ्क् (अकि) १।८४
अङ्घ् (अघि) १।१०५
अट्ट् (अट्ट) १।२५२
अड् (अड) १।३५३
अड्ड् (अड्ड) १।३४५
अण् (अण) १।४३७
अण्ठ् (अठि) १।२५८
अन्त् (अति) १।५९
अन्द् (अदि) १।६०
? अभ्र् (अभ्र) १।५५५
अम्ब् (अबि) १।३७५ }
अम्ब् (अम्ब) १।४११ }
अम्भ् (अभि) १।३८२
अर्घ् (अर्घ) १।७३१
अर्ब् (अर्ब) १।४११
अर्व् (अर्व) १।५८०
अल् (अल) १।५१६
अष् (अष) १।८९०
अस् (अस) १।८७२
इङ्ख् (इखि) १।१४०
इन्द् (इदि) १।६१
? ई १।३१७
? ईष् (ईष) १।६७५
उख् (उख) १।१२८
? उङ्ख् (उखि) १।१२९
उछ् (उछी) १।२१३
उञ्छ् (उछि) १।२१२
उर्द् (उर्द) १।२०
उर्व् (उर्वी) १।५६७
उह् उहिर्) १।७३०

? ऊय् (ऊयी) १।४८०
ऋह् (ऋह) ६।२७
एज् (एज) १।१७६
एव् (एवृ) १।४९७
ओख् (ओखृ) १।१२१
ओण् (ओणृ) १।४४६
कंस् (कसि) २।१४
कक्ख् (कक्ख) १।११९
कख् (कखे) १।७७८
कङ्क् (ककि) १।९१
? कज् (कज) १।२२७
कञ्च् (कचि) १।१६७
कट् (कटी) १।३१७
कठ् (कठ) १।३३१
कड् (कड) १।३५५
कड् (कड) १।१००
कड्ड् (कड्ड) ६।३५५
कण् (कण) १।४४१
कण् (कण) १।७८८
कण्ट् (कटि) १।३१७
कण्ठ् (कठि) १।२६१
कण्ड् (कडिं) १।२०८ }
कण्ड् (कडि) १।३५५ }
कन्द् (कदि) १।६७ }
कन्द् (कदि) १।७६५ }
कब्र् (कब्रृ) १।३७७
? कर्ज् (कर्ज) १।२२३
कर्द् (कर्द) १।५७
कर्ब् (कर्ब) १।४१३
कर्व् (कर्व) १।५८१

कश् (कंश) १।७१९
कश् (कश) २।१४
कस् (कस) २।१४
काञ्च् (काचि) १।१६८
काश् (काशृ) ४।५१
किल् (किल) ६।७४
कील् (कील) १।५२४
कु (कुङ्) १।९३७
कु २।३१
कुक् (कुक) १।८८
कुच् (कुच) १।८४४
कुट् (कुट) ६।८६
कुड् (कुड) ६।१०१
कुण् (कुण) ६।५५
कुण्ट् (कुटि) १।३११
कुण्ड् (कुडि) १।२६७
कुण्ड् (कुडि) १।३११
कुथ् (कुथ) ९।४२
कुन्थ् (कुथि) १।४१
कुन्थ् (कुथि) ९।४२
कुम्ब् (कुबि) १।४२६
कुर् (कुर) ६।६१
कुल् (कुल) १।८२६
कुश् (कुश) ४।१०५
कुस् (कुस) ४।१०५
कूल् (कूल) १।५२५
कृड् (कृड) ६।१०२
कृण्व् (कृवि) १।५९४
कॄ ९।१३
कॄ ९।२५
केप् (केपृ) १।३६४
केल् (केल) १।५३७
केव् (केवृ) १।५०१
क्नू (क्नूञ्) ९।८

क्मर् (क्मर) १।५५६
क्रथ् (क्रथ) १।७९३
क्रुञ्च् (क्रुन्च) १।१८२
क्लद् (क्लद) १।७६७
क्लीब् (क्लीबृ) १।३७८
क्लु (क्लुङ्) १।९६६
क्षल् (क्षल) १।८३६
क्षिण् (क्षिणु) ८।३
क्षिप् (क्षिप) ४।१३
क्षिव् (क्षिवु) ४।(१।३७९)
क्षीव् (क्षीवृ) १।३७९
क्षीव् (क्षीव) १।५६६
क्षुर् (क्षुर) ६।६२
क्ष्विड् (ञिक्ष्विडा) १।७३५
खक्ख् (खक्ख) १।१२०
खच् (खच) १।१६६
खज् (खज) १।२२८
खट् (खट) १।३०५
खण्ड् (खडि) १।२८१
खर्ख् (खर्ख) १।१२०
खर्द् (खर्द) १।५८
खर्ब् (खर्ब) १।४१४
खर्व् (खर्व) १।५७९
खल् (खल) १।५४४
खष् (खष) १।६८५
खिट् (खिट) १।२९८
खिद् (खिद) ४।५८
खुज् (खुजु) १।१९७
खुण्ड् (खुडि) १।२८२
खुर् (खुर) ६।६३
खुर्द् (खुर्द) १।२२
खै १।८९७
खोड् (खोडृ) १।५५१

खोर् (खोॠ) १।५५०
खोल् खोलृ १।५५१
गग्घ् (गग्घ) १।१५८
गज् (गज) १।२४३
गज् (गजॎ) १।२४९
गञ्ज् (गंजि) १।२२४
गड् (गड) १।७७०
गण्ड् (गडिं) १।३५६
गर्ब् (गर्ब) १।४१५
गर्व् (गर्व) १।५७८
गाध् (गाधृ) १।४
गु ६।१२५
गुड् (गुड) ५।९०
गुद् (गुद) १।२३
गुध् (गुध) ४।१२
गुप् (गुप) १।९५५
गुप् (गुप) ४।१२१
गुफ् (गुफ) ६।३८
गू ६।११८
गृ १।९२१
गृज् (गृज) १।२४५
गृञ्ज् (गृजि) १।२४६
गेप् (गेपृ) १।३६५
? गोष्ट् (गोष्ट) १।२५५
ग्रन्थ् (ग्रथि) १।३५
ग्लुच् (ग्लुचु) १।१९५
घग्घ् (घग्घ) १।१५८
घु (घुङ्) १।९३६
घुट् (घुट) १।७३७
घुट् (घुट) ६।१०३
घुण् (घुण) १।४३०
घुण् (घुण) ६।५८
घुर् (घुर) ६।६५
घृण् (घृणु) ८।६

ङु (ङुङ्) १।९३८
चक् (चक) १।९०
चण् (चणं) १।७९०
चण्ड् (चडि) १।२७६
चप् (चंप) १।३९७
चय् (चय) १।४७४
चर्च् (चर्च) १।७०९
चर्च् (चर्च) ६।२१
चर्छ् (चर्छ) ६।२१
? चर्ब् (चर्ब) १।४२०
चल् (चल) ६।७७
चष् (चष) १।८७५
चषघ् (चषघ) ५।२२
चह् (चह) १।७२२
चिट् (चिट) १।३११
? चिरि ५।३०
चिल् (चिल) ६।७६
चिल्ल् (चिल्ल) १।५३३
चीव् (चीवृ) १।८६४
चुट् (चुट) १।३२१
चुट्ट् (चुट) ६।९७
चुड्ड् (चुड्ड) १।३४४
चुण्ट् (चुटि) १।३२१
चुण्ड् (चुडि) १।३२१
? चुत् (चुतिर्) १।४०
चुल्ल् (चुल्ल) १।५३१
चूर् (चूरी) ४।४७
छर्द् (छदिर्) १।८०३
छम् (छमु) १।४६५
छुट् (छुट) ६।९८
छुप् (छुप) ६।१३८
जञ्ज् (जजि) १।२३९
जट् (जट) १।३०१

जल् (जल) १।८१७
जष् (जष) १।६७८
जिम् (जिमु) १।४६८
जु १।९२८
जुङ्ग् (जुगि) १।१५६
जुड् (जुड) ६।९९
जुत् (जुतृ) १।३१
जुन् (जुन) ६।४७
जूष् (जूष) १।६७२
ज्यु (ज्युङ्) १।९४१
झर्झ् (झर्झ) १।७१०
झर्झ् (झर्झ) ६।२०
झष् (झष) १।६७९
? झॄ (झॄष्) ४।२३
? टीक् (टीकृ) १।९५
ट्वल् (ट्वल) १।८१९
डिप् (डिप) ४।११८
डिप् (डिप) ६।९१
तंस् (तसि) १।६७३
तङ्क् (तकि) १।१४८
तङ्ग् (तगि) १।१४८
तण्ड् (तडि) १।२७८
? तय् (तय) १।४७५
? तय् (तय) १।४७७
तर्द् (तर्द) १।५६
तस् (तसु) ४।९९
तिक् (तिक) ५।२०
तिग् (तिग) ५।२१
तिप् (तिपृ) १।३५७
तिम् (तिम) ४।१५
तिल् (तिल) १।५३४
तिल् (तिल) ६।७५
तिल्ल् (तिल्ल) १।५३४
तीम् (तीम) ४।१६
तीव् (तीव) १।५६५
तुज् (तुज) १।२४०
तुञ्ज् (तुजि) १।२४२
तुट् (तुट) ६।९६
तुड् (तुड) १।३४७
तुड् (तुड) ६।१०४
तुण्ड् (तुडि) १।२७३
तुण् (तुण) ६।५२
तुप् (तुप) १।४०२
तुप् (तुप) ६।३२
तुस् (तुस) १।७०३
तुह् (तुहिर्) १।७२९
तूर् (तूरी) ४।४२
तूल् (तूल) १।५२७
तूष् (तूष) १।६६७
तृंह् (तृन्हू) ६।६९
तृक्ष् (तृक्ष) १।६५१
तृण् (तृणु) ८।५
तृप् (तृप) ६।३०
तृह् (तृह) ६।६८
तेप् (तेपृ) १।३६१
तेव् (तेवृ) १।४९५
त्रङ्क् (त्रकि) १।९३
त्रङ्ग् (त्रगि) १।१४९
? त्रन्द् (त्रदि) १।६६
? त्रुप् (त्रुप) १।४०४
? त्रौक् (त्रौकृ) १।९६
त्वक्ष् (त्वक्ष) १।६४७
त्वञ्च् (त्वन्चु) १।१८९
त्विष् (त्विषा) १।९८५
थुर्व् (थुर्वी) १।५७०
दक्ष् (दक्ष) १।६०३
दङ्घ् (दघि) १।१५७

सट् (षट) १।३०९
? सय् (षय) १।४७६
सस्ज् (षस्ज) १।१९९
सिट् (षिट) १।३००
सिध् (षिधू) १।४६
सिल् (षिल) ६।८४
सीक् (सीकृ) १।७५
सुम्भ् (षुन्भ) १।४२६
सुर् (षुर) ६।६०
सुह् (षुह) ४।२१
सूर्क्ष्य् (सूर्क्ष्य) (षूर्क्ष्य) १।५१०, ६५७
सूष् (षूष्) १।६७०
सृज् (सृज) ४।६५
? सेक् (सेकृ) १।७८
सेल् (सेल) १।५४२
स्कम्भ् (स्कभि) १।३८४
स्कुन्द् (स्कुदि) १।९
स्कुम्भ् (स्कुन्भु) ५।८
९।
स्खद् (स्खद) १।७६१
स्तुर्च् (ष्टुर्च) १।१७२
स्तै (ष्टै) १।९२६
स्थल् (स्थल) १।८२०
स्थुड् (स्थुड) ६।१०५
स्नस् (ष्णसु) ४।४
स्नुह् (ष्णुह) ४।८६
? स्फुड् (स्फुड) ६।११६
? स्वङ्क् (स्वकि) १।८२
स्वेक् (स्वेकृ) १।८०
स्वै १।९०३
हट् (हट) १।३०८
हठ् (हठ) १।३३४
हम्म् (हम्म) १।४६१
हल् (हल) १।८२१
हिल् (हिल) ६।८२
हुड् (हुडृ) १।३४९ }
हुड् (हुड) ६।१०२ }
हुंड् (हुड) ६।१०८ }
हुण्ड् (हुडि) १।२६६ }
हुण्ड् (हुडि) १।२७४ }
हूड् (हूडृ) १।३४८
हेठ् (हेठ) १।२६३
हेड् (हेड) १।७७१
होड् (होडृ) १।२८२ }
होड् (होडृ) १।३५५ }
ह्वेष् (ह्वेषृ) १।६१४

इति ४८९ धातवो विज्ञेयाः ।

अथ चुरादिधातवः

(येषु प्रश्नचिह्नानि ते ह्विट्नीमहाशयेन प्रयोजकत्वेनोरीकृताः शेषाश्च निरस्ताः)
ग्रन्थेऽस्मिंस्तु प्रयोगैस्ते साधिता धातवः समे

अंश (अंश) १०।३६२
अंस (अंस) १०।३६२
अघ (अघ) १०।३८५
अङ्क (अकि) १०।३७२
अङ्क (अङ्क) १०।३७३
अञ्च् (अन्चु) १०।२११
अट्ट् (अट्ट) १०।२५
अन्ध (अन्ध) १०।३७०
अम् (अम) १०।१८८
? अर्च् (अर्च) १०।२५९
? अर्ज् (अर्ज) १०।१९३
अर्थ (अर्थ) १०।३४९
अर्द् (अर्द) १०।२७७
? अर्ह् (अर्ह) १०।१९९
आन्दोल (आन्दोल) १०।६४,३८४
आप् (आप्लृ) १०।२८६
[इल् (इल) १०।१२०]
? ईड् (ईड) १०।१३०
? ईर् (ईर) १०।२६१
उलण्ड् (उलडि) १०।९
ऊन (ऊन) १०।३३५
ऊर्ज् (ऊर्ज) १०।१६
ओलण्ड् (ओलडि) १०।९
कण् (कण) १०।१८३
कण्ड् (कडि) १०।४५
कथ (कथ) १०।२९७
कर्ण (कर्ण) १०।३६९
? कल् (कल) १०।६८
? कल् (कल) १०।३१२
काल (काल) १०।३२५
किष्क् (किष्क) १०।१५४
कीट् (कीट) १०।१००
कुट् (कुट) १०।१६४
कुट् (कुट) १०।१७०
कुटुम्ब् (कुटुम्ब) १०।१४७
? कुट्ट् (कुट्ट) १०।२३
कुट्ट् (कुट्ट) १०।१६८
कुण्ड् (कुडि) १०।४६
कुत्स् (कुत्स) १०।१६६
कुद् (कुद) १०।६
कुमार (कुमार) १०।३२४
कुम्प् (कुपि) १०।११५
कुम्ब् (कुबि) १०।११५
कुम्भ् (कुभि) १०।१२०
कुशूल (कुशूल) १०।३२२
कुस्म् (कुस्म) १०।१७९
कुह (कुह) १०।३४५
कूट् (कूट) १०।१७०
कूट (कूट) १०।३३७
कूण् (कूण) १०।१५७
? कृप (कृप) १०।३१६
कृत् (कृत) १०।११३
केत (केत) १०।३३८
क्रथ् (क्रथ) १०।११३
? क्रथ् (क्रथ) १०।२७५
क्लप् (क्लप) १०।१२३
क्षम्प् (क्षपि) १०।८३
? क्षल् (क्षल) १०।६१

? पून् (पूजं) १०।१०२
पूर् (पूरी) १०।२५४
? पृ १०।१५
[पृच् (पृच) १०।२५०]
पृथ् (पृथ) १०।२०
? पॄ १०।१५
? प्रथ् (प्रथ) १०।१९
? प्री (प्रीञ्) १०।२९३
प्रेङ्खोल (प्रेङ्खोल) १०।६४;३८५
बट (बट) १०।३१५
? बध् (बध) १०।१४
? बन्ध् (बन्ध) १०।१४
बर्ह् (बर्ह) १०।२४४
बल् (बल) १०।८९
बल्ह् (बल्ह) १०।२४५
बष्क् (बष्क) १०।३६९
बस्त् (बस्त) १०।१५२
बुल् (बुल) १०।६६
[बुस्त् (बुस्त) १०।५५]
[बृंह् (बृहि) १०।२५३]
ब्लेष्क (ब्लेष्क) १०।३५७
? भज् (भज) १०।२०१
भण्ड् (भडि) १०।५२
? भर्त्स् (भर्त्स) १०।१५०
? भल् (भल) १०।१६९
? भाज (भाज) १०।३३३
भाम (भाम) १०।३१९
भिल् (भिल) १०।७१
भू १०।२०७
भू १०।२९०
भूष् (भूष) १०।१९७
? भ्रूण् (भ्रूण) १०।१५९
? मण्ड् (मडि) १०।५१
? मद् (मद) १०।१७३
? मन् (मन) १०।१७७
मन्त्र् (मत्रि) १०।१४८
? मर्च् (मर्च) १०।१०८
? मह (मह) १०।३१४
मान् (मान) १०।२८९
मार्ग् (मार्ग) १०।८०
? मार्ग् (मार्ग) १०।२९३
[मार्ज् (मार्ज) १०।१०९]
मिञ्ज् (मिजि) १०।२१८
मिद् (मिद) १०।८
? मिन्द् (मिदि) १०।८
मिश्र (मिश्र) १०।३६५
मी १०।२७४
? मुच् (मुच) १०।२१५
मुट् (मुट) १०।७९
मुस्त् (मुस्त) १०।९७
मूत्र (मूत्र) १०।३५३
मूल् (मूल) १०।६७
मृग (मृग) १०।३४४
मृण्ड् (मृडि) १०।१२४
? मृष् (मृष) १०।२९६
मोक्ष् (मोक्ष) १०।१९८
म्रक्ष् (म्रक्ष) १०।१२१
? यत् (यत) १०।२०३
यन्त्र् (यत्रि) १०।३
यम् (यम) १०।८७
? यु १०।१७८
? युज् (युज) १०।२५७
रंह (रहि) १०।३०५
रक् (रक) १०।२०९
रग् (रग) १०।२०९
? रच (रच) १०।३११

रस (रस) १०।३७६ नाधा.-ह्वि.
? रह् (रह) १०।९३
? रिच् (रिच) १०।२६६
रुज् (रुज) १०।२५५
? रुष् (रुष) १०।१३१
रूक्ष (रूक्ष) १०।३५४
रूप (रूप) १०।३७९
रूष (रूष) १०।३८५
लक् (लक) १०।२१०
लक्ष् (लक्ष) १०।५
लक्ष् (लक्ष) १०।१६५
लड् (लड) १०।७
लण्ड् (ओलडि) १०।९
लन्द् (लदि) १०।९
? लल् (लल) १०।१५६
[लश् (लश) १०।१९६]
लष् (लष) १०।१९६
? लस् (लस) १०।१८७
लिङ्ग् (लिगि) १०।२१२
लूष् (लूष) १०।१७५
? लोक् (लोकृ) १०।२४७
? लोच् (लोचृ) १०।२४८
? वच् (वच) १०।२९१
? वज् (वज) १०।८०
? वञ्च् (वन्चु) १०।१७१
? वण्ट् (वटि) १०।४९
? वद् (वद) १०।२८८
? वन् (वन) १०।२८७
? वर (वर) १०।२९८
वर्ण् (वर्ण) १०।१७
वर्ण (वर्ण) १०।३८४
? वर्ध् (वर्ध) १०।११४
वर्ह् (वर्ह) १०।२३२
? वल्क् (वल्क) १०।३५
वस् (वस) १०।२०४
[वस (वस) १०।३८५]
? वा १०।३२९
वात (वात) १०।३२९
वास (वास) १०।३३१
[विच्छ् (विछ) १०।२४२]
वित्त (वित्त) १०।३७८
? विद् (विद) १०।१७६
? विप् (विप) १०।१३८
वीज (वीज) १०।६४
वीर (वीर) १०।३४७
? वृ (वृञ्) १०।२६४
? वृज् (वृजी) १०।२६३
? वृत् (वृतु) १०।२५२
? वृष् (वृष) १०।१७२
वेल (वेल) १०।३२७
? व्युन्द् (व्युदि) १०।९४
? व्रज् (व्रज) १०।८०
व्रण (व्रण) १०।३८३
शब्द् (शब्द) १०।१८२
शम् (शम) १०।१६४
शम्ब् (शम्ब) १०।२१
शर (शर) १०।३१५
शार (शार) १०।३१५
शिष् (शिष) १०।२६७
[शीक् (शीक) १०।२७६]
शील (शील) १०।३२५
[शुण्ठ् (शुठि) १०।१०५]
? शुन्ध् (शुन्ध) १०।२८०
शुल्क् (शुल्क) १०।८१
शुल्ब् (शुल्ब) १०।७६
शूर (शूर) १०।३४६
शूर्प् (शूर्प) १०।७६
[? श्रथ् (श्रथ) १०।२०२]

? श्रण् (श्रण) १०।४२
? श्रथ् (श्रथं) १०।२७३
? श्रथ् (श्रथ) १०।३१७
[श्रन्थ् (श्रन्थ) १०।२८४]
? श्लिप् (श्लिप) १०।३८
श्वभ्र् (श्वभ्र) १०।८५
सङ्केत (सङ्केत) १०।३४९
सङ्ग्राम (सङ्ग्राम) १०।३६६
सट्ट् (सट्ट) १०।९४
सत्र (सत्र) १०।३५०
सद् (आङः षद) १०।२७९
सभाज (सभाज) १०।३३४
सान्त्व् (सान्त्व) १०।३३
साम् (साम) १०।३३ }
साम (साम) १०।३२६ }
[सार (सार) १०।३१५]
सुख (सुख) १०।३७४
सूच (सूच) १०।३२०
सूत्र (सूत्र) १०।३५२
? सूद् (षूद) १०।१८५
स्कन्ध (स्कन्ध) १०।३८५
? स्तन (स्तन) १०।३०६
स्तिप् (स्तिप) १०।१४१
स्तूप् (स्तूप) १०।१४२
स्तेन (स्तेन) १०।३४१
स्तोम (स्तोम) १०।३६७
स्थूल (स्थूल) १०।३४८
? स्निह् (ष्णिह) १०।३७
स्पश् (स्पश) १०।१४९
स्पृह (स्पृह) १०।३१८
स्फिट् (स्फिट) १०।३७
स्फुट् (स्फुट) १०।९०
स्फुट (स्फुट) १०।३८५
स्मि (स्मिङ्) १०।३९
स्वद् (ष्वद) १०।२५६
स्वर (स्वर) १०।३१०
हिंस् (हिसि) १०।२७८

इति २२९ धातवः ।

अनुपलब्धप्रयोगा धातवः

प्रश्नचिह्नाङ्किताः संदिग्धा धातवः

अक् (अक) १।७८६
अठ् (अठ) १।३३२
अण् (अण) ४।६७
? अन्त् (अति) १।५९
? अभ्र् (अभ्र) १।५५५
? अह् (अह) ५।२६
इख् (इख) १।१४०
ईख् (ईख) १।१३९
ईर्क्ष्य् (ईर्क्ष्य) १।५११
? ईष् (ईष) १।६७५
उठ् (उठ) १।३३५
उभ्रस् (उभ्रस) ९।५४
ऊय् (ऊयी) १।४८०
ऋक्ष् (ऋक्षि) ५।२९
ऋफ् (ऋफ) ६।२८
ऋम्फ् (ऋम्फ) ६।२९
ॠ ९।२६
? एठ् (एठ) १।२६४
कग् (कगे) १।७८५
? कर्ज् (कर्ज) १।२२३
कल्ल् (कल्ल) १।४९४
? कव् (कव) १।७१९
? कस् (कस) १।७२२
[कांस् (कासि) १।६३७]
कास् (कास) १।६३८
किट् (किट) १।३१६
कुच् (कुच) १।१८१
कुज् (कुजु) १।१९६

कृ (कृञ्) ९।१३ }
कॄ (कॄञ्) ९।१३ }
कॄ ९।२५
क्नस् (क्नस) ४।५

क्लिन्द् (क्लिदि) १।१५ }
क्लिन्द् (क्लिदि) १।७० }
क्लेव् (क्लेवृ) १।५०१
क्लेश् (क्लेश) १।६०२

क्षज् (क्षज) १।७६२ }
क्षञ्ज् (क्षजि) १।७६२ }
क्षिरि ५।२९
क्षिव् (क्षिवु) १।५६६
क्षी (क्षीष्) ९।३६
क्षीज् (क्षीज) १।२३३
क्ष्मील् (क्ष्मील) १।५१९
क्ष्विद् (ञिक्ष्विदा) १।७३५
क्ष्विद् (ञिक्ष्विदा) ४।१३३
खच् (खच) ९।५९
खम्ब् (खम्ब) १।४१४
खव् (खव) ९।५९
? खिद् (खिद) ७।१२
खु (खुङ्) १।९३८
खु ९।६२
खुड् (खुड) ६।१०९
खेव् (खेवृ) १।५०२
खै १।८९७
गम्ब् (गम्ब) १।४१५
गा (गाङ्) १।९३५
गुज् (गुज) १।२००

डी (डीङ्) १।९५३
तक्ष् (तक्ष) १।६६७
तञ्च् (तन्चु) १।१८८
तञ्ज् (तन्जू) ७।२२
तय् (तय) १।४७५
तिक् (तिकृ) १।१०२
तीव् (तीवृ) १।८८३
तुफ् (तुफ) ६।३४
तुभ् (तुभ) १।७४४
तुभ् (तुभ) ४।१२८
तुभ् (तुभ) ९।४९
तुम्प् (तुन्प) ६।३३
तुम्फ् (तुन्फ) १।४०७
तुम्फ् (तुन्फ) ६।३५
तूड् (तूडृ) १।३४७
तृम्फ् (तृन्फ) ६।३१
तेप् (तेपृ) १।३६१
त्रख् (त्रख) १।१३९
त्रङ्ख् (त्रखि) १।१३९
त्रुफ् (त्रुफ) १।४०४
त्रुम्प् (त्रुन्प) १।४०५
त्रुम्फ् (त्रुन्फ) १।४०५
त्वक्ष् (त्वक्ष) १।६५६
त्सञ्च् (त्सञ्चु) १।५५३
थुड् (थुड) ६।१०६
दाय् (दाय) १।८६७
दान् (दान) १।९७९
दाश् (दाशृ) ५।३२
दिन्व् (दिवि) १।५८८
दिप् (दिपृ) १।६५८
दुड् (दुड) ६।१०७
दृ ५।३३
दृम्फ् (दृन्फ) ६।३७
द्यु २।२९
द्यै १।८९०
द्राख् (द्राखृ) १।१२४
धण् (धण) १।४५३
धन् (धन) १।४५३
धूर् (धूरी) ४।४६
धृज् (धृज) १।२१६
धृञ्ज् (धृजि) १।२१७
धृ ९।२३
धेप् (धेपृ) १।३७७
ध्रञ्ज् (ध्रजि) १।२१५
ध्रण् (ध्रण) १।४५८
ध्रस् (ध्रस) ९।५२
ध्राख् (ध्राखृ) १।१२५
ध्राघ् (ध्राघृ) १।११२
ध्राङ्क्ष् (ध्राक्षि) १।६६२
ध्राङ्क्ष् (ध्राक्षि) १।६६५
ध्रेक् (ध्रेकृ) १।७६
ध्रै १।८९२
ध्वण् (ध्वण) १।४४५
नट् (णट) १।७८५
नभ् (णभ) ४।१२७
नभ् (णभ) ९।४८
नम्ब् (नन्ब) १।४२२
१ निन्व् (निवि) १।५८५
निव् (णिवृ) १।८५६
नीव् (नीव) १।५६४
न्वी ९।२५
पच् (पच) १।११७१
पद् (पद) १।४९
पर्प् (पर्प) १।४१३
पव् (पव) १।५०८

पष् (पष) १।८७३
पस् (पस) १।८७२
पिश् (पिशृ) १।७११
पुड् (पुड) १।३२०
पुंड् (पुड) ६।१०४
? पुण्ड् (पडि) १।३२०
पुण्ड् (पुंडि) १।३२७
? पुन्थ् (पुथि) १।४२
पुस् (पुस) ४।१०२
पृज् (पृजी) २।२०
पृञ्ज् (पृजि) २।१९
पृञ्ज् (पृजि) २।२०
पृड् (पृड) ६।४९
पेव् (पेवृ) १।३७२
पेव् (पेवृ) १।५०४
? पेश् (पेशृ) १।७१२
? पै १।९०५
प्युष् (प्युष) ४।१०२
प्युस् (प्युस) ४।६
प्युस् (प्युस) ४।१०२
प्रस् (प्रस) १।७५९
? प्रुष् (प्रुष) १।६९४
प्रेष् (प्रेषृ) १।६१४
प्रैण् (प्रैणृ) १।४५४
प्लेव् (प्लेवृ) १।५०५
बन्द् (बन्द) १।५१
बम्ब् (बन्ब) १।४१२
बस् (बसु) ४।१०६
बिट् (बिट) १।३१५
बिड् (बिड) १।३०६
बुन्ध् (उबुन्धिर्) १।८६१
बेद् (उबेदिर्) १।८६१
बेह् (बेहृ) १।६३४
ब्युस् (ब्युस) ४।१०७

ब्रग् (ब्रग) १।४४७
ब्रुड् (ब्रुड) ६।११२
भर्व् (भर्व) १।४२१
भुङ्ग् (भुगि) १।१५७
भुण्ड् (भुडि) १।[२७४]
भृड् (भृड) ६।११९
भृष् (भृषु) १।७४०
भृ ९।२०
भॄ ९।२१
भेष् (भेषृ) १।८६९
भ्रंस् (भ्रन्सु) १।७४३
भ्रक्ष् (भ्रक्ष) १।८९७
भ्रण् (भ्रण) १।४४४
भ्रुड् (भ्रुड) ६।११०
भ्रेज् (भ्रेजृ) १।१७७
भ्लक्ष् (भ्लक्ष) १।८७८
भ्लाश् (टुभ्लाशृ) १।८०८
मङ्घ् (मघि) १।१०७
मङ्घ् (मघि) १।१०८
? मङ्घ् (मघि) १।१५८
मभ्र् (मभ्र) १।५५७
मर्व् (मर्व) १।४१९
मर्व् (मर्व) १।५७५
मव् (मव) १।५९५
मव्य् (मव्य) १।५०९
? मा (माङ्) ४।३३
मान्थ् (माथि) १।४४
मिद् (मिदृ) १।८५३
मिन्व् (मिवि) १।५८४
? मुङ्ख् (मुखि) १।१३९
मुच् (मुच) १।१६८
मुञ्च् (मुचि) १।१६९
मुड् (मुड) ६।१०२
मुण्ट् (मुटि) १।३२२

मृज् (मृज) १।२४७
मृड् (मृड) ९।४४
मृष् (मृषु) १।६९८ }
मृष् (मृषु) १।६९९ }
मृ ९।२९
? मेट् (मेटृ) १।२८९
मेद् (मेद) १।८५४
मेप् (मेपृ) १।३६७
म्रुञ्च् (म्रुन्चु) १।११०
म्रेट् (म्रेटृ) १।२८९
म्लेट् (म्लेटृ) १।२९०
म्लेव् (म्लेवृ) १।५०७
यु (युञ्) ९।७
युत् (युतृ) १।३०
यौट् (यौटृ) १।२८८
रख् (रख) १।१३६
रग् (रगे) १।७७९
राख् (राखृ) १।१२२
राघ् (राघृ) १।१०९
रुङ्ग् (रुगि) १।१५४
रुट् (रुट) १।७३८
रुण्ट् (रुटि) १।३२४
रुण्ठ् (रुठि) १।३४० }
रुण्ठ् (रुठि) १।४४२ }
? रेक् (रेकृ) १।७७
रोड् (रोडृ) १।३५७
लङ्घ् (लघि) १।१५६
लम्ब् (लबि) १।३७४
लर्ब् (लर्ब) १।४१४
लाख् (लाखृ) १।१२३
लाघ् (लाघृ) १।११०
लाञ्ज् (लाजि) १।२३७
ली ९।३१

लुट् (लुट) १।३१० }
लुट् (लुट) १।७३८ }
लुट् (लुट) ४।१०९ }
लुठ् (लुठ) १।३३५
लुठ् (लुठ) १।७४०
? लुण्ठ् (लुठि) १।३४५ }
? लुण्ठ् (लुठि) १।३४३ }
लुन्थ् (लुथि) १।४३
? लुप् (लुप) ४।१२४
लेप् (लेपृ) १।३६९
लोड् (लोडृ) १।३५८
लौड् (लौडृ) १।३५२
ल्वी ९।३२
वट् (वट) १।७७२
वठ् (वठ) १।३२९
वभ्र् (वभ्र) १।५५८
वर्फ् (वर्फ) १।४०८
वर्ह् (वर्ह) १।६३३
वल्भ् (वल्भ) १।३८८
? वप् (वप) १।६८१
वस्क् (वस्क) १।९८
वाङ्क्ष् (वाक्षि) १।६५९
वावृत् (वावृतु) ४।४९
विच्छ् (विछ) ६।१४२
विज् (विज) १।२१४
विज् (विजिर्) ३।१२
विज् (ओविजी) ७।२३
विद् (विद) ७।१३
विध् (विधृ) ६।३३
? विल् (विल) ६।७८
विस् (विस) १।७०६
वुन्द् (उवुन्दिर्) १।८८०
वृज् (वृज) १।२१४
वृत् (वृतु) ४।४९
वृश् (वृश) ४।११३

अथ चुरादिधातवः

यत्र प्रश्नचिह्नानि तेषु धातुषु मन्यते प्रयोजकतां ह्विट्नीः।

अंहे् (अहि) १०।२३७
अङ्क (अङ्क) १०।३७३
अञ्ज् (अजि) १०।२२८
अर्क् (अर्क) १०।१०३
? अर्ह् (अर्ह) १०।१९९
अवधीर (अवधीर) १०।३८६
अश्व (अश्वतर) १०।३८८
? आप् (आप्लृ) १०।२८६
आह्वर (आह्वरक) १०।३९०
[इल् (इल) १०।१२०]
? ईर् (ईर) १०।२६१
उध्रस् (उध्रस) १०।२१४
ऊष (ऊष) १०।३८५
[ओलण्ड् (ओलडि) १०।९]
[कण्ठ् (कठि) १०।२९४]
कत्र (कत्र) १०।३५८
कत् (कर्त्) १०।३६८
कर्तृ (कर्तृ) १०।३५८
कर्त्र (कर्त्र) १०।३५८
! कल् (कल) १०।६८
? कल (कल) १०।३१२
कालोड (कालोडित) १०।३८९
किल् (किल) १०।६९
कुंश् (कुशि) १०।२३०
कुंस् (कुसि) १०।२२९
कुण (कुण) १०।३३९
कुण्ठ् (कुठि) १०।५०
कुंद् (कुद्द) १०।६
[कुन्द्र (कुद्रि) १०।६]
[कुप् (कुप) १०।२५०]
[कूट (कूट) १०।३३७]
कॄ १०।१७५
क्लृप् (क्लृप) १०।२००
? क्रथ् (क्रथ) १०।१३
क्षञ्ज् (क्षजि) १०।८४
[खेट (खेट) १०।३२१]
[खेड (खेड) १०।३२१]
खोट (खोट) १०।३१८
खोद (खोद) १०।३२२
गर्ज् (गर्ज) १०।१०७ }
गर्ज् (गर्ज) १०।१२५ }
गर्द (गर्द) १०।१२५
गर्ध् (गर्ध) १०।१२६
गर्व् (गर्व) १०।३५१
गर्ह् (गर्ह) १०।२९२
? गल् (गल) १०।१५८
गुप् (गुपू) १०।२४०
गूर् (गूरी) १०।१६३
[गॄ १०।१७३]
गृह (गृह) १०।३४३
? ग्रन्थ् (ग्रन्थ) १०।२६७
ग्रस् (ग्रस) १०।२१६
घट् (घट) १०।२२९
? घट्ट् (घट्ट) १०।९१
? घर् (घर) १०।१०९
? घुष् (घुषिर्) १०।१९४
? घॄ १०।११०
चण्ड् (चडि) १०।५०

? दल् (दल) १०।२१९
दस् (दस) १०।१४१
[दस (दस) १०।३४३]
दिवु् (दिवु) १०।१७४
दृप (दृप) १०।२७०
दृभ् (दृभ) १०।२६४
दृभ् (दृभी) १०।२७१
? धू (धूञ्) १०।२८२
धूश् (धूश) १०।९९
धूष् (धूष) १०।९९
धूस् (धूस) १०।९९
धृ १० [१।९४५]
धृष् (धृष) १०।१७२
ध्रस् (उध्रस) १०।२१४
? ध्वन (ध्वन) १०।३३६
? नट् (नट) १०।१२
नट् (नट) १०।२५३
नड् (नड) १०।१२
नड् (नड) १०।२६२
? नद् (णद) १०।२४९
निवास (निवास) १०।३३२
? पट् (पट) १०।२२०
पण्ड् (पडि) १०।८०
पण्ड् (पडि) १०।१३२
? पत (पत) १०।३०८
? पद (पद) १०।३४२
पश (पश) १०।३०९
पष (पष) १०।३०९
पिंस् (पिसि) १०।२५३
पिज् (पिज) १०।३३
[पिस् (पिस) १०।३२]
पुट् (पुट) १०।२२१
? पुट् (पुट) १०।३५६
पुण (पुण) १०।१०२
पुण्ट् (पुटि) १०।२५७
? पुष् (पुष) १०।२१८
पुस्त् (पुस्त) १०।९७
? पूज् (पूज) १०।१०२
? पूर् (पूरी) १०।२५४
? पूर्ण् (पूर्ण) १०।९५
पूल् (पूल) १०।९५
? पृ १०।१५
? पृच् (पृच) १०।२५०
? प्रथ् (प्रथ) १०।१९
? प्री (प्रीञ्) १०।२८३
बंह् (बहि) १०।२३८
? बध् (बध) १०।१४
? बन्ध् (बन्ध) १०।१४
बर्ह् (बर्ह) १०।१२४
[बल् (बल) १०।८९]
? बुल् (बुल) १०।६६
[बुस्त् (बुस्त) १०।५५]
ब्रीस् (ब्रीस) १०।१२३
ब्रूस् (ब्रूस) १०।१२३
भञ्ज् (भजि) १०।२५३
भिन्द् (भदि) १०।७९
? भर्त्स् (भर्त्स) १०।१५०
? भल् (भल) १०।१६९
? भाज (भाज) १०।३३३
? भूष् (भूष) १०।१९७
भृंश् (भृशि) १०।१५९
[मंह् (महि) १०।२३९]
? मण्ड् (मडि) १०।५१
? मद् (मद) १०।१७३
? मन् (मन) १०।१७७
मर्च् (मर्च) १०।१०८
? मह (मह) १०।३१४
? मार्ग् (मार्ग) १०।२९३

[माज् (मार्ज) १०।१०९]
[मी १०।२७४]
? मुच् (मुच) १०।२१५
मुद् (मुद) १०।२१३
मुल् (मुल) १०।६७
? मृज् (मृजूष्) १०।२९५
मृण्ड् (मृडि) १०।१२४
? मृष् (मृष) १०।२९६
मृष (मृष) १०।२९६
म्लक्ष् (म्लक्ष) १०।१२६
म्लेच्छ् (म्लेछ) १०।१२२
? यत् (यत) १०।२०३
? यु १०।१७८
? युज् (युज) १०।१५७
युज् (युज) १०।१७८
रंह् (रहि) १०।२६१
? रंह (रहि) १०।३०५
रघ् (रघ) १०।२०१
रङ्घ् (रघि) १०।२३५
? रच (रच) १०।३११
रस (रस) १०।३७६ नाधा.–ह्रि.)
? रह् (रह) १०।९३
? रिच् (रिच) १०।२६६
रुंश् (रुशि) १०।२५३
रुंस् (रुसि) १०।२५४
रुट् (रुट) १०।१३३
रुट् (रुट) १०।२२२
रुठ् (रुठ) १०।१३३
रुठ् (रुठ) १०।२४८
? रुष् (रुष) १०।१३१
? लक्ष् (लक्ष) १०।५
? लक्ष् (लक्ष) १०।१६५
लग् (लग) १०।२१०
[लङ्घ् (लघि) १०।२३६]

लज् (लज) १०।१०
लज (लज) १०।३६१
लञ्ज् (लजि) १०।३२
लञ्ज् (लजि) १०।२२६
लञ्ज (लञ्ज) १०।३६४
[लड् (लड) १०।७]
लण्ड् (लडि) १०।२५३
[लभ (लभ) १०।३८२]
? लल् (लल) १०।१५६
[लश् (लश) १०।१९६]
[लष् (लष) १०।१९६]
? लस् (लस) १०।१८७
लाभ (लाभ) १०।३८२
[लिङ्ग् (लिगि) १०।२१२]
ली १०।२६२
लुञ्ज् (लुजि) १०।३१
लुञ्ज् (लुजि) १०।२२७
लुट् (लुट) १०।२२३
लुण्ट् (लुण्ट) १०।२६
लुण्ठ् (लुण्ठ) १०।२६
लुम्ब् (लुबि) १०।११६
? लोक् (लोकृ) १०।२४७
? लोच् (लोचृ) १०।२४८
? वच् (वच) १०।२९१
? वज् (वज) १०।८०
? वञ्च् (वञ्चु) १०।१७१
वट (वट) १०।३०३
वट (वट) १०।३६०
वण्ट् (वटि) १०।४९
? वण्ट (वटि) १०।३६३
वण्ड् (वडि) १०।४९
? वद् (वद) १०।२८८
? वन् (वन) १०।२८७
? वर् (वर) १०।२९८
? वर्ध (वर्ध) १०।११४

[वल्क् (वल्क) १०।३५]
वल्यूल (वल्यूल) १०।३२८
वल्ह् (वल्ह) १०।२३३
[वस (वस) १०।३८५]
? वा १०।३२९
? विच्छ् (विच्छ) १०।२४२
? विद् (विदं) १०।१७६
? विप् (विप) १०।१३८
विल् (विल) १०।७१
विष्क् (विष्क) १०।१५१
विष्क (विष्क) १०।३८३
[वुक्क् (वुक्क) १०।१७२]
? वृ (वृञ्) १०।२६४
वृंह् (वृहि) १०।२३१
? वृज् (वृजी) १०।२६३
[वृत् (वृतु) १०।२५२]
वृध् (वृधु) १०।२५३
? वृष् (वृषु) १०।१७२
व्यप् (व्यप) १०।९४
व्यय् (व्यय) १०।९४
व्यय (व्यय) १०।३७७
[व्यय (व्यय) १०।३७७]
[व्युन्द् (व्युदि) १०।९४]
? व्रज् (व्रज) १०।८०
शट् (शट) १०।१६०
शठ् (शठ) १०।२७
शठ् (शठ) १०।१०४
शठ् (शठ) १०।१६०
शठ (शठ) १०।३००
? शम् (शम) १०।१६४
शल् (शल) १०।१६०
[शार (शार) १०।३१५]
शीक् (शीक) १०।२५५
[शीक् (शीक) १०।२७६]
शुक्ल् (शुक्ल) १०।८४
शुठ् (शुठ) १०।१०४
शुण्ठ् (शुठि) १०।१०५
? शुन्ध् (शुन्ध) १०।२८०
? शृध् (शृध) १०।२०२
? श्रग् (श्रग) १०।४२
श्रथ् (श्रथ) १०।१३
? श्रथ् (श्रथ) १०।२७३
? श्रथ (श्रथ) १०।३१७
श्रन्थ् (श्रन्थ) १०।२७३
[श्रन्थ् (श्रन्थ) १०।२८४]
? श्लिष् (श्लिष) १०।३८
श्वठ् (श्वठ) १०।२८
श्वठ (श्वठ) १०।३०१
श्वण्ठ् (श्वठि) १०।२८
श्वर्त् (श्वर्त) १०।८५
श्वल्क् (श्वल्क) १०।३४
श्वेत (श्वेत) १०।३८७
सम्ब् (षम्ब) १०।२१
साम्ब् (साम्ब) १०।२१
सार (सार) १०।३१५
सुट्ट् (सुट्ट) १०।२५
? सूद् (षूद) १०।१८५
सू १०।१०९
? स्तन (स्तन) १०।३०६
[स्तिप् (स्तिप) १०।१४१]
स्निट् (स्निट) १०।३६
स्पुण्ड् (स्पुडि) १०।४
स्फिट्ट् (स्फिट्ट) १०।१००
स्फुण्ट् (स्फुटि) १०।४
स्फुण्ड् (स्फुडि) १०।३९
स्मिट् (स्मिट) १०।३६
स्यम् (स्यम) १०।१६२
? स्वद् (ष्वद) १०।२५६
स्वर्त् (स्वर्त) १०।८५
हिष्क् (हिष्क) १०।१५४
हृप् (हृप) १०।११८a
हृप् (हृप) १०।११८

इति १६९ धातवः ।

साक्षादुपयोजितानां ग्रन्थानां सूची

१. अभिधान अनुशीलन—डॉ० विद्याभूषणविभुः ।
२. अभिधानचिन्तामणिः--हेमचन्द्रः ।
३. अमरकोशः (क्षीरस्वामिभानुजिदीक्षितटीकाभ्यां सहितः)
४. आख्यातचन्द्रिका—भट्टमल्लरचिता ।
5. Indogermanisches Etymologisches worterbuch—(Julius Pokorny)
६. कविकल्पद्रुमः (वोपदेवरचितः) । पूना १९५४ ई० ।
७. कश्मीरीयभाषाकोशः–सरजार्जग्रियसन म० म० मुकुन्दरामशास्त्रिभ्यां संपादितः
८. कामसूत्रम् (जयमङ्गलटीकासहितम्)
९. काशिका
१०. क्रियारत्नसमुच्चयः
११. क्षीरतरङ्गिणी—डा० ब्रूनोलीबिशसम्पादिता, १९३० ई० ।
क्षीरतरङ्गिणी—युधिष्ठिरमीमांसकसम्पादिता, २०१४ संवत् ।
१२. गुर्जरभाषाकोशः — नवभवनप्रकाशनमन्दिरम्, अहमदाबाद, १९४९ ई० ।
१३. चान्द्रव्याकरणम्—ससूत्रोणादिधातुपाठम् —डा० ब्रूनोलीबिशसम्पादितम्, १९०२ ई० ।
१४. जर्नल् अमेरिकन ओरियण्टल सोसायटी
१५. जर्नल् डब्ल्यू० जेड० के० एम० (=Wiener Zeitschrift für die Kunde des Morgenlandes.)
१६. (न्यू) जर्मन-इँग्लिश्कोशः—(केसल्सं) लन्दन, १९६१ ई० ।
१७. धातुपरिशिष्टम्—विलियम् ड्वाइट् ह्विट्नीः ।
१८. धातुप्रदीपः—मैत्रेयरक्षितरचितः ।
१९. धातुमञ्जरी (श्रीकाशीनाथकृता) चार्लीस् विल्किन्स् संपादिता, लन्दन, १८१५ ई० ।
२०. धातुवृत्तिः—मैसूर, १९०० ई० ।
धातुवृत्तिः—चौखम्बासीरीज, वाराणसी, १९३४ ई० ।
२१. (निघण्टुः)—निरुक्तम् (दुर्गाचार्यदेवराजयज्वटीकासहितम्)
२२. नैषधमहाकाव्यम् (प्रकाशटीकासहितम्)
२३. पञ्चतन्त्रम्—खेमराजश्रीकृष्णदास–१९२३ ई० ।
२४. पञ्जाबी-इँग्लिश्कोशः ।
२५. पद्मपुराणम् (मनसुखरायमोरप्रकाशनम् ।)
२६. पाइअसद्दमहण्णवो—कलिकाता, १९२८ ई० ।
२७. पाली-इँग्लिश्कोशः (पी० टी० एस्०) ।
२८. पालीधातुपाठधातवः—एस्० एम्० कत्रेः (पूना) ।
29. Vergleichendes worterbuch Indogermanischen sprachen herausgegeben und bearbeitet (Alois walde).

३०. पुरुषकारः (श्रीलीलाशुकरचिता दैवटीका)
३१. प्रसङ्गपारिजातम्—श्रीचेतनदासरचितम् (देशवाड़ीप्राकृतभाषामयम्)।
३२. प्रायोगिकसंस्कृत-इँग्लिश्कोशः वामनशिवराम-(आप्टे)-कृतः।
३३. बृहच्छब्देन्दुशेखरः—वाराणसेयसंस्कृतविश्वविद्यालयः, १९६० ई०।
३४. भट्टिकाव्यम् (जयमङ्गलटीकासहितम्)।
३५. मनुस्मृतिः (मन्वर्थटीकासहिता)।
३६. महाभारतम् (नीलकण्ठीयटीकासहितम्) पूना, १९३३ ई०।
३७. महाभाष्यम्—म० म० गिरिधरशर्मचतुर्वेदसम्पादितम्।
महाभाष्यम्—निर्णयसागरमुद्रितम्।
महाभाष्यम्—गुरुप्रसादसंपादितम्।
३८. मॉनियरविलियंमस्य संस्कृतकोशः।
३९. मार्कण्डेयपुराणम् (मनसुखरायमोरप्रकाशनम्)
४०. मुण्डारी-इँग्लिश्कोशः—बी० एल० मणीन्द्रभूषणभादुरिसम्पादितः।
४१. यशस्तिलकचम्पूः—सचन्द्रिकाव्याख्या। (निर्णयसागरमुद्रिता) मुम्बापुरी, १९१६ ई०
४२. रघुवंशमहाकाव्यम् (सञ्जीवनीसहितम्)
४३. Radices linguæ Sanskrit (N. L. westerGaard)
४४. लिङ्गपुराणम् (म० रा० मो० संस्करणम्)
४५. वाक्यपदीयम् (प्रकीर्णटीकासहितम्)।
४६. वाचस्पत्यम् (कोशः)।
४७. वाल्मीकीयं रामायणम् (तिलकटीकासहितम्)—निर्णयसा० मुम्बापुरी,
वाल्मीकीयं रामायणम् (गीता० संस्करणम्)
४८. वैदिकपदानुक्रमकोषः (विश्वबन्धुशसम्पादितः)।
४९. वैयाकरणसिद्धान्तकौमुदी (तत्त्वबोधिसहिता) नि० सा०, १९२९ ई०
५०. शब्दकल्पद्रुमः (राधाकान्तदेवविरचितः)
५१. शिशुपालवधम् (सर्वङ्कषासमेतम्)।
५२. श्रीमद्देवीभागवतपुराणम् (म० रा० मो० संस्करणम्)।
५३. संस्कृतधातुपाठानां धातुसूची—चा० ग० पल्सुलेः।
५४. संस्कृतभाषा—टी० ब्रोः।
५५. संस्कृतवर्तंखुख (ऑत्तो—बाथलिङ्कसम्पादित०)
५६. संस्कृतव्याकरणम्—ह्विट्नीः।
५७. सरस्वतीकण्ठाभरणम् (व्याकरणं भोजरचितम्)।
५८. सुश्रुतम् (डल्हणाचार्यस्य निबन्धसंग्रहाख्यव्याख्यासहितम्)—निर्णयसा० मुम्बापुरी, १९३८ ई०।
५९ स्कन्दपुराणम् (म०रा०मो० संस्करणम्)
६०. हालास्यचम्पूः—ज्ञानसुन्दर्या कविरत्नाभिधानया रचिता। कुम्भघोणम्, १९०६ ई०।
६१. हितोपदेशः—श्रीकृष्णदासगङ्गाविष्णु०, कल्याण—मुम्बापुरी, १९७९ संवत्।
६२. हिन्दीशब्दसागरकोशः (श्यामसुन्दरदाससम्पादितः)।

राज सरस्वतीभवनपुस्तकालयस्थहस्तलेखधातुपाठानां सूची

—धातुपाठः ...	२७९५३	च—धातुपाठः ...	३८०९०
—धातुपाठः ...	३८०१६	छ—धातुपाठः ...	३८१७४
—धातुपाठः ...	३८०४०	ज—धातुपाठः ...	३८२६०
ङ—धातुपाठः ...	३८०४३	झ—धातुपाठः ...	३८२९६

शुद्धिपत्रम्

अशुद्धम्	शुद्धम्	पृष्ठे	पङ्क्तौ
अङ्ग्रि	अङ्घ्रि०	१	२२
जे	जै	६	२३
प्रोपसर्गस्थविच्छित्तौ	प्रोपसर्गस्य विच्छित्तौ	१०	२३
(पा)	(प)	११	२३
बन्ध्नांय	बन्धनाय	१३	८
आँमो	अमो–, आमो	१४	९
आम	आम्		
<	>	१४	३२
याञ्चायाम्	याच्ञायाम्	१८	११
०युद्द०	०युद्ध०	२०	४
भतृ.	भर्तृ.	२७	९
आपच्यो०	आपच्छ्लो०	२८	१३
का-त	कात	३०	२१
<	>	३२	४
वर्णा–श्र०	वर्णाश्र०	३२	१२
ब्+√ ऋध्	व्–√ ऋध्	४९	१६
सद्द=नी.	सद्दनी.	५३	१५
<	>	६२	११
ङित्त्वात् ;	ङित्त्वात्]	८०	११
०वातिक	०वार्तिक०	२१२	१६
०मञ्जयार्यादि	०मञ्जर्यादि		
०नांस्तीति	०र्नास्तीति		
नाघिगतम्	नाधिगतम्	२१८	१५
छ—धूप * †	[illegible]—धूपना * †	२७२	२६
श-च-जै-श =	श-[illegible]-जै-श[illegible]	२८८	१९
शा-हे-वो	शा-हे-वो ×	३०२	१६
√ व्युसं	√ व्युस्	३१२	१९
बृंहन्ति	बृंहन्ति	३२८	१५
त्यतो	इत्यतो	४२८	अन्तिमा पङ्क्तिः
लम्बना र्थः	लम्बेनार्थः		

मा
—धा
—
—
ह
१.
२